Shri Raghunatha Temple MSS. Library,
४६६२ JAMMU

No. ८६४ क

Title शालिहोत्र

Author श्री गण:

Extent ३३८ पत्र Age

Subject आयुर्वेद

© Dharmartha Trust J&K. Digitized by eGangotri

शालिहोत्र नं. ३७

नं ३४

67

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

नं. [illegible]

[illegible]

[illegible]

आयुर्वेद:

5462

Introduction

1 – 7

Double # 130

Missing P# 170 – 179

F – 339

Complete

Sharma

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

नंबर	सूचीपत्र शालिहोत्रदा	प॰	श्लो॰
१	मंगलाचरण	१	१
२	ग्रंथनिर्माणविधिः	१	२
३	अश्वपालनप्रशंसा	१	५
	अध्याय २		
४	रोगाणांनामानि	७	१
५	आवर्तादिअष्टलक्षण	८	११
६	अश्वानांदशक्षेत्रकथनं	८	१४
७	आवर्त अर्थात भौरी	९	१६
८	स्थिरआवर्तस्थानानि	९	२३
९	आवर्तफलम्	९	२४
१०	अन्यावर्ताः संभवति स्थानानितेषां	१०	२६
११	विंशतिआवर्तनाशुभस्थानानि	१०	२८
१२	षट्विंशतिआवर्तानांनिंद्यस्थानानि	११	३८
१३	अथ शुभावर्तफलं	१२	४१
१४	अशुभावर्तफलानि	१४	६२
१५	शुभावर्तानि	१७	८४
	तृतीयध्याय: ३		
१६	अश्वलक्षणम्	१७	२
१७	अश्वदंतलक्षणम्	१८	३
१८	ओष्ठादिलक्षणम्	१८	४
१९	नेत्रादिलक्षणम्	१८	५
२०	कर्णलक्षणम्	१८	६
२१	मस्तकलक्षणम्	१८	६
२२	स्कंध अर्थात मंढे ग्रीवा = गर्दन	१८	७
२३	स्कंधलक्षणम्	१८	९
२४	जंघालक्षणम्	१८	१०
२५	पादलक्षणम्	१८	१२
२६	पृष्ठलक्षणम्	१८	१४
२७	लिंगलक्षणम्	१८	१५
२८	जघनलक्षणम्	१८	१६
२९	गुदालक्षणम्	१८	१७
३०	ऊरूलक्षणम्	१८	१८
३१	पाश्चिमजंघादिलक्षणम्	१९	१९
३२	अश्वानांशुभलक्षणम्	१९	२०
	चतुर्थाध्याय: ४		

© Dharmartha Trust J&K. Digitized by eGangotri

१

नं	सूचीपत्र	प	श्लो
	अथाश्वानांमिश्रितफलम्	२०	१
	श्वेताश्वलक्षणं	२०	२
	अश्वपालनफलम्	२१	३
	अश्वानांजठरादिश्वेतस्थानफलम्	२१	५
	रक्ताश्वलक्षणम्	२१	६
	ग्रहेजयदाश्वलक्षणम्	२१	७
	अष्टमंगलाश्वलक्षणं अर्थात् आठजगा	२१	८
	अनेकरंगाश्वलक्षणं (चिटीया	२१	९
	अश्वरक्षणफलं	२१	१०
	मध्येश्वेतस्यफलं	२१	११
	सर्वकृष्णमध्येलोहितफलं	२१	१२
	कृष्णोरक्तोवाश्वेतोदर फलम्	२२	१३
	कर्णादिस्थानेषुश्वेतचिह्नफलम्	२२	१६
	नेत्रेश्वेतकर्णलक्षणम्	२२	१७
	सूर्यकांताश्वलक्षणम्	२२	१८
	नागजातीयलक्षणम्	२२	१९
	ज्योतिष्मान्लक्षणम्	२२	२०
	आह्लादकीर्तिलक्षणम्	२२	२१
	पंचकल्याणलक्षणम्	२२	२२
	एकश्यिरचिह्नफलम् (स्तनस्यफलं	२२	२३
	नाभिमारभ्यपूर्वार्धरक्तंपश्चिमार्धहरितंय	२२	२४
	अस्यफलं अर्धश्वेत अर्धरक्तफलंच	२२	२५
	अस्यफलम्	२३	२६
	कृष्णपुच्छार्धस्यफलम्	२३	२७
	अथनिंदिताश्वलक्षणानि	२३	२८
	श्वेतैकपादं वा कृष्णैकपादं वा निंद्यं	२३	२९
	चतुष्चरणसितः द्विचरणसितोवाश्वलक्ष(ण	२३	३०
	सर्वांगलक्षणम्	२३	३१
	अथहयानांवर्णफलं	२३	३५
	अमन्सर्वांगलक्षणं	२३	३८
	लक्षणफलं	२४	४२
	वर्णवर्णफलंएथक	२४	४३
	पंचमोध्यायः ५		
	अथपुच्छलक्षणंफलंचस्थानविशेषेण	२५	१
	स्वस्ववर्णस्वकीयवर्णफलानि	२६	१
	अश्वानांनिंदितलक्षणानि	२६	२

© Dharmartha Trust J&K. Digitized by eGangotri

नं.	सूचीपत्र	प.	श्लो.
	षष्ठोध्यायः ६		
	अथाश्वानां हेषितं अथातूशब्दलक्षणम्	२७	२
	सप्तमोध्यायः ७		
	अथाश्वमुखात् गंधलक्षणम्	२७	१
	निषिद्धगंधिफलम्	२७	३
	अष्टमोध्यायः ८		
	अथाश्वानां छायानिर्णयः	२८	१
	पंचविधछायाकथनम्	२८	२
	पृथक्पृथक् छायाज्ञानफलम्	२८	४
	अथगत्याध्यायः ९		
	शुभगतिलक्षणम्	२८	१
	निषिद्धगतिलक्षणम्	२९	४
	अथसत्वाध्यायः १०		
	अथत्रिविधसत्वकथनं	२९	१
	अथसभेदकथनं उत्तमादिभेदेन	२९	२
	अथमहादोषाध्यायः ११		
	अथदोषकथनं	३०	१
	निषिद्धदंतकथनं	३०	४
	अथसदंत सदर्शनजन्मफलं	३०	५
	निषिद्धांगादिस्थानकथनं	३०	५
	अथमहादोषाणांफलनिकथ्यंते	३१	९
	कृष्णदंतफलम्	३१	१०
	विषमदंतफलम्	३१	११
	विरलदंतफलम्	३१	११
	अधिकदंतपंक्तिफलं	३१	११
	अथरोर्ध्वदंतपंक्त्याधिकाफलं	३१	१२
	हीनदंतफलम्	३१	१४
	अधिकदंतफलम्	३१	१५
	भग्नदंतदंष्ट्रास्यफलम्	३१	१६
	मुंडवृद्धिफलम्	३१	१७
	पंचमवर्षेमुंडवृद्धिफलम्	३१	१८
	विषमदंतास्यफलं	३२	१९
	लोमसदर्शनफलं	३२	२०
	सदंतजननफलम्	३२	२१
	दिवाजननफलम्	३२	२२
	हीनाधिकांगेकदर्शनस्यफलम्	३२	२३
	लवदर्शनस्यफलं	३२	२४

© Dharmartha Trust J&K. Digitized by eGangotri

नं	सूचीपत्रम्	प.	श्लो.
	निषिद्धनेत्रलक्षणम्	३२	२५
	वर्णफलम्	३२	२९
	खरसहस्रस्यफलं	३३	३१
	मार्जारस्यफलम्	३३	३२
	केशरहितास्यजन्मफलम्	३३	३२
	कृष्णठोडीफलम्	३३	३३
	अष्टस्थानकृष्णफलं	३३	३४
	कृष्णतालुजिह्वादिफलम्	३३	३५
	कृष्णाडस्तकशिरोमेढ्रेषुफलं	३३	३६
	अन्यवर्णस्यसितपुच्छफलं	३३	३७
	अन्यवर्णस्यसितपृष्ठफलम्	३३	३८
	वालकेशशिरोयस्यदृग्यचर्मगंधयुतास्यस्यफलं	३३	३९
	मलमासप्रसूतास्यफलम्	३३	४०
	शृंगस्यफलम्	३४	४१
	त्रिकर्णस्यफलम्	३४	४२
	गोखुरसमखुरफलं	३४	४३
	गोस्तनास्यफलम्	३४	४३
	पंचखुरास्यलक्षणम्	३४	४४
	ललाटदीमास्यलक्षणं मस्तके हृत्प्रदेशे फलं पुंड्र	३४	४५
	गुदायां मस्तके वा पुच्छफलं	३४	४६
	लिंगस्यमूडताफलं	३५	४७
	सर्वश्वेतस्यकृष्णशिरफलं	३५	४८
	एकपादस्यपृथक्वर्णफलम्	३५	५०
	यस्यपृष्ठस्कंधौमृगाजिनाभौभवेतांतस्यफलं	३५	५२
	अन्यांगेषुपृथक्फलानि	३५	५४
	एतेषांमहादोषाणांफलानि	३५	५५
	एतेषांसर्वेषांप्रायश्चित्तम्	३५	५६
	एषांस्वदेशस्थितौसत्यांशांतिरुक्ता	३६	५९
	इतिमहादोषाध्यायः		
	अथनालरागाध्यायः	३६	१
	नालरंगकथनम्	३६	२
	रक्तनालफलम्	३६	३
	नालदेशेरेखात्रयफलं	३६	४
	कृष्णनालफलम्	३६	५
	नालदेशेकृष्णविंदुफलं	३५	१०
	पुनःकृष्णनालभेदाः	३७	११
	रक्तनालभेदाः	३७	१२
		३७	

© Dharmartha Trust J&K. Digitized by eGangotri

नं.	सूचीपत्रम्	पत्रा	श्लो.
	समानवर्णविर्णनालकफलं	३७	१३
	नालदोषप्रतीकारः	३७	१४
	अथाश्वकुलाध्यायः ॥		
	अश्वानां कुलकथनं (र्णयः	३७	२
	कस्मिन्कुले जातोयमश्व इति लक्षणद्वाराणि	३८	१२
	कंबोजकुलोत्पन्नाश्वलक्षणं	३८	१३
	वाह्लीकाश्वलक्षणम्	३९	१९
	वनायुजाश्वलक्षणम्	३९	२२
	गांधाराश्वलक्षणम्	४०	२७
	वांपेयाश्वलक्षणम्	४०	२९
	सैंधवाश्वलक्षणम्	४०	३०
	तैतरकुलजाश्वलक्षणम्	४०	३१
	कुलजाश्वलक्षणम्	४०	३२
	उपकुलजाश्वलक्षणम्	४०	३३
	मेचककुलजाश्वलक्षणम्	४०	३४
	उपमेचकाश्ववर्णनम्	४०	३६
	त्रिगर्ताश्ववर्णनम्	४१	३७
	अर्जुनाश्वलक्षणम्	४१	३८
	साविन्नाश्वलक्षणम्	४१	३९
	यौधेयाश्ववर्णनम्	४१	४१
	यावनाश्वलक्षणम्	४१	४२
	ह्रस्वयावनाश्वलक्षणम्	४१	४६
	तुषाराश्वलक्षणम्	४२	४८
	कांदेयाश्वलक्षणम्	४२	५०
	नार्मदेयाश्वलक्षणम्	४२	५१
	आनर्ताश्वलक्षणम्	४२	५२
	काश्मीराश्वफलवर्णनम्	४२	५३
	सकानकाश्ववर्णनम्	४२	५४
	पार्वतेयाश्ववर्णनम्	४२	५६
	आजानेयाश्वलक्षणम्	४३	५७
	अथाश्वानां वयज्ञानम्		
	दंतैरश्वायुर्ज्ञानम्	४३	२
	अथ वर्णादिद्वाराश्वायुर्ज्ञानं	४४	१६
	अथाश्वानां वर्णकथनम्	४७	१
	देवाद्यश्ववर्णनम्	५०	१
	देवाश्वलक्षणम्	५०	३

© Dharmartha Trust J&K. Digitized by eGangotri

३

न॰	सूचीपत्रम्	पत्रा	श्लो॰
	अश्वमेधयोग्याश्ववर्णनम्	५०	७
	पुरोधाश्वलक्षणम्	५०	८
	हयराजाश्वलक्षणम्	५०	९
	देवमयाश्वलक्षणम् (मि:	५१	१०
	अश्वपूजनपालनेफलंरैवन्तस्य राज्य प्रा	५१	११
	अभिषेकयोग्याश्वलक्षणम्	५१	२१
	मंत्रियोग्याश्वलक्षणम्	५२	२५
	राज्ञः योग्याश्वलक्षणम्	५२	३३
	शत्रुविजयेराजयोग्याश्वः	५३	३८
	राज्ञाश्वलक्षणम्	५३	४०
	सर्वार्थसिद्धिकराश्वः	५३	४१
	राजाश्वलक्षणम्	५३	४२
	अथाश्वांगाध्यायः	५३ / ५४	१
	अथजिह्वादिअंगेनिर्णयः	५४	३
	दंतनिर्णयः	५४	५
	ओष्ठनिर्णयः	५४	६
	सृक्कणीचिबुकनिर्णयः	५४	७
	अपानप्रोथनिर्णयः	५४	८
	घोणागंडयोः कथनम्	५४	९
	अश्रुपातस्थाननिर्णयः	५४	१०
	नेत्रदृष्टिकथनं	५४	११
	अपांगकनीनकास्थानं	५४	१२
	ललाटशिरकथनम्	५५	१३
	मस्तककर्णशंखकटस्थानं	५५	१४
	हनुवक्त्रनिगालादिकथनम्	५५	१६
	विडमन्यस्थानकथनम्	५५	१७
	ग्रीवास्थाने जत्रुस्थानम्	५५	१८
	कीकसास्थाने ककुदस्थाने च	५५	१९
	असनस्थानपृष्ठस्थानकथनम्	५५	२०
	अप्रांसगलक्षणम्	५५	२१
	कंठवक्षकथनम्	५५	२२
	नाभिकिण मेढ्रलक्षणम्	५५	२३
	कलापलिङ्गकथनम्	५५	२४
	किणिकटिकाखुरकथनं	५६	२५
	पार्ष्णिशीर्षपादतलमंडूकीनां स्थानम्	५६	२६
	अश्वानां अंगादिकानां आयामोत्पन्नादितानि	५७	२७
	मस्तकेपुंड्रलक्षणम् मस्थानो	५८	२८

© Dharmartha Trust J&K. Digitized by eGangotri

नं.	सूचीपत्र	पत्रा.	श्लो.
		५८	९
	प्रमाणाध्यायः	५९	१६
	इतिकृत्राध्यायः	५९	९
	संग्रहेऽष्टांगलक्षणम्	६३	२८
	संग्रहे व्याधिनिर्देशोध्यायः	६७	४३
	इतिक्रियासूत्राध्यायः	६९	२२
	शालविधिः	७१	१९
	गुग्गुलविधिः	७२	१६
	वार्षिकविधिः	७३	७
	शारद्विधिः	७३	५
	हेमंत शिशिरविधिः	७३	३
	वसंतविधिः	७४	५
	ग्रीष्मविधिः	७४	४
	षड्ऋतुकाध्यायः	७५	१४
	लवणविधिः	७६	१६
	स्वस्थवृत्तेतुरगपरिचर्य्यानामध्यायः	७८	१६
	माषविधिः	७९	१९
	यवविधिः	८२	३७
	सस्यविधिः	८३	१६
	रसविनिश्चयः	८४	११
	रसवीर्यविधिः	८५	१५
	सुराकल्पम्	८६	१९
	मधुरविधिः	८८	९
	द्रव्यगुणदोषनिर्णयः	८९	११
	खोदनविधिः	९०	१४
	दशमूलाधिकारं	९०	६
	रसव्याकरणाध्यायः	९१	१७
	स्नेहपानविधिः	९२	३
	महातिक्तकंघृतं	९२	७
	द्वितीयमहातिक्तकंघृतं	९३	५
	शिरीषाद्यंघृतं	९३	८
	शिरीषाद्येघृतं द्वितीयं	९४	११
	शिरीषाद्येघृतंतृतीयम्	९४	१६
	पंचतिक्तकंघृतम्	९५	४०
	संग्रहे महास्नेहः	९५	४७
	चैतनघृतम्	९६	२३
	जीवनीयंघृतम्	९६	२४
	नाग्याद्यंघृतम्		

© Dharmartha Trust J&K. Digitized by eGangotri

नं.	सूचीपत्रम्	पत्र	श्लो.
	तैलविधिः	९७	५८
	अमृताद्यं तैलं	९८	६३
	गंधाद्यतैलं	९८	६६
	हिंस्राद्यतैलं	९८	७०
	प्रसारिणीतैलं	९८	७५
	शतावरीतैलं	९९	८१
	माषतैलं	९९	८३
	स्नेहकल्पः	९९	८८
	वृहत्कटुपिंडिकाः	१०१	१३
	शोषाद्यपिंडं	१०१	१६
	कटुपिंडं	१०१	१७
	द्विचत्वारिंशत्कटुपिंडं	१०१	२४
	लवणपिंडं	१०२	३०
	मिश्रपिंडम्	१०२	३१
	वर्तलवणः	१०३	४३
	सुगंधिकटुचूर्णः	१०३	४६
	उत्तरवातिकनाम	१०४	५७
	द्वात्रिंशत्कटुपिंडिका	१०४	६०
	इतिचूर्णादिरष्टम्	१०५	६९
	ऊषणादिपिंडः	१०५	७४
	षट्शत्तनांप्रतिपानं	१०६	८३
	अभयादिपानं	१०६	८४
	दैन्याद्यपानम्	१०६	८५
	वकुलाद्यपानम्	१०६	८६
	नेवराद्यपानम्	१०६	८७
	मुस्तादिकाथः	१०७	९१
	विडंगादिचूर्णम्	१०७	९५
	महारास्नादिपाचनं	१०८	८
	रास्नापंचकम्	१०८	१०
	कृष्णादितैलम्	१०८	१५
	रास्नाचतुर्दशः	१०९	१७
	रास्नाद्वादशः	१०९	२२
	रास्नादिकाथः	१०९	२३
	पाचनविधिः	१०९	२६
	शोथघ्नी	१०९	२७
	अग्निदीपकंनाम	११०	२९

© Dharmartha Trust J&K. Digitized by eGangotri

नं.	सूचीपत्रम्	पत्रा	श्लो
	लघुहिंग्वादि	१९०	३०
	बृहत्हिंग्वादि	११०	३१
	हिंग्वाष्टकम्	११०	३२
	श्योनाकाद्यंखलं	११०	३४
	पुष्कराद्यंक्षीरं	१११	३७
	चित्रकाद्यंलेह्यम्	१११	४१
	पित्तघ्नविधिः	१११	४७
	श्लेष्मविधिः	११२	५०
	लोहितचंदनादिप्रतिपानं	११२	५२
	समग्रप्रतिपानकल्पः	११२	५४
	कुष्टचतुष्टयं	११३	५७
	रसोनपंचकम्	११३	६८
	रसोनकल्पम्	११३	७०
	भोजनकल्पः	११३	७२
	द्राक्षादिकटुभोजनं	११३	७३
	त्रिफलादिचूर्णं	११३	७४
	निंबादिअवलेह	११४	७६
	मुस्तादिअवलेह	११४	७८
	भार्ग्यादिअवलेह	११४	७९
	अष्टांगचूर्णम्	११४	८१
	त्रयोदशांगचूर्णम्	११४	८५
	हरीतकीसूरणाद्यंलेहं	११५	९२
	लेहकल्पः	११५	९४
	आभाष्टकम्	११६	७
	लावणकल्कः	११७	२०
	धूमकल्कः	११८	३९
	प्रधमनकल्पः	११९	५३
	मुखधावनं	११९	५५
	अभ्यंगविधिः	११९	५७
	उन्मर्दक	११९	५९
	सर्वदोषहरं	१२०	६३
	लेपकल्पः	१२०	७४
	उपनाहः	१२१	८४
	अग्निकर्मनामाध्यायः	१२२	९७
	क्षारोध्यायः	१२३	९८

© Dharmartha Trust J&K. Digitized by eGangotri

५

5

नं.	सूचीपत्रम्	पत्र	श्लो.
	सिरावेधविधिः	१२६	३६
	स्वेदविधिः	१२८	५८
	लेखनीयान्यंजनानि	१२९	७४
	अंजनकल्पः	१३०	९०
	क्षीरविधिः	१३१	१००
	उत्तरवस्ति	१३१	३
	वस्तिनिरूहकल्पः	१३५	५८
	वातनिदानं	१३६	११
	पित्तनिदानं	१३६	१७
	श्लेष्मनिदानं	१३७	२२
	रक्तनिदानं	१३८	३१
	वातचिकित्सा	१३८	४
	पित्तचिकित्सा	१३८	६
	श्लेष्मचिकित्सा	१३९	९
	स्वभिन्नवर्जिनिदानं	१४१	२५
	स्वभिन्नचिकित्सा	१४१	४४
	रक्तवनेचिकित्सा	१४२	५२
	मूत्रचिकित्सा	१४३	६६
	मूत्रवर्तः	१४३	६८
	मुहवर्तः	१४४	७४
	वातोदरचिकित्सा	१४४	८०
	रक्तप्रमेहचिकित्सा	१४५	९०
	कोरहषचिकित्सा	१४६	९८
	स्नेहवर्तिचिकित्सा	१४६	६
	विवर्तचिकित्सा	१४७	१२
	मांसनिबंधचिकित्सा	१४७	१७
	कुंधवर्तचिकित्सा	१४८	२६
	वर्तोचिकित्सा	१४८	३१
	शूलचिकित्सा	१५०	५२
	ग्रामचिकित्सा	१५०	५३
	वातमूत्रचिकित्सा	१५०	६०
	पैत्तिकमूत्ररोगचिकित्सा	१५०	६१
	श्लेष्मकमूत्ररोगचिकित्सा	१५१	६४
	सन्निपातमूत्ररोगचिकित्सा	१५१	६७

© Dharmartha Trust J&K. Digitized by eGangotri

न॰	सूचीपत्रम्	पत्र	श्लो
	कपोतनिषादस्तम्भः	१५२	७५
	पृष्ठग्रहस्तम्भः	१५२	७९
	हनुग्रहस्तम्भः	१५२	८१
	मृगरोगः	१५३	८६
	आक्षेपकः	१५३	९०
	आर्दितः	१५३	९२
	वातस्तम्भनिदानं	१५४	९६
	उत्कर्णिकचिकित्सा	१५४	३
	महास्तम्भः	१५५	१६
	मन्यास्तम्भः	१५५	१८
	कपोतनिषादचिकित्सा	१५६	३०
	पृष्ठस्तम्भचिकित्सा	१५७	३२
	मृगजम्भचिकित्सा	१५७	३६
	मृगरोगचिकित्सा	१५७	४१
	आमितचिकित्सा	१५८	४४
	वातरोगचिकित्सा	१५८	५३
	सामान्यरोगचिकित्सा	१५९	५५
	सामान्यमुखरोगचिकित्सा	१६१	७६
	आवालुचिकित्सा	१६१	८२
	वातकचिकित्सा	१६१	९३
	जिह्वास्तम्भचिकित्सा	१६२	९०
	गलग्रहचिकित्सा	१६२	९७
	अधिदन्तचिकित्सा	१६३	९
	अश्वकाशचिकित्सा	१६३	१५
	पित्तकासचिकित्सा	१६४	२४
	श्लेष्मकासचिकि॰	१६४	२७
	स्नेहव्यापत्	१६७	४४
	लवणव्यापत्	१६७	५०
	धान्यव्यापत्	१६७	५३
	सुराव्यापत्	१६७	५४
	क्षीरव्यापत्	१६९	६२
	जलव्यापत्	१६९	८६
	सलिलव्यापत्	१६९	७३
	नाडीव्यापत्	१८०	८३
	कृमिकोष्ठ श्लेष्मकोष्ठचिकित्सा	१८२	८
	विषग्रहचिकित्सा	१८३	१८

© Dharmartha Trust J&K. Digitized by eGangotri

९

६

नं.	सूचीपत्रम्	पत्र	श्लो.
	वातहृद्रोगचिकित्सा	१८४	२९
	पैत्तिकहृद्रोगचिकित्सा	१८५	३४
	नीराणकचिकित्सा	१८७	५८
	प्रसुवाययुक्तं अंजलिकारिकाचिकित्सा	१८८	७५
	कर्णरोगचिकित्सा	१८९	८३
	अस्कपातचिकित्सा	१८९	९१
	वातवलासचिकित्सा	१९०	१
	आमंडचिकित्सा	१९०	७
	उत्रीतरोगचिकित्सा	१९१	१४
	अंडस्कंधचिकित्सा	१९२	२६
	अंडउच्चालनचिकित्सा	१९२	३१
	पित्तांडचिकित्सा	१९३	३५
	रक्तांडचिकित्सा	१९३	४०
	श्लेष्मांडचिकित्सा	१९३	४१
	पुछांडचिकित्सा	१९४	५१
	अर्षसाचिकित्सा	१९४	५७
	वालादकचिकित्सा	१९४	६०
	उदरिणीचिकित्सा	१९६	७७
	प्रस्कंधचिकित्सा	१९७	९८
	अन्तस्कंधचिकित्सा	१९८	१
	राज्ययक्ष्मचिकित्सा	१९८	१२
	व्यालचिकित्सा	२००	२७
	रात्रीहनचिकित्सा	२००	३६
	हरणीचिकित्सा	२०१	४६
	गलिकचिकित्सा	२०१	५०
	मधमनचिकित्सा	२०२	५३
	वसमनचिकित्सा	२०२	५७
	उन्मनचिकित्सा	२०२	६४
	कुष्टचिकित्सा	२०४	८३
	दद्रुचिकित्सा	२०४	९४
	पामाचिकित्सा	२०५	७
	दशपिनचिकित्सा	२०६	१६
	त्वक्दोषाध्यायः	२०७	३७
	सपणुचिकित्सा	२०८	४५
	द्रोणिकाचिकित्सा	२१०	६८
	मुखद्रोणिकाचिकित्सा	२११	८३
	हिक्काश्वासचिकित्सा	२१२	३

© Dharmartha Trust J&K. Digitized by eGangotri

नं.	सूचीपत्रम्	पत्रा	श्लो.
		२१४	२१
	वातसारचिकित्सा	२१४	२९
	पित्तातिसारचिकित्सा	२१५	३५
	श्लेष्मातिचिकित्सा	२१५	४२
	अतीसारचिकित्सा	२१६	५०
	कोटवाजी चिकित्सा	२१६	५३
	वातशिरोरोगचिकित्सा	२१७	५८
	पित्तशिरोरोग चिकित्सा	२१७	६२
	श्लेष्मरोग चिकित्सा	२१७	६५
	सन्निपातरक्तांग त्तु चिकित्सा	२१८	७५
	शिरोरोगचिकित्सा	२१९	८७
	नलुलंगिनचिकित्सा	२१९	९४
	कूर्चलंगिनचिकित्सा	२२०	९८
	अप्पस्थिचिकित्सा	२२०	१००
	नानुलंगिनचिकित्सा	२२०	७
	उरीलंगिनचिकित्सा	२२१	१२
	अशलंगिनचिकित्सा	२२१	१८
	त्रिकलंगीचिकित्सा	२२१	२१
	उभयलंगीचिकित्सा	२२२	२५
	चक्रसक्थिलंगिता	२२२	२९
	स्फुरलंगिनचिकित्सा	२२५	५८
	खुरादीनां चिकित्सा पांसुखुरचिकित्सा	२२६	२२
	मकंचप्रकोटचिकित्सा	२२७	३१
	स्थानरुकादीनांसामान्यचिकित्सा	२२८	३८
	उत्लूकपादचिकित्सा	२२९	११
	गुदभ्रंशचिकित्सा	२२९	१७
	भाराविषण्णचिकित्सा	२३०	३५
	रक्ताभिघानचिकित्सा	२३१	४९
	ज्वराभितापचिकित्सा रक्तपित्तचिकि०	२३३	९०
	विद्युत्तिमचिकित्सा	२३३	९६
	अग्निदग्धचिकित्सा	२३५	८९
	पित्तज्वरचिकित्सा	२३५	९६
	श्लेष्मज्वरचिकित्सा	२३५	९८
	सन्निपातज्वरचिकित्सा	२३६	६
	रक्तविपर्यासोषधीगंधचिकित्सा	२३६	९
	मानसज्वरचिकित्सा	२३८	३८
	वातसिंहानचिकित्सा	२३८	४०
	पित्तसिंहानचिकित्सा	२३९	४८
	श्लेष्मसिंहानचिकित्सा		

© Dharmartha Trust J&K. Digitized by eGangotri

नं.	सूचीपत्र	पत्र	श्लो.
७	सन्निपातचिकित्सा	२३९	५५
	रक्तसिंहानचिकित्सा	२४०	५९
	आगन्तुसिंहानचिकित्सा	२४०	६२
	प्रातारचिकित्सा	२४१	७९
	प्रतितन्नचिकित्सा	२४२	२४
	अष्ठीलचिकित्सा	२४२	८७
	बुद्बुदचिकित्सा	२४३	९५
	नानकाचचिकित्सा	२४४	९
	परिस्रावचिकित्सा	२४५	१७
	स्तंभचिकित्सा	२४६	२१
	रक्ताभिष्यन्दचिकित्सा	२४६	२७
	नेत्राभिष्यन्दचिकित्सा	२४६	३०
	मेजचिकित्सा	२४८	४९
	व्रणचिकित्सा	२५१	८०
	नाडीव्रणचिकित्सा	२५२	९०
	पुण्डरीकग्रहचिकित्सा	२५३	९
	अर्बुदचिकित्सा	२५४	९
	शल्यचरणम्	२५५	१४
	भग्नचिकित्सा	२५७	३५
	अञ्जनमंत्रः	२५८	१२
	कुंभनाममंत्रः	२५८	१७
	विषतंत्रं	२६१	१८
	रसायनविधिः	२६२	५७
	वाजीकरणम्	२६३	७
	ग्रहलक्षणनामभूतविद्याविधिः	२६९	६७
	ग्रहलक्षणाध्यायः	२७२	९७
	आरोगारिष्टनामाध्यायः	२७५	१९
	आरोग्यलक्षणम्	२७९	५०
	वैथारिष्टाध्यायः	२८२	३४
	दृष्टिकृतासिनावानात्	२८४	२६
	नेत्रपरीक्षा	२८५	४०
	जिह्वापरीक्षा	२८५	४१
	संग्रहाध्यायः	२८६	६
	प्रकृतिलक्षणम्	२८७	१२
	चातुर्वर्णिकम्	२८८	१७
	आयुर्ज्ञाननामाध्यायः	२९०	५२
	औषधरसानिर्देशः	२९२	१८

© Dharmartha Trust J&K. Digitized by eGangotri

नं.	सूचीपत्र	पत्र	श्लो.
	प्रथमसंभवः	२९२	१
	द्वितीयसंभवः	२९३	२
	तृतीयसंभवः	२९४	३
	चतुर्थसंभवः	२९४	६
	वाजीनांसंभवः	२९४	८
	साराध्यायः	२९५	१३
	अनूकाध्यायः	२९६	१
	शरीरलक्षणम्	२९७	१४
	आवर्ताङ्कवा	३०३	६४
	उक्तंचभगवताशालिहोत्रेण	३०४	७१
	व्यामिश्रकशेषालक्षणाध्यायः	३०६	५९
	गर्भसम्भवविधानाम	३०७	२
	शरीरविनिश्चयः	३०८	१
	सूतिकोपक्रमः	३१०	३२
	किशोरचिकित्सा	३१०	३७
	शरीरलक्षमानं	३११	४२
	कूटश्लोकव्याख्या	३११	४९
	चतुष्पंदचिकित्सा	३१२	५३
	धातुनामानि	३१३	६०
	दुर्मनाख्यानं	३१४	७६
	दोषोपक्रमः	३१५	८७
	गर्भलक्षणं	३१९	३४
	वाराप्रकीरणं	३२०	३९
	अग्निलक्षणम्	३२३	५२
	परिवेषोनामाध्यायः	३२४	३९
	अपिएवंचप्रयोजयेत्	३२५	५६
	उत्तरस्थानंसमाप्तम्	३२७	८८

इतिसूचीपत्रंसमाप्तः ॥

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

शा·
हो·
१

ॐ श्रीगणेशायनमः ॐ ग्रंथकर्ताग्रंथप्र
मादि वास्ते इष्टदेवको नमस्काररूपी
मंगल आचरण कर्ताभया मैंयोहांगणयो
प्रयोगमुनियोने कहेहैंन सोकहताहों
वारश्लोकोंका संबंधहै श्वेतदेहवालेश्री
शिवजीहैं तिनको नमस्कारकरके वापने
सूर्यको औरब्रह्माको औरशालिहोत्रको
कैसेहीशिवजीहै पापरूपीयोतिमरअंधका
रहै तिसके हरकरनेवालेहै सूर्यजीकैसेहैं

ॐ स्वस्ति श्रीगणेशायनमः प्र
णिपत्यधवलतनुमथतिमर
हरंगोपतिंगणेशंकंच अश्वायु
र्वेदनिधिंमहामतिंशालिहोत्रं
च १ येशालिहोत्रसंमतगं·
भीरमहर्षिभिःपुरागदिताः
तैस्तैतुरंगशास्त्रेयोगाःशा·
भैविकाराणाम् १

तिमरहरहै अरुगोपतिकिरणोंकेपतिहै
अरुशिवपक्षमें बैलकेस्वामिहै ब्रह्माजी
कैसेहैं किरणोंकेपतिहैं शालिहोत्रकैसे
हैं घोड्योंकायोआयुर्वेदहै तिसविषेनि·
पुणहैं अरुबड़ीबुद्धिवालेहैं १ येइयो
ग घोड़ियोंके रोगहरणेवाले शालिहोत्र
संमतगंभीरऋषीश्वरोंने अगले अप
ने अपनेग्रंथोंविषे कहेहैंनसोप्रयोग २

© Dharmartha Trust J&K. Digitized by eGangotri

ऐसा लिखोहुआ सद्गुन गर्ग इत्यादि मुनियोंने बोड़े
ओंके शास्त्रोंमें यो प्रथक् के सब काल ये पड़े योग
कहेहैं तिन्होंने वर्गे श्रेष्ठ योगकउके सिद्धयो
गोंका समेतप्रकार संग्रह कीयाहै हे राजन् पहे
सभ ग्रंथोंका सार ग्रंथ बनायाहै १ ये सब बड़ी बु
द्धिवाले यो महामति ऋषियोंने कहाहै धर्म
अर्थ काम नाम सिद्धि बोड़ेयोंकर्के होतियाहैं
अपसेंहि सबैक हयाहै तैय संहि तिन्होंका

तेषां मध्याद्ज्ञानसारान्तरं हृदयादि
लार्थमुद्धृत्य रचितस्त्वयं समा
सेन संग्रहः सिद्धयोगानां १ ध
र्मार्थकामसिद्धिर्यस्मात्तरंगैर्भ
वेन्मया पूर्वं कथितैर्महा
मतिभिस्तथापि वत्समुद्देश ४
अश्वेहं लगनाश्छीश्रीरव्ये:
विपुलयशः विजयप्रभवन
श्रेरयाहर्मविभूषणम् ५

मतले कर में यो हांग णकवि सोककेयो
गकरतेहें उनकी सिध्यातृ ग्रहणकर्के ध
राजाने श्रेष्ठ गुणवाले बोड़े सदाही रखने यो
ग्य हैं न कोंबोड़ेयोंकर्के पृथ्वी अपने हाथों
विषे रहती है अरु लक्ष्मीयश अरु शत्रुओं
कोजय यह सभ कार्य बोड़ेओंकर्के होते
हैं और बोड़े महिलोक भूषण शोभा
हैन ५

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा. हो. १

2

जिसके घर श्रेष्ठ शुभलक्षणांवाले घोडे रहिते हैन
तिसहि राजाके देश यश धन धर्म काम नाशकी संप
दां स्थिर होकर स्थित रहतीयां हैन ६ जिस राजा
की सारि सेना घोडेयांके समूहकर युक्त रहती है
तिस राजाकों पृथ्वी समुद्रतक हस्तविषें स्थित हो
ती है ७ जिसके घरविषें घोडे एकदिनवी वेडेमें
रहन तिसके गृहविषें लक्ष्मी नारायणका वस

यस्यां गृहपदे लक्ष्मीर्धर्मकामार्थसं
पदः वाजिनो यत्र तिष्ठन्ति सर्वल
क्षणसंयुताः ६ निवसन्यस्य सैः
धोलैः संपूर्णा यस्य वाहिनी तथा
सागरपर्यंतं हस्ते तिष्ठति मेदिनी
एकाहमपि यस्यश्वा निवसन्ति गृ
हाजिरे विलोदैतत्स्थलेषु काल
क्ष्मीस्तस्य गृहे स्थिरा ८ तेहयाः शु
भ्रलक्ष्मीणां हरदाकर्षणक्षमाः
देवाजिवलासंचारैः सद्यस्संशे
शितितलाः ९

स्थलकों छोडके निश्चलहोकरवासकरनी है
८ ऐसे घोडे सुंदर वंगालगामकीयांगती
यांकरके मनोरथवेके चक्रगतिसिंखेदे हैन
से घोडे शत्रुवैरीयों के धनकों बलात्कारक
रते हरनकों समर्थ हैन ९

© Dharmartha Trust J&K. Digitized by eGangotri

ऐसा और कौन है यो घोडे कों छोडके शत्रुओं की फौ
जविषे जाकर शत्रुओं को हटाकर वाजकी नरां फेरघु
डके आवे ऐसा होर कोई नहि १० ये घोडे यो धारण विषे
शस्त्रों करके कटे गए हैन अंग जिनांदे अरु निकल
गइयां हैन आंद्रां अरु घाओं कर व्याकुल तिनां कों
घोडे थे विना और कौन समर्थ है लै आउणे कों ऐ
सा होर नहीं ११ हरदेश व ऊमा मागि जानदे रखावले

कोमस्त्रं गमं मुक्ता श्वविशणरिपुवाहि
नीं शेपनवमुनरखेतिक्षुत्रापरपमुः
भवे १० शोश स्त्र विभिन्नांगानत्रानांश
त्व्रणविह्वलान् स्वामिनो वाजिनं मु
क्ता को निर्वाहयितुं क्षमः ११ हया
धीनं मयतो न तथा संग्राम कर्मणि
श्रेष्ठः परमेनास्ति राज्ञो विजय
कारकं १२ यस्यैकोपि सदुष्टोश्वो
वडवास्ति स्थितिवेशमनि तथापि वि
गतोस्माहाभी नास्ति स्थिति शात्रवः १३
हरदेशान्तरस्यापि विष्टनिष्टनिशंकि
नः ।

यांकों और युद्ध के यो कार्य हैन तिनां विषे राज
यां को घोडे थें विना और ऐसा विजय कों करन
वाला समर्थ कोई नहि १२ जिसके घर इक वी ना
गावल वाला घोडा वड़ा होया स्थित रहता है ति
सके वैरी हर्षों रहित उ देहों ये घर हि वै रह
ने हैन १३ आस्त्र विशेक हैन शुभलक्षण
जिनां दे ऐसे घोडे जिसके पृथ्वी विषे फिर
ने हैन ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ हो॰ १ तिसकेविरोधिहरदेशविषेंवसतेहैंन तदवीउरदे
हिरहेंदेहैंन १४ जैसेसत्रुओंकीसेनाविषें चलनी
होरवालेओतिदीविषें घोडेजैसे प्रवेशकरनेको स
3 मर्थहैंन तैसेहाथीसवारोंकेसाथ समर्थवीहैंन त
दवीप्रवेशनहिकरसकदे १५ राजायोंसतावीकार्य
करनेकोरथवीविषें जैसेघोडेहैंन तैसेइसलोकमें
हाथीनातो पियादे सतावीकामकरसकदे १६

नैरगायसशसेनासुविचरंतिमहीत
ले १४ सकलिनोपिसारोहागजोन
विशन्ति नितिष्ठतीवाचलेतीवाप्र
विशंतियथाहयाः १५ आशुकार्या
णिभूपानांयथाश्वाःरथवीनले ऊर्व
नीहतथाशीघ्रंनगजानपदातयः १६
पदातिगजभृत्यैश्वशालशोधसहस्र
शः वेष्टितोपिव्रजसह्योयथेष्टंपदि
गाडिव १७ रणाद्धतोपितुरगोदेशा
कालाद्यपेक्षया पुनःप्रतिनिवृत्या
शुहंतिशत्रुचमूरणे १८

पियादेअरूकड़ेवलवालेहाथीसैकड़ेहजारांतिनां
कर्के घेरयाहोविघोड़ा अपणिइछ्याकरचलजाता
है जैसेसर्पवादेलोंकेविचते गरूडजीचलकर
निकलआउतेहैं १७ रणकोछोडकर घोड़ा
देशकालकीउपेक्षाकर्के पीछेवीफिरआयहोया
फेरघोड़ेकोमोड़कर सितावीयुद्धविषेंवैरीयोंकी
सेनाकोमारताहै १८ घोड़ेसोहैंन एकक्षणविषे
कहेहोजानेहैंन अरूचरीविषेंनिरवेडकारहजारों

© Dharmartha Trust J&K. Digitized by eGangotri

होजातेहैं अरुएकक्षणमें योप्रधानशत्रुहै तिसकों
देवकेमस्तकेस्थानकोपहुंचादेतेहैं १९ घोडेथेवि
नाऐसाओरकोनहैं एकक्षणविचनेउचलेआउना
अरुतिनविषेहूरउठजाणा अरुक्षणमेंपीछेचल
आउणा अरुक्षणविचअगेचलआउणा ऐसेंइनजा
लवालनटओंकीनाईं घोडेंकोछोडके कोनखेले
नकोऔरसमर्थहै कोईनहिं २० येराजेघोड्यों
कोंरखदेहैन सेशत्रुओंकीसेनाकोंघेरकरशत्रु

क्षणादेकतमायांतिक्षणाद्यांतिसह
स्रशः क्षणान्मुखेपिष्ठेवीक्षन्तेयति
यमसादने १९ क्षणमतःक्षणहरेत
णपश्चात्क्षणपुरः इन्द्रजालकिवोति
ष्टकोमोमुत्कानरगमे २० तेविपक्ष
तयैकृत्वाघ्नपुरःश्रियमुन्नेमा पिशि
कृमरिपुमस्केहृत्यारयंतितेरगामात् २१
वेष्टितस्तयदातिष्टहिताययमषा
दनैः नदातेविजितमन्येयदिकृपा
पिरत्ते २२ शत्रोःसहायमायातं
कृत्वाहृत्वादपिदुर्न गत्वाक्षेतिहया
रोहाः पुनरायांतितत्क्षणात् २३

यांकोमारकेउनाकोयोश्रीउत्तमलक्ष्मीहै तिसको
आप्तहोतेहैंन २१ यदयोपुरुषयोयाघोडेयोंसेना
करकेघेरयाहोया घोडेजिसदेशायदानेथिंविना
स्थितहैं अरुंइहककेरक्षतवीहै तदवीतिसकोंहा
रेआहोयाहिमनतेहा २२ येघोडेयोंकेसआरहै
न सोवैरीयोंकीसहायताओरआईहै इसवातों
कोसुणके सनावीहूरजायके हस्तेहीतिनकों
मारदेतेहैं फेरसनावीहिमुडकेचलआउदेहैं २३

© Dharmartha Trust J&K. Digitized by eGangotri

रा॰
हो॰
४

पृष्ठविषैंस्थितश्रस्वयोहैं सोनिश्चयकरशत्रुश्रोंकी
सेनाकों नाशकरतेहैं योघोड़ेपृष्ठविषैंस्थितनहि
हैं सोभोजनत्यायजलस्थानसाकरतेहैं २४ श्र
रुयोखेडतश्रगड्डाहोपरोगीहोवें श्ररुश्रस्वऊपर
चढ्याहोवे समर्थ तदवीशत्रूउसकेऊपरनहिंगमा
नुकरसकदे श्ररुयोसमर्थस्थितहै सूरवीर श्रोर
सयोश्रापहैरयाहोवे श्रोर तरवार उगाला यत्नुष
परेहैहस्थविषेहोवे श्ररुस्वारहोवे तोपेसायत्नुष।

स्वारैनेयवसंनेोयेनाशयेत्तिनसंशय ः २४
श्रश्वमानाश्रपेवेत्तपयेतिहिणवश्च
वित्तैवमृदोषैवगमयेतिनशत्रवः
कल्पिताःसंस्थिताःशूराःलिश्रमन्नाह
थाशिताः २५ स्वङ्गप्राशयत्नुहैस्ताःसे
ग्रामेपृङमेयानराः जितशीतातपाल।
सोनिनगासाजिनासनाः २६ गुणमा
नाहयायोद्दादेवानामपिडमेयाः ने २७
स्मादृषिघटाकार्याहयसंदोहसंयुता
वेदहीनायथायत्रिःपतिहीनायथातिः
सेना हयहीनानत्थासेनाविलसीएाा
पिनशोभते २८ यहोताहै श्ररु २९
पृष्ठविषैंजे
जिनोंनेंजीतेयाहै शीतस्पश्रालसभयश्ररुभोजन
येयोयारसप्रकारसन्नधुश्रश्चोंकेऊपरचढके युद्धक
रतेहैं सोभटदेवतयोंकोंडर्नेयद्रस्वकरजीनेजाते
हैं तिसकारनतेंराजानेघोडेयोंकेसंत्तुवालीसेना
करनेचाहिये २७ जैसेंचंद्रमाविनाराश्री
श्ररुस्वामीविनापतिव्रतास्त्रीनहीसोभापाते
तैसहिंघोडियोंविनावडेविस्तारवालीबी से।
नाहै नदवीनहिंसोभदी २८

4

जेहाथीमदमत्तअरुपर्वतकेखंडसमदेहोंकीउपमा
अरुकिसेकरकेवहिहटायेजाते अरुकोइनहिउन
केवलकोसहारसकदा ऐसेवीहैन तदवीउनकीर
क्षायेअग्रभागसेनाकेघोड़ेहैं तिन्होंकरकेहिहोति
हैं २९ महर्षियोहे गर्गादिक सोइसकरकेसेनाकेअ
गोविषें घोड़िओंकोसलकहतेहैं येघोड़ेयिंविनाफौज
गिड़पड़तीहै जिसतराजड़केकटेहोयावृक्षसोपड़
ताहै ३० येऊराजेघोड़ेयोंकेउपरचढ़के युद्धकरतेहैं

उग्रंतेयपिमातंगाःभिन्नशैलेंद्रसंनिभाः
रुद्धेगतिर्निवार्येनपादरक्षैस्तुरंगमैः २९
तस्मात्ब्रुवात्प्रशंसंतिसेनागेभ्रमहर्षयः
अश्वैर्विहीनाःयास्तेछिन्नमूलाइवद्रु
माः ३० येऽस्याहूफाभूपनयोसमन्म-
हागजरथरत्ननिकरवरभटजनित
रुधिरजलनिधितरंगसंकुलमभि-
त्रवलजलधिमामथ्यतन्मथ्यादा-
विपालक्ष्मीमाहृत्यनिजभुजवश-
मानीयवेश्मभिवप्रणयिजनो-
पभोग्यांकुर्वंति ३१ श्रीरामराम-

सोभूपतिराजेशत्रुओंकीसेनारूपीसमुद्रकोंमथ
कर तिसविषेजोयत्नहैं तिसकोसत्तावीहरकेअपणी
याभुजाकेआधीनअपनेभोगनयोग्यकरलेतेहैं जैसे वे
श्याकामीपुरुषकोहावभावकरकेवसकरलेतीहै
कैसीवीवैरीयोंकीफौजरूपीसमुद्रहै तिसमेंवडे
वडेमदकरमत्तमस्तहाथिरथऔररत्न अरुवडे।
वडेयोधातिनोंकायोनिकलेआरुधिरसोइभया
समुद्रतिसकीयांयोलहरांहैन तिनांकरकेव्याकु
लयाहैशत्रुसेनासमुद्रतिसकोंमथकेचारओरते

पा॰ शत्रुवोंने रहित पृथ्वीके राज्यका देशका लाभ हो
हो॰ नेकरके प्राप्त होयाजो धर्म अर्थ कामना अरु जस के
५ सावी जस वेहुमा अरु फटक मणि अरु मोती तिना
कीमाई शुद्ध धनयो जस है तिसकरके त्रैलोकीको
5 हरणकरते हैं २१ अथ अशोभावणीपृथवीकेनटहू।
विकृत्सा जोघोड़े प्रेसे असवाराकरके युक्तहैं कैसे
सारे हैं धनुष प्राश बर्छी असि तरवार तोमर नरगा।
ला पट्टहैं इत्यादि विघ्न जिनोने सो प्रबल वाहकी नरा

अकंठकावनितलराज्यलाभादवाप्त
धर्मार्थकामाश्चइस्फटिकमणिप्र
काफलधवलयशसात्रिभुवनमा
हरयंति २१ येवाश्वायत्तुःप्राशासि
तोमरैरावेहरयिष्टिनालेप्रबलस
मीरइवप्रभृत्ससाद्रीकृतगंडमंड
लालयमधुपमधुरध्वनिसुखवि
नमहाविगजघटासघटितसक
टकाटिकाघनग्रंथितविकटाटो
पनटसत्राइस्सभटसमूहैकुन्त २२

बहुत मस्तान कीये हैं गंडकपोलोंका मंडल वि
स्तार तिनोंविषे स्थित मधुप भ्रमर तिनोंकी ध्वनि
मधुर शब्द तिसको सुनके शब्द करते हैं महान श
त्रुवोंकी हस्तीयोंकी घटा बदलरूपी सेना और
संदरणकट गंडकीयों चोटीयोंका मस्तानगंड
आहुआ तिसकाविकटयोआटोपशब्द जिस
में अरुफारे होए संयोए अरु जिरा जिनोंने अ
सेयो सुभटयो धर्योंके सारे समूह तिसतूं २२

© Dharmartha Trust J&K. Digitized by eGangotri

अनवरतकानिरंतर वारंवार छोडे जोबाण अरुण
घरनिर्मल हुआ रांयोयारांवर्षीविंडकोन्याई ति
नां करके ढकदीयाहै सूर्यकीयांकिरणांकेसमूह
काप्रसारका प्रकाशतिसने हनेराकरदीयाहै
दिशाअरुअकाशविषे १४ स्फुरनचमकदीसोदा
मनीविजली पंक्तिवनकरके तिसकरकेप्रका
शमान अरुवहुतशब्दकरतेहोयेतूं महानवडी
जोघनानारूपवदलसमूह तिसनूं १५ सोघोडे

अनवरतशुक्लावाणविमलसलि
लधारासहस्राच्छादितदिनकरक
रनिकरप्रसरांबरकारीकृतसकल
दिग्भोभागं १४ स्फुरनवहसौदा
मिनीलतांप्रद्योतितमतिगर्जितम
हारिपुनलदव्यूहं १५ तेचिराच्छृत
शः खंडखंडीकृतविघटितविग्रहादि
शादिशः पातयन्ति १६ तस्याश्वरका
श्रुतहृष्टविग्रहामहाविलक्ष्मीरणवा
समसाति हृष्टानना साधनिसादि
काभवेत्तरंगमायस्यवलेमहीपतेः
१७

यांकेअसवार तिनांनूं शत्रुसेनाकेयोधेयांको
टोटेटोटेकरके सेकडे शत्रावीदशादिशांविषेंछो
डकरसुटदेतेहैं १६ जिसराजाकीसेनाविषेंघो
डेहैन् तिसकोमहाशत्रुओंकीयोलक्ष्मीरणवा
सरणभूमिघरविषें प्रसन्नमुखहासीप्रमुख
जिसकासोमार्गमे तिसकोंप्राप्तकरणेवालीहो
नीभई कैसीभीहै तिसकीप्रीतिकरयुक्तहै अरु
सुनेयाश्रारदेखेयाहैदेहजिसकाश्रेसीयोरे १७

© Dharmartha Trust J&K. Digitized by eGangotri

रा॰
स्तो॰
९

घोडेयोंकीसेनाकास्वामिराजाहै सोइसपृथ्वीकूं
भोगताहै जैसेआपवरयाहोणवालीकामिनीस्त्रीको
नर पृथ्वीकैसीहै सभसमुद्रहै मेखलातडागीजि
सकीओरस्वरस्वरगंगाजीहै रोमावलिवालोंकीपं
क्ति तिसकरविभूषितशोभायमानहै ओरजोवडे
नउचेपर्वतकेशृंग सोईहैस्तनजिसके अरुजोश्रेष्ट
श्रनगरसोईहैश्रृंकार कोटरूपीहारतिसकरकेप्र.
कासमान अरुसंपूर्णशत्रुपतनरूपीदोषव्याधितिसे

संवेभोनितियमेखलांस्वरसरिद्रोमाव
लीभूषितांतुंगाद्रिपयोधरांपुरवर
श्रंकारहारोज्वलां निःशेषप्रतिपक्ष
दोषरहितांविद्वज्जनोद्यानतांपृथ्वीमा
वरकामिनीमिवविरेभुंक्तेश्वसेनापा
तिः १८ अश्वयोकेटापविलासदीर्घमा
र्गांतरीकृताः श्राम्यंतिमस्तकेवतिपूषि
णासंगमनेरयेः १९ भूषितस्ववभोड
श्वचामरैश्चापलंकृते आरूह्यवाजि
नेराजानाशयेद्रिपुसैनकं २० एनेवा
मोवराजस्यकरणगणाःसंतिसमं
स्थाना।

रहितयोंहै ओरविद्वानलोकसमूयोंहै सोईतिस्का
शवहै असीपृथ्वीकूंभोगताहै १८ येस्त्रीयोंकीव
हतप्रीतीवाले अरुहरदेशविषैगयेहोदवीसोघो
रेयोंकरकेप्यारियोंकेसंगमकेसुखकोंसनाथी
श्राभराशतेहैं १९ सर्वाणिकेभूषणोंकरकेभूषितश्च
रुचामरियोंकरकेशोभित असेघोडेऊपरचढकेरा
जाशत्रुकीसेनाकोंनाशकरताहै २० हेराजन् ए
हेओरगुणोंकेसमूहहैं इसलोकविषैघोडेयोंकेहै
स्थानगुणोंकरकेपुरूहैन तिनोंकासमरूदेवता।

© Dharmartha Trust J&K. Digitized by eGangotri

इंद्रके सहित सूर्य चंद्रमा थिले करके जानते हैं.
इसकारणते ये श्रेष्ठ गुणवाले घोडे हैं तिनो
के रोगके नाशका कारण ये चिकित्सा है इन घो
डेयों की चिकित्सा लाज श्रेष्ठ मुनि गर्ग सुतादि
योने करी यो योग सिद्ध ग्रहरोले घोडे इन्नों वाले
तिनां के के कहि है ५। इति शालिहोत्र गर्गकृत ग्र
च प्रशंसाध्यायः १ अब इसके उपरंत कहते हैं
घोडेयां को बडे भयानक रोग बढने होते हैं न सो

सर्वेषां वर्णगौर्याणां परितः सहिताः स्व
र्णवर्णाः द्रव्यश्च देवानानं मथेषा अ
वरगुणवता रोगनाशस्य हेतुः सिद्धैः
स्वल्पैश्च योगैर्मुनिवरगदितै यो हते
षां चिकित्सा ५। इति श्रीशालिहोत्र
गर्गकृत चिकित्सिते अश्वप्रशंसा प्र
थमोध्यायः १ अथैव गुणानां मेषां
मौचितो वृत्तिहेतवः व्याधयो वहवो
घोराः शांतिस्तेषां चिकित्सया १
सा चिकित्सा मुनिश्रेष्ठैः काश्यपा
दिभिर्यत्नतः नसशास्त्रस्य वाग
निश्रेष्ठैर्महर्षिभिः २

कैसे रोग हैं ये आयुर्वेद जानने वाले ये गुणी
वैद्य हैं तिनां की वृत्ति उपजीवका तिसके हेत।
कारण हैं न सो चिकित्सा करके शमन होते
हैं न १ हे राजन् सो चिकित्सा मुनियों।
ने कहि है शास्त्र तें जानी पलि है तिस शास्त्र के
अंग तिस शास्त्र के पाठ अंग महा ऋषियों·
अश्वशास्त्र के जानने वाले योनेक रहे हैं २

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ टी॰ ८

अरुउपंगनकीआठप्रकारकेकहेहैंतिन सोक्रमक
रिकेकहतेहो सोसुनो शल्यनाम व्रणकाछूहडी
इत्यादिनिकाशनेकायंत्र औरव्रणकानिश्चय
करणा कायचिकित्सानाम संपूर्णअंगोंविषे
होणवालेरोग ज्वररक्तपित्तादि उनाकाशमन
करणा शालक्यनाम ग्रीवाकेऊपरकेरोग
कर्णअक्षिनासाके तिन्होंकाहरणा किशोरक
चिकित्सानाम बालकीपालना औरमाताकेदुग्ध
दुग्धशुद्धकरना औरग्रहपीडाकीशांतिकरणी
विषतंत्रनाम सर्पवृश्चिकलूतादिशुद्धणेका।

उपांगानितथैवाष्टौ शृणुतानि यथा
क्रमं शल्यकायचिकित्साचतथा
शालक्यमेवच ३ किशोरकचिकि
त्साचविषतंत्रंतथैवच रसायनंभू
तविद्यावाजीकरणमेवच ८ अ
गानिषष्टिविजानीयादुपांगान्यथे
नाशृणु उत्पत्तिलक्षणंचैवइमा
नःकौतुकानिच ५

दोषजाननणा अरुविषकेहरनेका उपायकर
णा रसायणनाम आयुबुद्धिबलकरअरुअव
स्थास्थिरकरणी औररोगहरणा भूतविद्या।
नाम देवतादैत्ययक्षगंधर्वपितृपिशाचग्रह
इन्होंकरकेजोपीडितहोवै तिनोंकोशांति
बलिदानकरणा वाजीकरणनाम जिनों
कावीर्यथोडावाक्षीणहोगयाहोवै वाविकारी
होगयाहोवै तिसकावधाना एहुअष्टअंगआ
युर्वेदकेकहेहैं औरउपांगकहतेहो सोसुनो
उत्पत्तिस्थानलक्षणचिह्नउत्पातउपद्रवकौत
क ५

अथ लेखण अभिप्रचार कल्पसमर्थ अकल्पअस
मर्थ अतिदृष्ट सारणेवाला रोग पर इस शास्त्र के
विशेषकर उपांग कहे हैं न ६ पर बड़े विस्तार
वाला संपूर्ण शास्त्र दिव्य दृष्टीवाले देखा है सो मै
रैने से थोड़ी बुद्धिवाले कैसे जानने को समर्थ हो
नहि हो सकते ७ तिसकारणते तिनाका थोड़ा
थोड़ा लक्षण अरु थोड़ी थोड़ी चिकित्सा उपाय एवं

अथ आभिप्रचारस्य कल्पाकल्पमति
दृष्टं एतान्युपांगानि तस्य शास्त्र
स्य तत्वतः ६ सर्वमेतन्महाशास्त्रम
ल्पैरल्पबुद्धिभिः शक्यते नहि विज्ञा
तुं यद्दृष्टं दिव्यचक्षुषा ७ तस्माल्ल
क्षणमल्पाल्पं किंचिच्चिकित्सितं
दृष्ट्वा दृष्ट्वा विचार्यैतल्लिखितं एवं
शास्त्रतः ८ ब्रह्मणास्त्रमिवामोघेन
रोगामयविहिंसा विनाशायस्तु
न्हृष्टं एवं शास्त्रमहोदयैः ९ शा
लिहोत्रेण गर्गेण सुश्रुतेन च भाषि
ते नवंयद्वाजिशास्त्रस्य तत्त्ववेदिभि
इसीस्यत १०

शास्त्र आदि शास्त्र शालिहोत्र इत्यादिक तिनां
कों देख देख विचार के लिखे हैं न ८ जैसे एवं
शास्त्ररूपी समुद्र ते शालिहोत्र गर्गाचार्य सु
श्रुत इन्होंने निकासकर के योग कहे हैं न ब्रह्मा
स्त्र की न्याई जैसे कदापि कदी वी निष्फल नहि
होजाने वाले जैसे घोड़ियां के रोगरूप शत्रु तिनां
के नाश करणे वास्ते कहे हैं न सो सभ इन्हां घोड़ियां
के शास्त्र का बीज इस शास्त्र विषे स्थित किया है १०

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
८

8

अबघोड़ेयोंके सभलक्षणकहतेहां आवर्तवर्ण
कहिये रोमकावक्र रंगसत्वपराक्रम छायावा
णिचिह्नकोछुपाणिवाली गंधगति चालस्वर ११
शरीरपर अरघोड़ेयोंकेदेहमेंरहतेहैं तिनोंके
लक्षणआठप्रकारकेहैं न पकलक्षण सत्व हूस
रा वर्ण तीसरा गति चौथा स्वर पंचमा गंध छठं
मा छाया सतमी ११ आवर्तचक्रयिनकोभोर।

इहांनीलक्षणंछत्वेनंरंगाणांश्रवल
नेआवर्तवर्णसत्वानिछायागंधगति
स्वराः ११ शरीरंचवचाहतांनेषांलक्ष
णमष्टधा सत्वंततोद्वितीयंवर्णस्तृ
तीयंवर्णउच्यते १२ चतुर्थंतुगतिर्ज्ञेया
पंचमस्तुस्वरस्तथा गंधःषष्टस्तुविज्ञे
यश्छायाश्चैवतुसप्तमं १३ आवर्तस
श्मलेयपतलक्षणंतथा दश
लेषांदशाख्याताः तेसाणपिदशै
वहि १४ दशक्षेत्रविभागेलक्ष
णलक्षयहृदयः शीर्णावर्णीणमा
सोहोदिनानिह्रादशैवहि १५

मीयांकहतेहैं सोअबमाजानना इनोंलक्ष
णोंते प्रकृतिन्होंकीपांघोड़ियोंकीयांदशा
दशाकहियाहैन प्रकृतेत्रवीस्यानदशाहीक
हेहै १४ प्रकृदशाक्षेत्र इनोंकेजाननेवाला
वैद्यबुद्धिमानलक्षणघोड़ेयोंके देखलेवे
त्रयवर्ष प्रकृदोमहीने वारांदिन पहेदशा
कहिहै १५

© Dharmartha Trust J&K. Digitized by eGangotri

घोडेकीआयुषा बत्तीवर्षकहिहै तिनांकोपहे
घोकहिहै सोदशाहै घोआयुषादशमाहेसा
है सोयुनीयोनेदशाकहिहै १९ अबआदवि १
र्षे आवर्तचक्रोंकालक्षण कहताहों आवर्त
शुक्ति १ संघात २ शुकला ४ स्वबलीढकं ५
शतपादी ६ पादुकार्द्ध ७ पादुका ८ पहेचा।

द्वात्रिंशदायुषोवाजीनस्तैषाकथि
तादशा आयुषोदशमोभागोदशा
प्रोक्तामनीषिभिः १९ अथतावत्प्र
वक्ष्यामिसर्वमावर्तलक्षणं आवर्त :
शुक्तिसंघातंशुकुलास्वबलीढकं
शतपादीपादुकार्द्धंपादुकाचाष्ट
मीस्मृता आवर्ताकृतयस्त्वेताःप्र
द्वैसंपरिकीर्तिता १८ रूपमासां
विशेषेणपुनःकथितपुनरेद्युउ
लेस्वबलीढंस्यात्संघातंस्याहेमेउ
ले १९ शतपादीपादुकाशुक्तिस्व
यमपिपर्द्दगुलाः पादुकार्द्धंतु
लेप्रोक्तायुक्तलेनबर्द्धसंख्याने २०

मैंदनकीमाई घेरेवांगरस्वरूप अठआवर्तक
हेहैं १८ अबइनांकेस्वरूपफेरविशेषकरके
उत्तरनेतरविषेकहेहै स्वबलीढदोयअंगुलिप्र
माणकहाहै अरुसंघाअपिअंगुलप्रमाणहै १९
अरशतपादि पादुका शुक्ति पहे ३य ढेढेअंगु
लप्रमाणहै अरपादुकार्द्धएकअंगुलप्रमाणहै
सकलअर्थअंगुलकहीहै २०

© Dharmartha Trust J&K. Digitized by eGangotri

ज्या॰ हो॰ ५

१

आवर्तप्रमाणअंगुलीकानीसराहेसो एहेरनां
काप्रमाणकहिआहै तत्रतिनोंमेआवर्तप्रथा
नश्रेष्ठ अरुशक्तिकी शुभमाने ॥ घोडेयांकों
आवर्तत्रयप्रकारकेकहेहैंन एकध्रुव दूसरा
शुभ तीसराअशुभ तिनांविषेंध्रुवदश कहे।
हैंन अरुउनकेस्थानवीदशकहेहैंन ॥ ध्रुव

त्रिभंगांगुलमावर्तेमानमेषामिदं
स्मृतं तत्रप्रथानोह्यावर्तः शक्तिश्चा
पिशुभामता ॥ आवर्तास्तुरगाणां
ध्रुवाः शुभाश्चाशुभाश्चते त्रिविधाः
तेषांध्रुवादशमताः स्थानानिदशै
वकथितानि ॥ उरसिशिरसिच
द्वेद्वे रंध्रोपरंध्रयोर्द्वौद्वौ एकंल ला
टमध्ये विंघाटेकंप्रपानेच ॥ ए
वंध्रुवादशैतेस्थानेष्वयदशासं
ख्यमताः कथिताः एतेस्वस्थाना
स्थाः प्रदक्षिणावैशुभाः प्रशस्ता
स्तु १४

दशस्थानकहतेहैं छातिमें दो शिरविषेंदो
एककरे रंध्रछिद्रहोंगे मेंदोउपरंध्रविषेंदो
एकमध्यविषे एकघ्याण..... विषे ॥
इसप्रकारध्रुवदश दशोंस्थानोंविषेंवालों।
मेउत्पन्नहोएहुएकहेहैंन एहेयोकहेहैंसोअ
पणेस्थानविषे अरुप्रदक्षिणा सजेपासेआ
वर्तफरहोवे सोश्रेष्ठशुभफलवालाहै १४

इनांलक्षणोंकरकेरहित घोडायोगी आशुभा
वाला अरु पापलक्षणवाला निंदित होताहे अ
रुयो प्रमाणकहेआहे जिसते चूट अरु स्थानक
हेहैं इनांविषें नाहोवे अरुयोवीचसे छिन्नकटे
याहोवे सोवीहच्छे नहिकहे १५ जिसघोडेके
देहविषें उदयइत्यादिकस्थानोंविषें दशशुभ
नामवाले आवर्तप्रदक्षिणावर्तभौरली याहोवे
सोघोडानागजातिकहेया है शुभकराहे १६ औ

एतैर्विनान्येरगः सल्लक्षः पापलक्ष
णस्त्वशुभः हीनाः स्थानप्रशस्ताश्चिह्नि
न्नानप्रशस्यन्ते १५ उरस्योदशैतेषु
वाशावीरेप्रदक्षिणावर्ताः वसंतिय
स्यतुरगस्यनागजातिशुभप्रदःसो १६
अमेध्यसन्त्येरगस्यरोमनानाशुभा
शुभाः स्थानानितत्रवर्तिः षट्चनेहा
वर्तेषान्तस्मृते १७ त्रयोदशविनानी
याहेतेवैगतवस्मृताः द्विविधः संग्र
हस्तेषांप्रशस्तानिंदितस्तथा १८
स्थानानितेषांहस्थानिनिर्दिष्टानि
नुविंशति षट्समतिशुभानिपानि
इतिषट्सुवर्तिस्मृताः १९

इवी घोडेके रोमांके उत्पन्न आवर्त शुभफलवा
ले अरु निंद्यफलवाले स्थान उनांके छे आन्द
र हेन सो आवर्तसउको कहाहे १७ तिनांकेबीच
तेरांप्रकारकेआवर्त आनन्तकहेहैं तिनांका
दोप्रकारकासंग्रहकहाहे एकशुभफलवाले
अरुदूसरेनिंद्यफलवालेकहेहैं १८ तिनांके
बीचस्थानबीसएजायोय शुभफलवालेकहे
हैं औरछिहत्तरनिंद्यमाटेकहेहैन एहेस्थान
मेस्थानकहेहैं १९

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
१०

10

दोस्थान स्कर्णीस्वाखोंतिन्हों विषेंदोवालोंके
आवर्तघेरेकहेहेन १॰ मध्येविषे चारस्थानके
रकरै तिनोंविषेंवारोंआवर्तहै दोफेरावा
लायमनाम त्रयकरत्रेताग्निसेहै ३१ त्रयआ
वर्तघेरेयांकारकेनिश्रेणिनामकहाहै अरुवा
मेफेरांकारकेचक्रांगकनाम आवर्तहैं तिनांआ
वर्तोंकुवीचये ऋवेदकेवछकारमेंहै सोसभ
नोंसेश्रेष्ठस्नालायककहेहेन ११ एकस्थान
स्थानेहे स्कर्णीश्रोकेनयोहोरोमतो
स्तौ ३॰ ललाटेचैव वक्षनाभिस्थाना
निषुनरेवहि नेषपिहादशावर्तीया
मोत्रेताग्नयस्तथा ३१ त्रिभिर्निश्रेणि
कानाम चक्रीर्भिश्चाक्रांगकः आवर्ताः १२
हनिनामेषांपृथवीमध्येपवस्थितः
स्थानमेके स्कंधेनेयस्थाने हृकर्णी
मूलयोः स्थानेनिगालस्कंकेस्थाने
दैवंकेप्रकीर्तिते ११ स्थानेषुतेषया
वर्ताएवमावर्ताविभावयेत् केशांत
योम्स्थानेहनयोस्फिकिहृदयेंवि
३ः १४
स्कंधायान और दोकर्णीकेमूलविषेंस्थान
करैहेन एकस्थान दोयभुजाकेवीचमेंहै
एकगालविषेकहियाहै ११ इनांस्थानांवि
षेजोआवर्तभोरदीयांतिनाकेवुद्धिमानवै
द्यविचारलेवे केशांतकेपास आलके नि
गीचदोस्थानहैन तिनोंदोनोंविषेंस्फिकिसि
पीयाकेपासप्रकारजानों तिनांकोंभाग्य
करतेहैं १४ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

निसविषेंपंचफेरहैं ग्रोरवर्त्तिविषें ग्रावर्त्तहै सो
श्रीवत्सनामकरकेकहाहै ग्रोरवीदोयवखीवि
षेहैं वारग्रावर्त्तत्रयछोरकेकैपक्ककहेहैं ११ दो
नोंवाहोंविषें ग्रावर्त्तस्थानदोयजनैं होयस्थान ३
परप्रकृतिकेवक्षकार होयरोमवालोकेग्रावर्त्त
स्थितहैं १९ एहशुभस्थानजोवीसप्रकारकेकहे
हैं घोडेयोंकेरोम वालोंकेचिह्नोंके सततीसग्रस्था

ग्रोष्ठेलोवत्ससिप्रोक्तस्तावर्त्तैः पंचभि
र्भवेत् ग्रन्येद्वेवत्सस्थानेवत्तभि
क्षिभिरेवच ११ बाह्वोस्थानद्वयंप्रो
क्तंतत्रावर्त्तद्वयंविदुः द्वेचोपरध्र
यास्थाने द्वौस्थितौतत्ररोमजौ १९
एवंशुभानिस्थानानियान्युक्तानि
तुविंशतिः भवंतिरोमजास्तेषुस
प्तत्रिंशच्चसंख्यया १२ ग्रथखलक
टशंखमन्याशुपातोष्ठनासापुटके
पनानुसिक्किलिंगेंडुगंडेशुकर्णाग्र
कुतिस्थानाण्डकोशेषुवै १८

नयोकहेहैंन १२ इसकेउपरंतस्थानकहतेः
हैं कटशंखग्रहकर्णकेमध्यकास्थानहै
शाख कटक ग्रह ग्रवटेकेपासहै मन्यागल
कीनाडीयो मोढे ग्रह सिरकेवक्षकारहैं ग्र
स्कपानगरेकपालोंकेमध्यविषेंहैंन ओष्टदंतो
कोढकनेवालेहैं नासापुट नामकाकेछिद्रको
उपरलाभाग स्कंधमोडे जानुजंघ स्फिकपिंड गु
दाकेनलेदोनापासमेंहोतेहैं ग्रंडग्रंडकोशहैकु
णहैं गेरगलाहै कर्णाग्रकन्नाकाग्रग्रभाग कुक्ष
वसी [illegible] गोडेयोंकेहेठकास्थान मूत्रकोशमूत्रव
स्ति १८

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा·
हो·
॥

हृत्पुत्रवके अंदरविषेगलेकेतलेकास्थाननाडी
कहीहै जिसविषेदाडलगीयांहोरयांहै वटुक
स्फिकपिंडकेदोनोपासेमेंहै चिबुकयोअपर
केतलेहै पार्श्व पसलीयांहै वस्तनाभिकेदोनो
पासे पिंडीपासेतेहै जिसकोवस्तकहतेहै पार्श्व
पसलीयांहै गुह्यमूल डंबकाम्धरकास्थान भ्रुव
मध्य भ्रवेठकेमध्यमेंरनोस्थानोविषेश्रेष्ठवृद्धि
वालादेखलेवे २९ त्रिक देहकीयांकत्स ऊलि
लकरनोकीयांसंधियांइ तिसकोत्रिकचुडा
कहतेहैं गल मांडेकियांडीरनाकायोसंयोग·

हृद्वटुकचिबुककक्षपार्श्वेगुह्य
मूलेभ्रुवोर्मध्यभागःहृदयानामधे
शोभ्रवैनेष्वथहृत्पद्मंसंमतिलि
तथैव २९ त्रिकगलककुदन्तशी
र्षास्तनप्रोष्ठचोलाणामनाभीहृदि
कोउरसीमध्यमानेभ्रुवेकाकस्थे
कमेकेचिडवोनिनोरामजाः ३०·

स्थानहै कण्ठ कारी केर ग्रासन छातीकेउ
परयोद्गमहै सोजत्रुकहिहै उसके अरुकाडी
केपासहै प्रोष्ठ ओष्ठकेउपरकास्थान प्रपानका
हाहै उसके ऊपर प्रोष्ठनासाकेनिकटस्थान
है अरुप्रोष्ठकेविच चोलाणानामस्थानहै ना
भि नाभी हरि उदर कोउरस्थान उदर परके
अरुवत्सस्थलके मध्यविषेहै जिसकोछा
तीकहतेहै गदाकेरेठसीवनीकहिहै प्रा·
पानस्थल अरुकाकुसा जत्रुअरुककुद इ
नोकेमध्यकास्थानहै रनोस्थानोविषे पक
एकरोमकर प्रावनसनतनी कहेहैन ३१·

© Dharmartha Trust J&K. Digitized by eGangotri

औरवी मुखके उपर त्रय वालोंके विद्धस्थान
करेंन कृष्टिका स्कंधके ऊपरस्थानहै जिनोंको
मोने कहतेहैं कूर्च हृदयके पासकास्थानहै
जंघा तैसेहि कलाविषे अरु चारे स्कंधोंके वि
षै सोलानराके रोमांते होएदे विद्धकहेहै ४१
पट्टेसतनर प्रकारके आवर्तचक्र मुनियोंने यो
रेयोंको निषधकहेहैन १ना सभनोंकी गिन

उपरिवकस्थिताः प्रयानस्ववान्येत्र
योरोमजाः कृष्टिकाकूर्चजंघाच·
कलास्वपितथैवच वक्त्रेस्थेवणा
देषुषोडशास्थितरोमजाः ४१ ॥
निषद्वमस्मतिरशुभावर्तानांवाजिनां
मुनिप्रोक्ताः सर्वेषांपरिसंख्याशते
त्रयोविंशतिस्तैव ४२ अशुभाशुभा
शुभफलं स्वैरेवात्तरैः प्रभनार्थं·
लक्षणमावर्तानांपृथक्पृथक्लप्र·
वक्ष्यामि ४३ आवर्तोस्तकस्योष्ठ
लोः तायस्यवाजिनःस्यात्ता प्राप्नोति
मिष्टमत्रेभर्तापुत्रांश्चपौत्रांश्च ४४

नी एकसेत्रेयी कहिहैं ४२ अब आवर्तोंके
अशुभ अरु निष्ठफल और लक्षण थोडे अक्ष·
रोंकरके बहुत अर्थ जिनोंविषे सो सभनो
को भिन्न भिन्न करके कहताहों ४३ जिसघो
डेके त्लोठों ऊपर आवर्त वा भिपीया होवे.
तिसका स्वामी मधुरअन्न अरुपुत्रपोत्र इना
कोप्राप्तहोताहै ४४

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ हो॰ १२ जिसघोडेके मस्तकके विषें प्रदक्षिणावर्त्त सजे
13 पांस होरवाले आवर्त्तदोय होवें तिसका स्वार
शत्रूको जीतकरके अरु वैरीयांके सिरपर
चडकर स्थिर रहताहै ४५ जिसघोडेके मथ्य
के वीचमें त्रयफेरवाला निश्रेणीनाम आव
र्त्त होवे तिसघोडेकरके राजा जय लक्ष्मी अ
श्वनांकोलभताहै ४६ जिसघोडेके मथ्यमें दो घे

यस्यावर्त्तस्य भवेत्तां ललाटमौ द्वौ प्रद॰
क्षिणावर्त्तौ नृपस्वामी विजयी परि
हन्ति मूर्ध्नि शत्रूणाम् ४५ निःश्रेणी यस्य
भवेत् त्रिभिरावर्त्तैर्ललाटमध्ये तु रा
ज्ञा तेनाश्वेन तु लभते विजयं यत्नेन या
ने ४६ सन्नावर्त्तैर्वीजी वक्त्रे दिशसं
स्थिते ललाटे तु कुरुते स्वामिनमवि
रान्महीपतिं पुत्रवंतं च ४७ आव
र्त्तौ मुकुलो वास्तवप्रदेशे प्रदक्षि
णो यस्य नृपतेरगमस्य भवतो संग्रा
मे जयति रिपुसैन्यम् ४८

रेवा वारफेरवाले आवर्त्त भौरह्रीयां स्थित हो
वें सो घोडा अपणे स्वामीको थोडे दिन विषें
ही पृथ्वीका राजा अरु पुत्रवाला करदेताहै
४७ जिस घोडेके मथ्यके ऊपर स्तवख्यात
कहाहै तिसके विषें मुकल कलीकीतरां
आवर्त्त चक्र दक्षिणावर्त्त होवे तिसघोडेका
स्वार युद्धविषें वैरियांकी फौजको जीत
ताहै ४८

© Dharmartha Trust J&K. Digitized by eGangotri

घोड़ेके कर्णोंके मूल विषे होय वृषभ नामवा
ले चक्र स्थित होते हैं तिनोंका स्वामि संग्राम
में जयलभता है और भूषणोंके समूहको प्रा
प्त होता है ४९ जिसघोड़ेके निगालमें हृत्तु श्र
ङ्गलकीयां नाड़ियोंकी संधी स्थानको निगा
लकहते हैं तिसविषे यो आवर्त्तहै तिसको दे
वमणि कहते हैं सो है जिसको सो अपणे स्वामी
को सभप्रकारकीयां वासनाको देता है और देश

आवर्त्तौ वृषभाख्यौ तु यौ तुरगस्य कर्ण
मूलयो नाम्ना स्वामी विजयं लभते ल
कारनिकारांश्च ४९ आवर्त्तः स्याच्च निगा
ले देवमणिः सर्वकामदः स्वामिनो राष्ट्रस
न कोश संपन्नौ ख्याति ददाति विजयं
च ५० आवर्त्तौ हेम शुभान त्रिभकार्ये
ककुद्वंशुक्रा नजाइफोल्टपतिर्जय
ति रणे शत्रुसेनानि ५१ यस्योपरंध्र
भागे रोमावर्त्तः प्रजायते श्रीमान् ते
न स्वामी विजयी तिष्ठति रणे मूर्ध्नि।

भाषणा ५२

शत्रुकोश धन संपदा स्वर्ण विजय वैरीयोंनेप
रसमभे देता है ५० ककुद् काठीके ऊपर जिसवि
षे श्रसमाड़े लगे होय हैन तिसको छोड़करके प्र
ष्ठकेपासे विषे जो आवर्त्त है सो सभ शत्रुभे हैन
तिनोंको नाश करता है तिसके विषे बड़े हुआ।
राजा शत्रुओंकीयां सेनोंको शत्रुविषे जीतता
है ५१ जिसघोड़ेके कंठके वीच बालोंके फेर
वाले चक्र होय हैन वही सोभावाले तिसघो
ड़ेका स्वामी रणविषे जायको लभकरके शत्रु
ओंके सिरपर पादरखके स्थित होता है ५२

© Dharmartha Trust J&K. Digitized by eGangotri

शा. हो. १३

13

जिसघोडेके कंठविषे आवर्त्त वा अथवा शुक्तीसिका
प्रकर होवे प्रकाशमान तिस घोडेके करके राजाके
भंडार और मित्र वहुत वधतेहैं ५३ पूर्वका यो अ
र्द्धभाग तिसविषे प्रकाशमान जय आवर्त्तोंवाला
वक्रशिरविषे और पिछेके भागमें मेखली तड़ा
गीकीनरो वाल ऐसा आवर्त्त सभनां निंघ लक्ष
णोंको नाशकरताहै ५४ जिस घोडेके सिरके

आवर्त्तः कंठस्थः शुक्तिर्वा रोचमानः
स्यकः राजसेनाश्च नन्दकोशो मित्रा
णिवर्द्धते ५३ रोचमानस्तु पूर्वार्द्धे
निःश्रेणी शिरसि स्थिता पश्चार्द्धे मे
खलीसर्वान्शुभान्हंति रोमजान् ५४
केशान्तयोश्च शुक्ती द्वेन राजस्य पतेय
स्य नस्य स्वामी विजयी विवर्द्धते पुत्रपो
त्रैस्च ५५ आवर्त्तो वस्त्यश्चनस्तु पा
र्श्वेवनारः कंठे च रोचमानः सोश्व
श्रीवत्सकी नाम ५६ तेनाश्वेनारिपुसे
न्यं विजित्य निवर्त्तते राजा प्राप्नोत्यश्वो
सवहृतनाहृं सोऽश्वोयशश्च ५७

पास भालविषें दो सिपीयां होन जिनांको वागांके
हते हैं तिसका स्वामी जयको प्राप्त होता है और पु
त्रपोत्र वहुत वधते हैं तिसके ५५ जिसघोडे वस्त्य
ल गलके हेठ दोनोपासे चारचक्र और कंठविषे प्रका
शमान आवर्त्त सो घोडा श्रीवत्सकी नाम करके क
हाहै ५६ जिसघोडे करके राजा शत्रुकी सेनांको
जीतकर चल आवताहै और वडेपनको देशां
को लोकोंको जश इनोंको प्राप्त होता है ॥

५७

© Dharmartha Trust J&K. Digitized by eGangotri

जिस घोडेके वक्षस्थलविषे चार आवर्त फेरवाले
चिन्ह होवन तिसकास्वामी युद्धविषे जय ग्रहण करन और
निष्कंटक राजको लभदाहै ५८ जिसघोडेको व
स्तीकेविषे त्रय भौरउीया सिपीकी तरांहोवे सो
घोडा सभ वांछांके देणेवाला होताहै अरु तिस घो
डेकरके राजा वैरियोंको जीतकर स्वस्थचित्त होकर
अपने स्थानको मुडआवताहै ५९ जिसघोडेकी
बाहूओंविषे आवर्त भौरउीया अथवा सिपियांहोवन
तिसकानाम अंगदीकहाहै तिसकास्वामी स्वार रत

वक्षसि यस्यावर्ताश्चत्वारः स्युस्स वाजिनः
स्वामी प्राप्नोति रणे विजयं विनं निष्कं
टकं राज्य ५८ शुभो वक्षसि स्याय
स्य: सर्वकामद: सोश्व: तेन सौवि
जितारि: स्वस्थो विनिवर्तते राजा ५९
वाह्वोर्यस्यावर्तौ शुक्ती वा सोगदी ह।
य:प्रोक्त: प्राप्नोति तस्य भर्ता रत्नामाभर
णानि कं राज्य ६० आवर्तो रध्रोपरि य
स्यासावृद्धे मेखलीनाम तेनैश्वर्य्य
भर्ता: पुत्रै: पौत्रैश्च वर्द्धते राजा ६१
एते शुभा: प्रशस्ता सप्तत्रिंशानरोम
ताकथिता: ॰

मणीयां वा घोघे जिसजिस वस्तविषे श्रेष्ठ होवे
तिसकोंरत्न कहतेहैं और भूषण बहुत लभदाहै ६०
और जिसघोडेके छिद्रोंके नासांथी आदिले घो
विवरहै तिनोंके ऊपर आवर्त होवे तिसको छदं
मेखलीनामकर कहतेहैं तिस घोडेकरके तिस
कास्वामी राजा वडे ऐश्वर्य्य प्रताप और पुत्र पौत्रां
करके युक्त वधताहै ६१ इतने सतत्रीवालोंके
स्थान शुभकहेहैंन और ॥

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा॰
हो॰
१४

वीसस्थान निंद्यमाड़े कहतेहैं उनोंके फल इसके उ
परंत कहताहूं ९१ जिसघोड़ेके कंठोंविषे सोकटक
णी अरु पुरुशुंडियोंके मध्यहैं तिनोंविषे जोहोय आव
र्तेहैन सो तिस मालकके कुलको नाशकरतेहैन जि
सके शंख भुवटे अरु कूटके मध्यकहाहै तिसविषे वा
लोंके फेरहोवे सो तिसके स्वामीको सारे कुलका ना
यकरतेहैं ९१ शंख अरु कूटके ऊपर घोर कहेयाहै
जिसघोड़ेके घांटोंपे आवर्त होनोपासहोवे तो वडुभय
के देणेवाला कहेयाहै अरु भुवटेयोंविषे वालोंको

स्थानामेषां विंशतिरशुभानां फलमतो
वक्ष्ये ९१ आवर्तौ कर्णौ हृदयस्तनशुभौ भ
र्तुः कुलस्यांतकौ भर्तुः सर्वकुलक्षयंवक्
क्तः शंखोऽर्ध्वरोमजो ९२ आवर्तौ घाट
यो हृदयस्य भयदो ग्रमध्ये रोमजो मित्र
श्रीविद्धमध्ये नानसुतनाशानर्थदो स्वामि
नः ९४ आवर्तो हनुमध्यकुर्वगलस्थाः
स्फिचोकुक्षौ द्वाः यस्याष्टमस भर्तृर
धनिमस्वावात्तो वपाली भवेत् ९९ आवा
तौ हन्वो यनस्यकौ मन्यो इवो मस्त
दो भर्तुर्जीवितनाशनो तन्विवामस्कं
धोऽर्ध्वरोमजो ९६

आवर्तेहैन सो मित्रकेनाशकरताहै कर्णोंकु पिछ
लेपासे वडनामस्थानहैं तिन्होंकेमध्यविषे जो वि
रहैन सो तिसके स्वामीको निरंतरके उपद्रवके
देणवाले कहेहैन ९४ जिस घोड़ेके ठोडी गलना
ली और कुंचे हनुकेपास गल सोड़े पर कहे कुली
इनोंस्थानोविषे और वांणके आवर्तहोवे तिस घोड़े
के भर्ता मार्गविषे बहुतवायुकरके पीडितहोताहै ९
घोड़ेकी या ठोडीपर आवर्तहै सो पुनकेनाशकरणवाले
है मस्याविषे मस्तकहै अरु जे सोड़ेयां विषेहै सो
भर्ताके प्राणोंको धनादीनाश करतेहैन ९९

© Dharmartha Trust J&K. Digitized by eGangotri

जेरे अश्रुपातविषें गंडोंके मध्यमें अश्रुपातस्थान क
हेहै तिनोंविषे योहै आवर्त सो स्वामिको इष्ट दुःख
शोक भय देणेवाला जान स्फिक् पिंडी गुदाके हेठ
लेपासे कहेहैन तिनोंविषे यो वालोंके फेर है सो स्वा
मीके कुलका नाशकरणेवाले होनेहै जेरे रोमोकेच
क्र गलेके मध्यविषे जन्मेहोएहैन सो भर्त्तोको गल
रोग और अर्त्तीके दुःखकरके मृत्युकेदेणेवालेहैन
जेरे नेत्रोंविषे वालोंके चिह्न होएदेहैन सो अपने भ
र्त्ताको बंधन दुःख शोक भयके देणे वालेहैन ६७
जब घोडेके उपरले होठविषे आवर्तहोवे तबस्वामी

आवर्तौ इष्टदुःखशोकभयदौ विध्यश्रु
पातोद्भवौ स्यातां भर्तृकुलस्यनाशनकरौ
स्फिक्पिंडजौ रोमजौ आवर्तौगलम
ध्यजौगलगदार्त्तौदुःखमृत्युप्रदौ भर्तृ
बंधनदुःखशोकभयदौ नेत्रोद्भवौरो
मजौ ६७ आवर्तस्तूत्तरोष्ठे यदि भवति
हयो मातरं हंति भर्तुः प्रोथावर्तान्तरंगः स
कलकुलमसौ नाशयत्याशु भर्तुः कंठावा
र्तौ सरोघेः परिकरसहितं स्वामिनं हंति
शीघ्रं घोणावर्ती च भर्तुर्जनयति तुरगः
कश्मलं मृत्युमाशु ६८

कीमाताकूमारदेताहै नासकेपास होठके ऊ
पर प्रोथस्थानकहाहै तिसविषे रोमोके चक्रवा
लाघोडा अपने स्वामीके सारे कुलको सितावीना
शकरदेताहै नाभितत्रीके सज्जेखड्डे कंठस्थान
हैन तिनोंविषे यो आवर्तहै जिसघोडेको सो अप
णे स्वामीको वाणोंके समूहोंकरके परिवारसमेत स
ताकी नाशकरताहै अरु घोणास्थान अति और प्रो
थके वक्षकरमेहै तिसविषे आवर्तवालाघोडा भ
र्त्ताको कष्मलताभ अरुमरण सितावीकरताहै ६८

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
१५

ंडविषे आवर्तवाला घोडा स्वामीकों सेकडेके देणे
वालाहै और कालका हलकारा संदेसा देणेवालाहै
यो घोडा जानुवोंविषे आवर्तवाला है सो अपणे कु
लनं अरु स्वामीको वडे क्लेशयुक्त योसा करे है तिस
विषे रहतताहै और न्यायवहुतनकर वोर पाप शास्त्र
वायु अग्नि विषे भय इनके देणेवाला होताहै सो म
हा दोषवाला नामकहाहै ऐसा घोडा नवेलेविषे
नही वाडना अरु राजा तिसको सतावी राजथे वाहि
र निकासदेवे ८८ जिसघोडेके ककुद काठीपर वा

गंडावर्तीनंरंगो भयशातजननः स्वामिनोस्य
सहतो जानावर्तीन्नरगः नपयति स्वकुले
स्वामिनं नीत्रयोके प्रायश्चो गंशि स्वानुल
विषभयदः स्यान्महादोषसंतः शालायां
नाप्रवेश्यो नरपतिमविरान्नालयं मा सुरा
स्यात् ८९ आवर्तमथ कक्कुद्यवंते वि
यान्महादोषनमं सैोइं सपयवाजीसक
लस्यनस्सविनह्यो राज्यविनाशनस्य ते
नस्पृशो इंदहणं नपशेप देयहिजेभ्यः त्वा
विरान्मद्याव निष्कासयेद्दाप्यथजातं
मांइषीश्च सनेहापराहसमध्ये ९० स्याद्गा
सुनोयमतकाककसोइव लस्याथ भेदाम
इतनवाजिना।

लोंका आवर्त होवे तिसकों म
हाभयानक वडेदोषवाला जाने सो घोडा तिसका
होवे तिसकों कुलके सहित धनराज्य इनोंके नाश
करणेवालाहै ऐसे घोडेकों स्वामीके नाशकरणे वृ
लेकों छुपनाहि अरु देखवी नाहि अरु ब्राह्मणनों
भी नाही देवे अथवा जंगलदाही वाहर कडदेवे अथ
वा पापांके देशोके मध्यमें त्यागदेवे ९१ यत्तु अरु
ककुद छाति और काठीके मध्यका कसनामस्थानहै

© Dharmartha Trust J&K. Digitized by eGangotri

तिसविषें यो वालोंका आवर्त्त है तिसका भर्त्ता तिस
घोड़े साथ युद्धविषे मरता है सो सैकड़े काकों करके
भक्षण करीदा है कैसेवी काक हैंन येड़े वडे उच्चे भय
देणवाले शब्द करनेवाले हैंन तिनों करके ११ जिस
घोड़े कीये वक्षीयोंविषे रोमोंके आवर्त्त होवे तिसका
पति संबंधियोंके सहित सताबी नाश हो जाता है जै
सेग्रीष्म ऋतविषे सूर्यकी यों किरणों करके जल सु।
क जाता है १२ हृदय और वक्षस्थलके मध्यमें क्रोड
स्थान है अरु आसन मध्यस्थानके पास है क्रोडविषे

अन्ते हन्तः काकपक्षैस्तु भक्ष्यते उच्चैःरद्भि
र्वहूभैरवानुवान् १२ पार्श्वोर्ध्वे यस्य हि रो
मजो न भर्त्ता सपत्नः तुरगस्य तुस्य आशुत
संयाति यथा निदाघे स्वल्पं जलं भास्कर र।
श्मिजालेः १३ क्रोडरूढ आसन मध्यजो
वा स्याद्रोमजो यस्य तुरगमस्य स स्वामिनं
हन्ति विशाद्ववत्स मार्गे स्थितं राजकुलेण
वा १४ कर्णावर्त्ती भर्त्तुः कर्णच्छेदं वमूले
वा कुर्यान् हृदयावर्त्ती हृद्रोगशोकं बंध
नं मरणं १५ उपरिस्थित प्रयाणो प्रदत्ति।
णे स्थस्य दो मजो यस्य ।

अथवा आसन विषें जिस घोड़े के वालों के चक्र होवे
सो घोड़ा अपणे स्वामनको रस्ते विषे राजकुलविषे ।
युद्धविषें स्थित होएको शताबी निश्चय करके मार
ता है १४ यो घोड़ा कर्णों विषे आवर्त्त वाला है सो भ
तीके कंनाको कटाता है अथवा कर्णमूल रोग वा
कर्णपीड़ा करे है ये घोड़ा हृदयविषे आवर्त्ती वाला
है सो हृद्रोग शोक बंधन मरण स्वामीको देनाकर
के करता है १५ जिस घोड़े के प्रयाणके ऊपर गोडके
उपर प्रयाणस्थान है तिसविषें प्रदक्षणावर्त्त से जो
पास चक्र होवे ॥

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ सोपतिके पिताको नाशकरैहै जेकर खेटपासे होवे त
टी॰ व भ्राताका नाशकरताहै १६ योप्रपानके मध्यविषें
१९ स्थितहोवे तो स्वामिस्वारको नाशकरताहै यहे त्रय।
प्रपाणविषें स्थित आवर्त्तेकहेहैन जिसघोडेके नासा
पुटोंविषें वक्रहै सो स्वामिके धनकानाश निश्चय
करके करताहै १८ जिनाघोडेयाके सीवनी गुदाकेह
ट और कतिविषें अथवा गुदाविषें आवर्त्तेहोन सो स्वा
मिका कतिरोग करतेहैं और भर्त्ताको कदीवी सुखन
हीं देणेवाले कहेहैन १९ जिसघोडेके मूत्रकोशवि

भर्त्तुः पितरं हन्याद्भ्रातरं वयेवासमभागेव १६
स्वामिनमथमध्येस्यात्त्रयंप्रपाणोपरिस्थि
ताश्चेते नासापुटे यो भर्त्तुर्वित्तविधातभृव
कृते १७ आवर्त्तासीवन्यायेषांकृतावथा
नेदेशवा तेकतिव्याधिकाभर्त्तुर्नेसुखाव
हाः कथिताः १८ हृष्येतेयस्य हृयस्य सो म॰
तौ पुच्छमूलसंज्ञातौ भर्त्तारंस्वसमघातयोवा
णहतो मंत्रजेतप्राणान् १९ भर्त्तुर्दारांहृ
न्ति रोमजौ यस्य मूत्रकोशस्थो मुष्कोऽडवी
तविघातेष्टस्तनश्चौनवागुणौः २० नाभ्यां
यस्यावर्त्तौ लक्ष्यन्तु भर्त्तारं विरंसुसंज्ञातः रोगे
जलोदराद्यैःपीडयेत नाशमेदेहः २१

षें दो रोमोंके वक्रहोवे सो भर्त्ताकी यास्त्रीयांको
हरणकरताहै अरु जिसघोडेके हृकणों अ
र्ध ऊपर आवर्त्तहोन सो ज्येष्ठपुत्र वडेपुत्रके मार
णेवालाजानो और तिसका आयुवी कमहोती।
है २० जिसकी नाभीपर वक्रहोवे तिसका स्वा
मी संतानोंदे साथ जलोदर इत्यादिक रोगोंकरके
चिरकाल पीडाकरयुक्त होतेहैन इसमेंकुछ स
न्सानाही २१

16

© Dharmartha Trust J&K. Digitized by eGangotri

जिसका त्रिकके ऊपर आवर्त्त है तिसका स्वामी तिस घो
डेके सहित युद्धविषे प्राणोंको त्यागता है गोडेके हृदय।
स्थानस्थान कहा है तिसके विषे आवर्त्तवाला स्वारके
साथ सो घोडा शस्त्र साथ मरता है ८२ जिस घोडेके
कुक्षिका संधोंकी संधीस्थानविषे आवर्त्त जिनोंको।
नैरंत कहते हैं सो होवे तिस घोडेका स्वामी बडे
शोककरके बहुत दुःखी होता है ८३ प्रसाद मेल कमल
वज्र तोरण धनुष खड्ग शंख वेदका स्वस्तिकासर्वतो
भद्र मत्स्य हर्णी भरियादा कलश श्रीवृक्षक सदृश

त्रिकजो यस्यावर्त्तः सहभर्त्ता सौ रणेम्रिये
त्प्राणान स्यरावर्त्ती शस्त्रेण वध्यते स्वामिने
वसहाश्वः ८२ यस्याश्वस्यावर्त्ताः संभूताः
कुक्षिकासु हयेषते भर्त्तान स्वामिसैनः सदा
रुग्णैः पीड्यतेत्यर्थैः ८३ प्रासादाब्जनवज्र
तोरणाधनुर्निस्त्रिंशशंखोयस्मा वेदीस्वस्ति
कमत्स्यहर्णीकलशः श्रीवृक्षकसन्निभः
लक्ष्याष्टापदवज्रलांगलगदावेष्टार्करूपा
कृतिः प्रावर्त्तो यवतोरणादिसवरः सह
जित्वा जिनः ८४ गेहे यस्य निर्जिता रि
लोरिपुः स्थ्रीपतिर्जायते निश्रेणी सपवा
सरत्नाकरयेनाम्निशुक्रागदी खड्गांकुशा
वामरध्वजरथास्वत्तपत्राकृतिः सुश्रीमान्स
भरः सदाशुभफलोपमोजेयः श्रीफलः ८५
अष्टपद वज्र हल गदा वेष्टमा सूर्यरूप संभ रनोंकोलंग
आवर्त्त हह तोरण इत्यादिक चिन्ह होवे जिना घोडियों
का ऐसे घोडे जिसके घर होवे सो पूजायोग्य है अरु
सबके देणेवाला है सो सब शत्रुओंको जीतकर्के पृथ्
वीका स्वामी राजा होता है ८४ निश्रेणी यव आवर्त्त हो
वे तो निश्रेनाम है सभ संदर रत्नका संग्रह यव अग्नि अ
कुश तोन वर्णके वहाट खड्ग अंकुश चौरी धजा रथ व ब
ऐसे जब चिन्ह होवे सो श्रीमान् शोभावाला अरु सदा ही १
शुभ करे है श्रेष्ठफल धर्म जय श्रेष्ठकार्यकर होता है ८

शा॰ हो॰ १२

17

जिसघोडेके वक्षस्थलविषे आवर्त होवे अथवा और म
थेविषे जिसका स्वामी वैरियोंको जीतकरके युद्धविषे
सो पृथ्वीको चिरकालभोगताहै सो देवापक कहाहै
राजाको सुख यश देश देणेवालाहै ८६ शालिहोत्रेण
कहाहै येइनिश्चकरके चिन्ह सत्व वर्ण प्रभा शोभा प
ह समभवालोंकरके होते हैं नक्षत्रके प्रभाके फलकाउ
दयहै और गतिकावेग और देह पहसमभकालके फ
लहैन और समभवाकीकेक्षेत्र जिसके विषे होते हैं न

आवर्तस्तथयस्यवक्षसिभवेदन्योललाटे
थवा भर्त्तातस्यरिपुंविजित्यसमरेयुद्धेकेवि
रंमेदिनी देवापः समुदाहृतोनरपतेः सा
ख्यार्थराष्ट्रप्रदः ८९ उक्तंचशालिहोत्रेण
योप्युवक्षभवेत्तुकः सत्ववर्णप्रभास्तथा
तेयास्तेगमनामंतिनेत्रभावफलोदयाः
गतिस्वरशरीराणिसर्वकालफलानित
शेषाक्षेत्राणिसोरणानत्रतत्रफलंविदुः ९०
इतिश्रीशालिहोत्रगणाकृतेचिकित्सिते
आवर्ताध्यायः २ सर्वाचार्यकृतेशा
स्त्रसंग्रहागमसत्तमे आवर्तलक्षणंप्रोक्तं
सर्वांगानांप्रवक्ष्यते १ निर्मांसंहिवदनं
नेत्रनुसंखरस्नायनेसहते नेगतस्त्रमहा
ललाटनयनेमध्येसुगंधप्रभं गंभीरतनु

हेतिसतिसका फलमाणो ९० इतिश्रीशालिहोत्र
गणाकृते चिकितेभाषायां आवर्ताध्यायः २ ॥
सर्वाचार्यगणोंकृतं शास्त्रादि तिन्हां करके बनायेहु
ये योशास्त्रग्रंथ तिन्होंने निकासके श्रेष्ठ आयुर्वेद जो
इयोंका जिसने आवर्तचिन्हकहेहैं अब सारे अंगों
के चिन्हकरतेहैं १ मांसरहित सुंदर अनल अरु को
मल सरल गिरट सुख जिसका अरु ऊंचाहै और सुं
दर विस्तारवाला मथा और नेत्र और मध्यमें सुंदर
सुगंध शुभअंगभीर इगोलेवा जिसन्न और ।

© Dharmartha Trust J&K. Digitized by eGangotri

बहुत विस्तारवाला लालरंगवाला तालू जिसका
और जीभ कमलके पत्रकी न्याई कोमल सूक्ष्म स्निग्ध
सम सहजा योग्य है और दंत बराबर गिरदृष्टि है अरु
अदरलेपासके उच्च सुंदर चैन और चिट्टे रंगवाले हुए
पड़े ठोडेयांके श्रेष्ठक है हैन २ ओठकी संधि श्रेष्ठ और
स्तना जिह्वाका हेठला स्थान है जीभ ओष्ठ मध्य पड़
पंचस्थान कोमल और सरल सदाही घोड़ेको श्रेष्ठ करे
हैं ४ घोड़ेकीयां अखीयां फटक मणी र मालती के फु

ले रवेमायतनम हृन्मणानालाकं शुभे जिह्वाप
अदलोपमामद्रुतनवुश्रवणासममाहजिता २
दमनानलसमा हृनासस्निग्धाभ्यंतरोनतुः स
घ्राणोन्तमपुवर्णौभाः स्थिराप्रशस्ताःतुरंगा
णां ३ सक्कोष्ठावथ सूनानिह्वा ओष्ठश्चपंचवा
मेवशं पतानिमहदनिमदानग्निरागास्पश
स्तानिकथितानि ४ नेत्रेशस्तेहयानांस्फटि
कमणिनिभे मल्लिकपुष्पवर्णौ स्निग्धेशुभेवि
शालेद्रुतकनकनिभेजातिवैदूर्यवर्णे ५
णोष्ठ क्रौंचवर्हसहिपनयननिभेरिष्टिनीलो
वनाभे उन्नाने निवेलीकेसममथविपुले
मांसहीनेललाटे ५ हृस्वोनतवनीला ग्राव
रोमसावलिनाशुभाकर्णौ ॥

लके सम वर्णवालियां अरु थिंदे सुंदर विस्तारवाले
और गालेहोपसनेके रंगके सम और जाति वैदूर्यम
णिके बराबर रंगवाले और हरण ऊठ कुंजपक्षी है
म हाथी टिटिणीपक्षी इनोंके नेत्रोंके तुल्य शोभा
वाले ऐसे नेत्र होवे और मस्तक ललार उन्नावलीयां
करडीयां ने रहित बराबर और विस्तारवाला थोडे
मांसवाला ऐसा होवे ५ और कर्ण जिसके छोटे स
म अग्रने त्रिरेखावालीकरके रहित सरल सुंदर
ऐसे केनहोन ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ और मस्तक जिसका हाथीके कुंभके अर्द्धभागके और
हो॰ सीके स्तनकी शोभावाला शुभश्रेष्ठ कहा है ६ प
१८ हैयोएवं मेकहेयोगुणहैं तिनांकरके युक्त घोडेयों
का मुख श्रेष्ठ कहा है जिसघोडेके मोंढे पुष्टहोवें
18 और कर्णोंका पिछला पासा गिरदहोवे और मध्यवि
षे अच्छी तरां पुष्ट होवे ऊंचा मोटा और खिंचेया हुवा
मस्तहोवे और काठी वडे विस्तारवाली लंबी एहे ल
क्षण घोडेके शुभ कहे हैं ७ जिसघोडेकी ग्रीवा

गजकुंभार्द्धभस्त्रीकुचोपमो मस्तकः शुभः ॥ ८
एतैः सर्वगुणैः समन्वितमिदं शस्तं मुखं वा
जिनां स्कंधे सुपीनाव विशालौ मध्ये च पु
ष्टव समुच्छ्रितौ च पीनानताकुंचितमस्तका
च ग्रीवा सुदीर्घा नरगस्य शस्ताः ७ कुक्कुटाहि
भोगप्रतिमा समुद्धृता शक्राधुपा भा शिखि
संनिभा वा ग्रीवा भवेद्यस्य स राजवाहनः सु
ग्रीवनामा तुरगोत्तमः शुभः ८ उपचितमांसः
पीनः स्थूलोच्छ्रितः शस्यते स्फिरस्कंधः स्कंधोर
स्थलौ पीनौ वक्षः पीनं सुविस्तीर्णं ९ हृन्नेसु
ता क्रोडे वा ह्रस्वो दीर्घो ह्रस्वः समो पीनो हृन्नेति
मांसलाः स्नी निरर्थकाः स सुविशिष्ट १०

कायी जैसे कुपित होया सर्पका देह ऊंचा होया दा होवे
और जैसे इंद्रका धनुष चित्रित होवे अथवा मोरके सम
शोभा होवे ऐसी जिसकी होवे सो राजाका वाहन सु
ग्रीवनाम करके घोडेयों विषे उत्तम श्रेष्ठ कहा है अरु
शुभ करा है ८ अरु स्कंध मोंढे वधे होया मांस सहित वि
स्तारवाले ऊंचे दृढ हल्के होते हैं ऐसे फेर विस्तार
वाले अरु मोटे होते तो श्रेष्ठ कहे हैं और वक्षस्थल पुष्ट
अरु चौडा होवे ९ क्रोड हृदय वक्षस्थलके मध्य है
सो गिरद अरु चिकना अरु भरा लंबोया गिरद सरल
बराबर मोटिया श्रेष्ठ हैं नाजु गिरद थोडे मांस वा
ले शुभ श्रेष्ठ कहे हैं १०

© Dharmartha Trust J&K. Digitized by eGangotri

होरेयांके शास्त्रमानने वालियोंने जंघांवरीयों उत्ती
या शुभकहिये नकुंवृष्यान जंघाकेतले वरोमा
सेहैं सोनिपुर गमनाडीवाले ग्रहतवा जोरवी प्रा
रतहिहोन नोशुभहै ॥ कुष्टिका संवका संधीस्या
नहै सेछोटे ग्रह गिरदकेनेलगेहोए पेसेशुभजान
ने और संब छोटे चुगिरद ग्रह मिलेहुए खोनेके सं
व बांपुर स्नतवर्ण उत्तेश्रेष्ठहैन मंहूकीपादतलवि
षेंकहिहैं सोजिसकेपुटीदीनाहोवे हलोके ग्रह वि
वरवेद शुभकहेहैन पादतलकामध्य हृगा साफ

जेघेसमाहितेवेन्तुरंगमाणामिहावाजैः नि
गूढशिरावथक्रुद्धैस्त्वचौनिशूढसंधीव ॥
हूसवृहनेश्लिष्टसमाहितेकुष्टिकेशुभेजेघ
हूसाहूनास्त्रुतुरा ग्रवलीदकः खरल्हराकाराः
वहलाःसमुन्नताःस्रनेस्फुरिताहूस्वमध्यमूढ
काः नलमध्यस्थगंभीराःशस्ताहूस्वकवर्णा
श्च ॥१२ ॥ हृहनिमग्नंवशहूसहृस्वकिविदायत १२
शस्तं पार्श्वदीर्घवृत्तेस्थुवृत्तेवहनुदरंव ॥१४
स्थूलवृत्तेहूसंमहाशुलवमेहनशस्तं वृत्तोहू
साव समावलोमसोस्निताहृषणौ ॥१५ जंघे
नवृत्तेसमहृद्वृत्तासनस्थुत्रिकेशस्तं जघने
मंसवृत्तेमहृद्वालेशास्पते ॥१६

एकरंगवाला श्रेष्ठकहाहै ॥१२ पिंडनिसकी वाहूपकेवि
चवरीहोए हृगी छोटी मुटी कमककवोरी ग्रेमी श्रेष्ठ
करोहैं और वेतीया लेवीयांते गिरदश्रेष्ठहै वत्तस्थल
और उदर स्थल ग्रह गिरदश्रेष्ठहै ॥१४ लिंग मोटा गिर
द छोटा ग्रह वरेमस्तवाला ग्रकाकहियाहे हूकए
ओर गिरद छोटे बराबर वालो विना फुलेदशुभहे ॥१५
जघन त्रिकके हेठहै गिरदवडे विस्तारवाले ग्रह
त्रिक वकेश पतलाश्रेष्ठहै जघनोंविषे हृविहोहे
गिरदकोमलवालोवालातुंव श्रेष्ठकहाहे ॥१६

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ गुदाविकनी हूणी गिरद फ़राखी नहिंहैन ऐसी हड्डी
हो॰ कहिहै स्फिकिंकहिं गुदा आसपासके हैठेलपासे हैन
१९ सोमारे हुए छुटेहुए गिरद श्रेष्ठहैन १७ पटोंकेमध्य
योस्थानहै सोछिद्ररहित उपोइयोहै सो नल्य अ
ह्ककरेड़लेरहै सक्थिनी उपांगोविषे वंधनकरीहोर
सोचोड़ेकी सरल अरुभरीयांहोयां गिरद श्रेष्ठहै १८
स्थूर और नेथांनेलेकर योअंग हवे अगलेपासके करे
न तैसेही बुद्धिमान पिछलेपासकेवी विचारलेवे यो
डेके १९ जिना घोरियोंके वडेवयेहोवें वल शरीरको

सत्तामयानेगालेनंगभीरंसेहनेवलिविहीनं
स्फिकिंशेसपीनोसहिनौवहेनौ १७ समां
शालोडवेनरमछिद्रविकटाउपाडदेशौन
सन्नौपरिहतौचसक्थिनीहनेनिमेशले १८
स्थेसनेत्राघाश्चावयवाः पूर्वशरीरेयथासशुदि
ष्टाः पश्चिमकायेपितथाविलक्षयेद्दाजिनांप्रा
नः १९ उपचितवलशोभाः सत्वसारेरूपेताः
सरभिक्षमसंगायाः शालमेचोह्यनादाः वहुवि
धशुभवर्णाः मेहनोगाः सरूपाः शुभगतिजव
युक्तावाजिनः सनेत्राः २० भद्राः कफप्रकृता
थः सकलप्रसन्नाः स्थूलास्थमस्तैवरणाजाश्च जि
तेन्द्रियश्च हसेरवंडचवरणोः कठिनमेहदि

शोभापराक्रम और धातुवल तिनोंकरकेयुक्तहैं अरु
सुंदरसुगंधिवाले योहैन और शाल अरु वदलोंकीना
ईशब्दहिणकनेतिनोंरा ऐसेयोहै और अनेककनरोंके
श्रेष्ठरंगवाले और सफेदन छुटेहुयेअंग और सुंदरउदा
रंगवाले और श्रेष्ठगतीयोंवाले वेगकरयुक्त श्रेष्ठवा
जो नाती सुंदर शलोयिनोंदीयां २० सोभद्राकल्याण
रूपवाले कफस्वभाववाले अरुश्रेष्ठकुलविषेजन्मेहों
य स्तरवीर और अपणेस्वामीकेवसयोहै जिनाने इ
न्द्रियांजीतीयांहोरयां ऐसे नोहे अरुजिनोंके सव॰

19

© Dharmartha Trust J&K. Digitized by eGangotri

छोटे अरु दूरे नहिंतें करके वडे विस्तारवाले होन जि
नाके तेजवाले सुंदर वलवाले अरु यथास्थानकर
प्रगट अंगावाले ११ अरु सम छोटे होवें अरु कोश
कर्ण लिंग पेर जिनोदे अरु विस्तारवाले होवें जंघां
मुख भुजा पासे जिनोके और थिंदे चिकने हैन दंद
सावर्ण नेत्र जिनोके और मास विना उचा विस्तार
वाला वहुत उचा मस्था जिनोदा ११ सुंदर विकटले
वे हैन उंपाउ जिनोके पीठवाले और आगे ते वहुत
उचा है मुहार आगा जिनोदा अरु मास रहित है यो

स्नेहस्विनः सवलिनश्च विभक्तगात्राः ११
ह्रस्वोरुकर्णाः समपेशपादाः सुदीर्घनेत्रान
नवाहुपार्श्वाः सुस्निग्धदन्ताः सावर्णनेत्राः
निर्मांसनेगायतनेगवक्त्राः ११ सुपाडुदेश
विकटाः सुदीर्घामनस्विनश्चोच्छ्रितपृष्ठका
याः निर्मांसघोणास्तनुजानुजंघा विस्तीर्ण
वक्षोजघनासनाश्च १२ वाहाः सुरूपाः शुभ
नामनोज्ञाः विभक्तदेहापविनोगमांसाः ह्र
स्वाः स्वहाभारसहाः सुसमवा आवर्तेषु दाश्च सुद
गपार्श्वाः १४ स्त्रियाणि मांसानि घनानि ये
षां भवंशां सुदृढानि वोल्वलानि कायेविभ
क्तोपचितानि संतिने वाजिनः श्रेष्ठतमाः प्रश
स्ताः १५

एनाइन जानु जंघां जिनोकी पां विस्तार
वाले हैं वक्षस्थल जघन आसन स्थान जिनोके ११
येउं वोढे सुंदर रूप सुंदर वाला मनको प्रियकर
चालियांवाले अरु देह जिनोके अंग भिन्न २ प्रतीत
होने हैं अरु वडे वंपहों मासवाले और पूछ शिखा आ
दि जिनोके सहारनेवाले आहृ पराक्रमवाले और अह
यो आवर्तन चक्र हैं तिनोकरके शुद्ध जो हैन अरु सुंद
र गव अंतर हे तिनके समर वक्षस्थान जिनोके १४ जि
नाके मांस चिकने अरु घने सुटे होय हैन और विकार
रहित जो हैन अरु देह विषे विभाग करके व पे होय

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
१०

20

योहैन जिनाके ऐसे घोडे बहुत श्रेष्ट और शुभफलके
करणेवाले कहे हैन २५ जिनां घोडेयांके मोटे अरु
विस्तारवाले हैन पीठ जघन वक्षस्थल स्कंध मध्ये उद
र नेत्र और ठुडी ने रहित यो हैन और कोमल पतले
केश सिरके वाल देहके रोम और वाल ऐसे या घोडे हैं
सो बहुत श्रेष्ट कहे हैन २६ जिस घोडे के देह विषे इ
सतेंल लक्षण चिन्ह होन सो देववाहन कहे या है ऐ
से घोडे को प्राप्त होके राजा सभ शत्रु प्रोते रहित स
हर्ण पृथिवी को शासना करता है २७ इतने लक्षणों

पृथुपृष्ठजघनवक्षः स्कंधललाटोदरेक्षणा
बलिनः सूक्ष्मतनुकेशतनूरुहवालाश्च हयाः
प्रशस्ते २५ पंचविंशत्प्रशरीरलक्षणभ
वेन्नंगस्य सदेववाहनः तं प्राप्यनिःशेषसप
त्नवर्जितो प्रशास्ति कृत्स्नां नृपतिर्वसुंधरां २
पतेल्लक्षणानि वसंति यत्र तत्राग्निरुक्शास्त्र
भयानि नूनं न सांप्रयो नाशुपसर्गदोषा
स्तस्माच्चरेद्दैः सततं प्रहृष्टाः २८ इति श्रीशा
लिहोत्रगणकृतचिकित्सिते सर्वांगपरी॰
क्षानामाध्यायः १ सर्वांगलक्षणप्रोक्तेन
रंगाणां विशेषतः मेदवृद्धिर्प्रवीपार्थ्यमिश्र
के श्रेष्ठनेत्रना १ श्वेतः श्वेतसफः सिता
सितवदनः श्वेतांडमेढ्रस्तथा ।

वाले घोडे न होग रहित हैन नहां अग्निभय रोग शत्रु
भय नहीं होते और सभ प्रकारके रोग संघाग्न दोष
को ईवी नहीं होते तिसकारणते राजयोंने ऐसे घोडे
निरंतर सदारी एवा योग करे हैन २८ इति श्री शालि
होत्र॰ सर्वांगपरीक्षा॰ध्यायः १ घोडेयांके भिन्न १ स
भ रंगोंके लक्षण कहे सब घोडे वृद्धिवालेके जे
णने वास्ते रंगे मिले लक्षण अब कहने हैं १ जिसका
रंग श्वेत अरु संव श्वेत अली मध्या अंडकोष लिंग॰

© Dharmartha Trust J&K. Digitized by eGangotri

विटेहोवे अरु चमडा सिरकेबाल गुदा पुट्ठेश्वेत होवें
अरु सिंह हाथी शब्द इनोंकीसार्ईस्वर सभअजनोंकेके
इयत अरु श्रेष्ठचालवाला शुभहै सभअंगतिन्हांवाला
सुंदरकांति और सुंदरआवर्तोंकके युक्त ऐसाघोडा जि
सदे विषवसे तिसकोबहुतसुखदेणवालाकहेयाहै २
तिसराजाके घोडोंकी सेना हतहोईकी वाकीयोरहीहै
सोडरीहोई नसजातीहै अरु तिसराजाको कार्य काम
ना धनप्राप्तहोनेहैं अरुसंग्रामविषैभीजयहोतीहै ३
तिसघोडेनू सारेधन सभइच्छाकेसाथवीलैलेवे तिसक

श्वेतश्च क्लिन्नकेसरः सितगुदः सिंहेभशंखस्व
रः सर्वैजनैरपूजितः शुभगतिसंस्थानवान्सु
प्रभः आवर्तैश्च शुभैः हयस्तनिवसेद्गृहेयस्मा
त्स्वस्वदः २ राज्ञस्तस्याविलेहतशेषकापिना
निविष्टेन नशार्थकामसंपत्सग्रामेनसंविज
यस्मात् ३ तेनरहुस्तीयान्तरंगसर्वेस्वनापियत्ना
थैः अजिन्मल्लनमरेद्रः इष्टशीनिष्ठकोरोभेम् ५
नवरेश्वेतः शुभान्क्रकेशोश्वेतोददातिवानंद यो
षायांवाविपनसौभाग्यवैविक्रेद्यात् ४ वी
मेपार्श्वविनेद्याद्रथदक्षिणेधनंदागात् सो
ख्यवन्तमिद्यात्स्वेतःपृष्टेसुखेवजय ५ कणी
यस्यसितोसफाश्चनयनेशोणास्यक्रूसासवा सो
ग्यः सर्वसुखप्रदोनरपतेःसौभाग्यसंपत्करः -

कैसताना किसीसे जीत्यानहीजाता अरु इष्टवीवैरियोंते
रहितभोगेगा ४ जिसके जठरविषैश्वेतचिन्हहोवे सो
स्वामीको वहुतपुत्रदेताहै जिसकी छातीश्वेतहोवे सो
सुखदेताहै जिसकीकाछीश्वेतहोवे सोलक्ष्मीदेताहै
जिसकेत्रिकविषैहोवे सोसौभाग्यदेताहै ५ जबखवेपासे
होवे तोविलयनदेताहै सज्जेपासेका धन और स्त्रीयां
देताहै वत्तीमें होवेतो सुखदेताहै पृष्ठविषै अरु सुख
मेंजयकरताहै ६ कर्णी जिसकेश्वेत और संवविटे अ
तीलाल वा कालियां जिसकीयां सो घोडाराजाको स
भसुखके और सुंदरभाग्यकेसंपदाकोदेणवालाहै

© Dharmartha Trust J&K. Digitized by eGangotri

भा० हो० २१ यो घोडा लालरंगवाला और चिंदा और बहुत श्रेष्ठ लक्ष
णोंकरके युक्त ऐसे लक्षणोंवाले घोडेको यो राजा लभ
ताहै तिसकौ रणविषै जय और बहुत सुख वत्र धन
पे सम बहुत होते हैं ७ यो घोडा पके हूए नाम एके
रंग और स्यामवर्ण बदलके सब प्रभा सुसकी यो ऐसे
घोडेके ऊपर पृष्ठ समे बढता है निश्चय करके सब जीव
तिस राजाके सदा वस होते हैं ७ जिस घोडेके आठ स्थान
स्वेत होन बक्षस्थान ईव सिर मुख सब बार ऐसे घोडेको
अष्टमंगल अरु हिनकर जाणे सो भनोंको सदा यश देश

स्निग्धं रक्तमनीवलक्षणयुतं यो घोटकः प्राप्नुया
त् तस्मान्नो विजयः सुखं च परमं वित्तप्रभूतं भवेत्
सपक्वं नेयाभमरिष्ट सन्निभं यो स्वं समारोहति पृ
ष्ठ काले भूतानि सर्वाण्यपि तस्य नूनं भवंति वश्या
नि सदा नृपस्य ७ अष्टौ सितानि यस्य भवंति वाजि
नो वक्षःस्थलं पुच्छ शिरो मुखं सफाः विद्यात्तं तं हि
तं मष्टमंगलं भवेद्यशोराष्ट्र सुखप्रदं सदा ८ नी
लैश्च रक्तैः सितैश्च पीतैः कृष्णैश्च मिश्रैस्त्वथवा
विचित्रैः यो मंडले भूषित सर्वकायः स्वामिनो व
जयी कोष्यमुख्यः ९ पर्याणमध्यः सुतपुण्यदर्श
नीयात्तः सदा तु मकर्तव्य साधनः यस्मिन्सदेशे नि
वसंति रोगास्त्वग्निक्षता स भयं न जायते १० यः प
तिनहो वस्त्रीमध्ये स्वितयेन शुक्रुपदेन सत्रुं हीना
मासा प्रमर्दनः शत्रुसमानां ११ सुखदेता है ८ यो
घोडा नील लाल चित्र पीले काले रले मिले अथवा बहुत
वर्णोंके मंडलोंकरके शोभायमान सारदेह जिसका सो अप
णे स्वामीकी जय करणेको प्रधान है ९ सो पर्ह घोडा यत्न
है अरु पवित्र दर्शनवाला है अरु राजाको सदैव कालमें
कल्याणकर और अर्थ धनादिकोंका साधन है जिस देश
विषे ऐसे घोडे रहते हैं तहां अग्निकी पीडा और शत्रुको
भय नहीं होता है १० यो घोडा समय विषे चिकना अरु ख
न बालोंके पटलकरके युक्त है सो मत्रुहनामा है सो पर्ह व
री यों की सेना को मथन करनेवाला है ११

© Dharmartha Trust J&K. Digitized by eGangotri

ये काला रंगवाला घोड़ा अरु श्वेत कारमें लालवर्णके
पट्टकरके युक्त है सो वी सन्नद्ध नाम अश्व है यापहलेका
फलकहियाहै सोई इसकाबी है ११ जो घोड़ा काला अ
थवा लाल रंगका है अरु श्वेतवर्णके जठरकरके अथ
वा वक्त्रकरके युक्त है सो घोड़ा वैनयिक नाम कहाहै सो
यम है अरु संपूर्ण अर्थकी सिद्धी करणेवाला है १२ यो
घोड़ा काला अथवा लाल अरु रक्तवर्णके उदर वा व
क्त्रकरके युक्त है उसी फलको स्वामीके ताई देता है यो
पूर्वकहिआहै १४ यो घोड़ा श्वेतवर्णके चिन्हकरके व

यः कृष्णः परिनद्धः स्यात् श्वेतो हि तेन पट्टेन स
न्नद्धः सोपि हयः सर्वाभीष्टफलदस्य ११ यः कृष्ण
शोणो वा सितेन जठरेण वक्त्रेण वापि वैनयिकः
सततं वा नीयते सर्वार्थसिद्धिकरः १२ कालो वा
रक्तो वा उदरेण रक्तेन वक्त्रेण वापि फलमनदेव
भर्त्रे ददाति यस्मै व प्रदिष्टः १४ कृष्णायसितेन
हस्तिरंगमो वक्त्रसासितेनैव सर्वातिनामा सो
विजयार्थं नरपतिना प्रयतः कार्यसमेत्यस्य १६
ग्रीवे ग्राम्यो वशिरः सकृष्णवर्णपाण्डुरं भवेद्यस्य स
र्वार्थकामदो सो हयः शिरः श्यावतोनाम १७ श्वेत
स्यास्य सशिरः श्वेततरं यस्य लक्षणो स्त्रियं भर्त्रे
सर्वार्थकरः समर्थकान्तः समाख्यातः १८ येह
स्वमंडले स्वर्थैर्वा चित्रे विभक्तनेत्रास्तु

तस्थलकरिविधि होवे सो सर्वातिनाम करके है सो राजा
सेनाकरके एवं हि विजयका अर्थरूप कार्य करके हाहै १६
जिसघोड़ेका सिर नेत्रापर्यंत अरु कर्णसमेत श्वेत पी
तपांडुरवर्णका होवे सो घोड़ा सभ मनों विषे मुख्य श्याव
तनामक हाहै सो सभ अर्थ पन कामनांके देणेवाला
है १७ जिस रंगके घोड़ेका सिर बहुत श्वेत अरु स्त्रिय
होवे सो समर्थकान्तनाम प्रगटकहियाहै सो अपणेस्वा
मीके संपूर्ण अर्थकार्य करेहै १८ ये घोड़ा छोटे
छोटे मंडलों करके अथवा चित्रों करके विभक्त भिन्न नेत्रों
वाले हैन ।

© Dharmartha Trust J&K. Digitized by eGangotri

शा.
हो.
२२

सोनागजातिनामकूहेहैन अरुशत्रूकी सेनाकोमर्द
नमथन करनेवालेहै १९ योकाल रंगकाघोडाहै
अरुश्वेतहै वह मस्तक सब सिरकेबाल अरुपीठ
जिसकी सोज्योतिष्मान्नामहै सोधर्महै स्वामीकोसं १.
हर्षसिद्धी अरुधनोंवाले पृथ्वीके राजदेनेवालाहै
जिसघोडेके सब रोमांकर्केफके होवेहोन सोआह्ला
दकीर्तिनामहै सोस्वामीको थोडेहीकाल ऐश्वर्य
अरुपुत्रपौत्राकोदेताहै २१ जिसघोडेकेसब विंदहो
वे अरुमस्थकेसहित मुखश्वेतहोवे सोघोडापंचभद्रहै

पंचैसनामहैनासेविंतेयानागजातीया १९ कृ
सोश्वेतवर्णासितवदनशफःश्वेतकेशाति
हृष्टः ज्योतिष्मान्नामधर्मःसकलवसुमतीरा
ज्यदःस्वामिनोसौ २० आह्लादकीर्तिःकथितो
रोमभिःरानादितैरवैवीजी भवेरविराणदघा
द्विभवपुत्रास्वपौत्रास्त्र २१ सितस्य यस्यवाजिनः
शफःसमस्तकस्ववं संपंचभद्रकोभवेन्नृपस्य
गृहसौख्यदः २२ एकोपियस्यवर्मिःसविंदुस
श्वभःस्थिरोश्वस्य प्रभोनितस्यरुवीमहहावे:
श्रियराज्ञा २३ नाभिसमादायन्तरंगमुख्यवा
लाकवर्णोयदिहवेमहं स्यात्सश्रिमाठहरि
णाकवर्णोशरीरसमद्युतिसपुतस्य २४ सबा
मिनोगृहविवर्द्धनोश्वोभवेद्धिवाचेनयिको
वराश्वः

जिसकोपंचकल्यानकहतेहैं सोराजा
कोदेशकामुखदेनेवालाहै जिसघोडेकारंगएकहि
होवे अरुमुंहरक्तिमय ओरश्रेष्ठकांतिहोवे तिसकोसो
भीराजा निर्द्वंद्व दोषरहित वहुतलक्ष्मीको प्राप्तहोता
है २३ जिसघोडेका अगलापासा नाभीतक प्रातका.
लकेसूर्यकेसमवर्णहोवे अरुपिछलाभाग हरणा
क चंद्रमाकेतुल्यहोवे ओर देह पराक्रमकांति ३।
नांकेपकहोवे २४ सोघोडाशुभलीको देशकीवृद्धी
करणेवालाहै योअश्वकापछलाभाग चंद्रमाके।

22

© Dharmartha Trust J&K. Digitized by eGangotri

नसुरंगवालाहोवे अरुपिछेकाहिस्सा सवेतकेसूर्य्य
समहोवे सो घोडियोंकेविषेश्रेष्ट वैजयकनामहै २५
जिसघोडेकादेह पराक्रमकांति इत्यादिलक्षण होवें
सोनिशावैजयिकनामघोडाहै सोराजाकोदेशायस
अर्थ धन सुंदरभागय कुलकीवृद्धि येदेदेणेवालाक
हिआहै २सीतरंग कालाघोडा ओर श्वेतदेहहै अर्द्धभा
गजिसका सो ऐसानितमहिश्रेष्टहै २७ जिसघोडेके
पैर सफेदचिह्नहै अरुनिश्चयो आवर्तचक्रहोवें अरु

शशांकवर्णोयदिदृश्यवेमंडेवालाकेवर्णोयदि
पश्चिमार्द्धे २५ शरीरसंबंधुतिसखुतस्सान्त्रा
त्वानिशावैजयिकःसवाजी शत्रुःसदाराष्ट्रय
शोर्थसंपत्सौभाग्यरोगोत्रविवर्द्धनस्स पंचक
कृसाहरयस्वनितंसुक्रार्द्धकायाश्चरगाःप्र
शस्ताः २६ सितपादसुरोर्यस्तुआवर्तेकलि
तेरपि षट्‌पदाभोभवेघस्त्रकुसतास्वतषाद्‌ः २
शत्रुश्रियंतेपिविवर्द्धयंतिरणेगताःशत्रुजये
वक्रपृः असितशफःसितैकचरणोनशुभस्त
रंगः अहितकोन्लपसवलजीवतनाशकरः २८
चरणचतुष्टयसितंहितयंत्वथवाभवतितस्स
समस्तेरथसलवदस्तरगस्तुसदाविजयी ३०
त्रिष्टयुस्सिलत्तुसितस्तुःसिमहांसितत्रिसिवुदी
ऐहितिकथितः

जोअसमरकीयांभावलाहोवे ओरकाले
होनताले ओरवारेपरजिनोदे २८ ऐसे घोडेवेरीयोंकी
लक्ष्मीकों वधातेहैं ओर रणविषेशत्रुकी जयकों करते
है जिसके संवकालेहोवें अरुएकश्वेतहोवे सोशुभ।
करनहिंहै सोराजाकोवेरीकरहै ओर सेना अरुप्राण इ
नकेनाशकरनेवालाहै २९ जिसके चारसंवश्वेतहोन
अथवा दोसंवश्वेतहोन सो अपनेस्वामिके सदाहीका
र्यकेसवविजयकेकरणेवालाघोडाकहियाहै ३० जि
के ययस्थानमोटेहोवे अरुचयछोटेहोन त्रयकोमल·

© Dharmartha Trust J&K. Digitized by eGangotri

शा०
हो०
२३

अरु त्रय बडे विशाल और सूक्ष्म त्रय लंबे होन सो सभधारी
र शुभ श्रेष्ठ कहा है सो घोड़ा सुखेराश्य ऐश्वर्य का करने हा
है २१ घोडेके वक्षस्थल अरु मथा जघन २२ विशालवा
ले श्रेष्ठ जाणे अरु पिठ कर्ण कुष्टिका एहे त्रय छोटे शु
भ कहे हैन २३ वाल रोम आला एहे त्रय कोमल श्रेष्ठ २२
जाणे और मुख नेत्र शिर एह घोडेके बडे श्रेष्ठ कहे हैन
और जीभ खोंखा एहे त्रय सूक्ष्म श्रेष्ठ कहा हैन घोडेया
के काडी जंघा मुख एहे त्रय लंबे शुभ जाणे २४ घोडे

स्तनसमेषां रीते शुभप्रवराश्वरागः सुखेराश्यवि
भूतिकरः २१ वक्षो ललाटं जघनं हयानां त्रीणि
प्रशस्तानि पृथूनि विद्यात् पृष्ठं च कर्णौ च कृक
टिका च ह्रस्वानि वै त्रीणि शुभानि विद्यात् २२ वा
लाश्च रोमाणि च केसरं च त्रीणि प्रशस्तानि मृदूनि
विद्यात् आस्यं च नेत्रं च शिरो हयानां त्रीणि प्रशस्ता
नि महान्ति विद्यात् २३ औष्ठौ च जिह्वा च खरश्च कि
णौ च त्रीणि प्रशस्तानि तनूनि विद्यात् ग्रीवा च जं
घे वदनं हयानां त्रीण्येव दीर्घाणि शुभानि विद्या
त् २४ शशांकचन्द्रहिमाभा हंसमुक्ताफलाभा कु
न्दकनकसुवर्णाः पद्मकिंजल्कवर्णाः अभिनव
कुसुमाभाः किंशुकाभाः शुकाभाः विकचकुव :
लयाभाः इन्द्रनीलाग्रभाभाः भृंगाभाः कोकिलाभा
सजलजलधरालिप्सिभिन्नांजनाभाः ।

और वे हिमा बरफ इनके समप्रभावाले हंस और मोतीयों
के दाने तुल्य प्रभावर्णवाले और ये शुद्ध होवें सुव
र्णके वर्णवारंग और ये कमलकी पांखरीयां के समव
र्ण और नवीन पोकुसुमकोडानिसके तुल्य पलास
के फूलके रंग सम तोते के समवर्ण और फूले होए
कमल के सम रंग और इंद्रनील मणिके समवर्ण
और भ्रमर कोकिला के समवर्ण और सजल मेघ और
निन्हों के सम और कटे होए सुरमे के समवर्णवाले

© Dharmartha Trust J&K. Digitized by eGangotri

और प्रातकालके सूर्यके अशोकपुष्पके गुच्छेसम और
फूलेहोए कमलके सम और लाक्षारसके तुल्य वर्ण
वालेयेहेन २९ हे राजन् इसप्रकारके येघोडेहेन सो
देशके धारणवाले हेन् जिनकियां दीर्घ लंबी ग्रीवा
अरु पार्श्ववल्लीयां बडे विस्तारवाले नेत्र लक मोटे वृत्त
स्थूलमस्तक जिनांदे २७ जिन घोडेके छोटे हैं पिठ अरु
कोश कर्ण अरु कराडे और हुने स्नव और थोडे मासवाली
यांलवीयां जंघा और सूक्ष्म हैं त्वचा रोम अरुवाल औरको

वालाकाशोकपुष्पस्तवकरक्तकिसलयभोजला
क्षारसाभाः २९ इत्थंभूताः नरेंद्रान्यपवरगदिता
राष्ट्रधारास्तुवाहाः दीर्घग्रीवाः सुपार्श्वाः पृथुन
यनकटिस्कंधवत्तोललाटाः २७ ह्रस्वपृष्ठाण्डक
र्णाः कठिनघनखुरादीर्घनिर्मांसजंघाः सूक्ष्म
त्वग्रोमवाला मृदुतनुरसनाघ्रोथसत्कोष्ठकेशाः
शुद्धावर्ताः सुरूपाः घनसितदशनाः स्वप्रभाः सु
ष्टसत्वाः येषां पीठं विधास्ते नयनमनोनंद
नाः स्निग्धवर्णाः मंगल्याः भूपतीनां सकलवसु
मतीराष्ट्ररत्नप्रदास्ते २८ हेमाभाः शोणवर्णा
स्तुहिनगिरिनिभाः कोकिलाकज्जलाभा येवा
हाराश्ववाहाजितपवनजवातीक्ष्णवारांमसु
गाः ॥

मल और सूक्ष्म हैं जिह्वा ओष्ठ स्कंध और बाल
और श्रेष्ठ हैं आवर्तचक्र और सुंदर रूपवाले होने और
श्वेत हैं दंत और श्रेष्ठ प्रभा अरु सत्ववाले ये हैं औरवी
इसतरांके हैं प्रकृष्ठोंके नेत्र अरु मनको आनंददे
णेवाला अरु चिकनेरंगवाले ऐसे घोडे राजेयांको
संपूर्ण रिद्धियोंवाली पृथिवी देश रत्न इनाकेदेणे
वालेहैं २८ येघोडे सुवर्णकी प्रभावाले अरु रुधिर
समवर्ण हिमालेके सम और कोकिलाकी प्रभावा
ले कज्जलके रंगके औरयेहे राजवाहा हैं जिनाने
जीतेयाहै वायुकावेग अरु तीक्ष्ण हैं गलाका •

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ समुद्रजिनोंने हे राजन् तिनोंके संग्रामविषे वीरोंकरके
टी॰ भोगनेयोग्यजो लक्ष्मीहै सो सदाजलशायी हरिकावृ
२४ क्षस्थलको अरुसमुद्रकी क्रीडाको छोडकर वास
करतीहै ४९ येड मेघवदल और भ्रमर कोकिलाके कं
24 ठकेसमरंगवाले हैं और फुलेहोए नाषके और चंद्रमा
की किरणकेसम गंगाजलके हिमालेकी न्याईयोहै औ
रयोप्रातकालके सूर्यकी किरणोंकेसम लाल और लाक्षा
केरसकेसम गोरोचनकेसम कांतीवाले स्वर्णकेरंगका

नेषांराजनलुराये निवसतिकमलासर्वदावीरभो
ग्याः सक्ताक्रीडसमुद्रंजलशयनहरेः पीनवक्ष
स्थलस्था ४९ जलधर भृंगाभकोकिलागलनि
भविकसितकुमुदेंदुकेकरः गंगाजलनहिमगि
प्र॰ रिभंतरुणदिवाकरकिरणांके लाक्षारसरोचन
द्युतिकनककांतिऊरुराजनराजवाहनं ५० ब
हुभीतिकरमनोवसकरंवर्णप्रभाभासुरं खाव
नेत्रनपीनबाहुयुगलं सारंगसिंहेक्षणं पिंडेमध्य
रितंवदष्टविततमानप्रमाणोन्नतं सर्वांगेषु स
मल्लक्षणयुतं जस्विवेगाधिकं ५१ सच्छाय
समनोज्ञगंधसलिलंगंभीरहेषान्वितं ॥

औसेजोघोडे हे राजन् वाहनकरनेवालेरख ५० हे राज
न् घोडेऔसेवाढनेवालेरखे कैसे योनेत्रोंको देखनेक
कैप्रीतिकरे अरुमनकोवसकरे अरुवर्णकांतिशोभा
करयुक्तहै अरुसुंदरमुखवर्तीवाला अरुचने और मुंह
हैदोयबाहु जिसके अरुसारसऔरसिंहकेतुल्यहीणा
करनजिसका पिंडुरोपतल्ल अरुपीठ बडेविलासवाली
जिसकी ऊंचाईमेप्रमाणसे बहुतऊंचा सब अंगोंवि
षैयो सगुणलक्षणकहेहैं सो सभधारेहोएहै अरुते
जवाला बहुतवेगवाला ५१ और सुंदरछायावाला
अरुमनकोजानेवाला और जलकी सुगंधिकरयुक्त
बहुतगंभीर हिणकनजिसका और संनद्धवद्धहै

© Dharmartha Trust J&K. Digitized by eGangotri

ऐसा उपवाहन होता है इंद्र कर मंगल के देणेवाला और
धर्म अर्थ कामना के देणेवाला है ४२ यो चोड़ा स्वर्ण
के सम वर्णवाला है सो स्वामी को कल्याण कर है यो च
न्द्रमा के तुल्य है सो वैरीयों का नाश करता है जो अलसी
के फूल के रंगवाला है सो जय के देणेवाला है यो पाटलव
र्ण है सो भंडार पुत्र स्त्रीयों की वृद्धि को करता है ४३ ते
सैहि योलाची के सम प्रभावाला है सो स्वामी नूं जय दे
ता है यो सारस कमल वा पत्नी के तुल्य आभवाला भया

सत्राघे वोपवाह्यं च मांगल्यारोहणे हयं ४२
शक्रराजेंद्र त्रिवर्गफलदायकं ४२ ग्रथ्यक
नक निभस्त्वंगः श्रियं वा स्वतस्यापि कुर्यात्
शशांकोपमः शत्रुनाशं तथैवातसी पुष्पव
र्णो जयं पाटलः कोशवृद्धिं सुतांस्त्रैव दारान्
४३ तथैलासवर्णस्तु भर्तुर्जयं सारसाभः
परमार्थसिद्धिं च कुर्यात् रणे वाजीनो रोम
कस्याथ सारस्यभर्तुर्भवेद्दीर्घमायुर्जयं श्री
कृतश्च ४४ क्रौंचपत्रेण कर्केण वे कुर्वते
नापि राजा रणे शत्रुपक्षं जयेत् नालपुष्को
त्पेषाश्चैव पुच्छं शिरो लोचने मेहने श्वेतवर्णे
च स्वामिनस्त्वेवमेतद्दुलेभे ४५ वर्णेनैलत्वण
कीर्तिनेरसमपरमशोभने वर्णेनैलत्वणवसते

को श्रेष्ठ अर्थ अरु सिद्धी को कर्ता है रण विषे जय अरु ।
स्वामी को निरोग कर है बल को सेनापति कर्ता है तिसके
स्वामी की आयु वृद्धि होती है अरु जय स्वभाव कही होती है ४४
क्रौंचपक्षी के पक्ष सम वर्ण कर्क कर्के कुकडु वर्णवाले के
के राजा वैरीयों के पक्ष को जीतदा है ये है घोड़े नालपुष्प
सन्तुं व सिर नेत्र लिंग श्वेतवर्णवाले हैं ते से अपणे भ
र्ताको ऐसे दुःख कर्के लभते है ४५ यहे श्रेष्ठ शुभ वर्ण
का लक्षण कहा है अब अशुभ वर्णों के लक्षण कहते हैं ।

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ हो॰ १५ 25

भस्मलोहाकेरंगवाला सोनेके अंगारकेवर्णवाले काक
केनालूकेसमवर्ण गिद्दड कबूतर काकरेनाके समवर्ण
वालेघोडे और काउकी तुंजबागुरवर्ण और धूएंरंगवाले
अथवाउल्लू इनकेसमरंगवाले असेघोडेहूं छेनहिंक
हूं यहस्वामीको रोगकर और संबधियोंकानाशकर्ताहै ४ ८
येघोडे श्वेत पाटल गौरवर्णकेहैं अरुनाल नेत्र अरु संब
कालेवालोंकरके युक्तहोवे असेघोडे जिसकेघरविषेंस्थित
रहैं तिसका खजान और देश नाशहोतेहैं ४९ जिसश्वेतव

भस्मवर्णाखरांगारवर्णाधोन्नतालवर्णाः पृशृगा
लोपमाःकपोताभकाकाभुवर्णाह्याः काकनें
डोपमाःपुत्रवर्णाह्कोलूकवर्णाश्चयत्र अश्वा।
स्तामुनारोगदाभर्तुरेनेसुहृज्ज्ञासनाः ४८ शुक्ले
वर्णाश्चयेपाटलायेचगोराहयाःकृष्णतालवत्ति
शुक्लाःपुराश्चैवबालेस्मकृस्पर्द्देहेयस्यतिष्ठंति
वैत्तीयनेतनस्यकोशश्चराष्ट्रंच ४९ पट्टेनरक्तेन
कालेनवाश्वेतवर्णास्ययस्यमध्येभवेयस्यनद्दं
रक्तरंगस्य सस्वामिंनघातयमाहवेयस्यमध्येरक्त
कालेनपट्टेननहोभवेसोपिवाजीरणेस्वामिंन
घातयमेव ५० इतिश्रीशालिहोत्रगणाहृतवि
किंस्मितेवर्णशुभाशुभाध्यायः ४ अथनागा
सस्त्रियेनपुष्पनलतणलक्षते विंदवोयेम
वर्णाह्यस्यास्यवर्णेनसपुष्पसंज्ञास्मृवे॰

णकेघोडेकालालरंगका अथवा कालेरंगकेपट्टेकरके
मध्यदेयनयुक्तहोवे सो अपनेभर्त्ताको रणविषेंमरावे
ताहै अरु जिसकाकालेपट्टेकरके वपनकीयांमलक
होवे सोघोडा अपनेस्वामीको निश्चयकर युद्धविषेंमरा
वताहै ५० इतिश्रीशा॰गा॰वि॰ वर्णशुभाशुभाध्यायः ४
अबघोडेकेयेफलहै तिन्हकेलक्षणकहतेहैं जिसघो
डेकायेवर्णहै तिसकेइसीरंगकेबाल होय विंदुजन्मेहोवे

© Dharmartha Trust J&K. Digitized by eGangotri

तिनोंको शुभ करा फल करते हैं यो एकवस्थान जिसके
हेठ फल होए तो स्वामीको राज्यका लाभ करता है मध्य
के धनका लाभ करता है त्रिकाल कंठके हेठके अन्नपा
नका एवं कंनविषे पुत्रकी प्राप्ति अरु स्तनके विषे
फल होए तो मित्रोंको वधाते हैं और वक्षी विषे मोडे के पु.
न को देते हैं नाभिस्थानके निश्चयकर सेनापति करते हैं
जब मूत्रकोषों विषे होवे तो घोडेके स्वामीको पुत्रकी
उत्पत्ति होती है पत्तोंमे होवे तो अपणे पत्तके लोकोंकी

पुच्छिते राज्यलाभो ललाटेत्र विनं निगालेत्र
पानं तथा वामकर्णे स्तनौ तालिरर्थं वामे त
रे पुच्छिते मित्रवृद्धिः तथा वक्षसि स्कंधदेशोप
नं नाभिदेशेन सेनाधिपत्यं ध्रुवं मूत्रकोशे स
तो मतिरश्वस्य भर्त्रे भवेन्मूत्रयोः पत्रवृद्धिवि
दोस्थि क्रिणोरत्रपानं तथार्भयोर्वित्तलाभं प
रां निवृत्ति कंठदेशे स्तनांश्चैव दारा स्कंधे पान
योर्मित्रवृद्धिं सदा गुह्यकयोर्स्तयोः पुत्रलाभाश्च
न्त्वर्थसिद्धिं हृयाः पुच्छितात् स्वामिनां संप्रक
वंति सर्वांगजातेस्तु पुष्पैः सिते वाजिनां स्वनि
नां: सर्वकर्मार्थदा एवमेतानि पुष्पाणि सर्वे शु
वर्णेषु शुक्लेषु शुक्लानि पीतेषु पीतानि शस्ता
निवे ।

वृद्धि होती है विंदों मे अरु स्वालों विषे
होवे तो अन्नपान बहुत प्राप्त करता है रंध्रों विषे फल ध
नका लाभ करता है और कंठके पुष्प पुत्रकोस्त्री याको
बहुत सुख करते है कंधां तो विषे फल मित्रकी वृद्धि कर
ते हैं अरु अंडों विषे अरु अंशों मे होवे तो सदा ही पुत्रके
लाभको करता है अरु सारे देह विषे पुष्प होवे तब भली
को वार अर्थ धर्म अर्थ काम मोक्ष करता है और सफेद
अंगोंके फल कल्याणकारे हैं अरु सारे देह विषे श्वेत व
र्णके फल होवे जिस घोडेको सो राजाके योग्य कहा है
अरु सफल कार्यके देणेवाला होता है इस प्रकार पहर फल।
सम्भने वर्णों विषे है न श्वेत विषे श्वेत पीत विषे पीत श्रेष्ठ
करे हैं ।

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा॰
हो॰
२६

26

इसके उपरांत निंद्य स्थानको कहते हैं। जठर विषें गलमें
शंख पुरपुडियों विषे फुलोंवाले घोडे स्वामी को निश्च
य करके सदा तथा केभयको करते हैं अरु कृत्तिका
के मृत्युको करते हैं और कांठी प्रोष्ठ मन्या अस्कपात प्र
भाव त्रिक इनों विषें पुच्छ भर्ता के वित्त धनका नाश करै है
और स्फिग् इड पदों विषें होवे तो स्त्री को दूषण लगता
है घोणा के पुत्रकी मृत्यु करै है अवटे मित्रों से वैर कराते
है कूर्च के भर्ताको सदा धनपीडा करै है गुदा के अरु डंव
के पास अर्थका नाश करता है ऐसे घोडों के वचन कहते हैं

अथ कुहरवलनठरे गले शंखयोः पुष्पिताः स्युः
प्रकुर्वन्ति भर्तुः सदा त्वर्थं कृत्तिकता मृत्यु।
स्य मेव कंठे प्रोथ मन्या स्कंधपाते प्रभावे त्रिके वि
त्त नाशं स्फिक् इड पदेषु स्त्री दोषं प्रकुर्वन्ति घोणा
अथो पुत्र मृत्युं अवटे मित्र वैराणि कूर्चे प्रभर्तुः
सदैवार्थपीडामपाने तथा पुच्छमूले तु सर्वा
र्थ निर्नाशनं ते च योर्वै धनं प्रोथगात्रस्थेषु पुत्र
मृत्युं वनानो: कंठे चैव गोत्रं तथ वाटयो स्पृह्या
कृत्तिका सैव भर्तु विनाश कटि क्रोडरो हि पुप्पा
दुःपुष्पाणि शस्तानि रक्तानि सर्वे रत्नेशानि स
स्निग्ध रूपाणि तस्मात्प्रशस्तानि वै श्वेतवर्णा
न पुष्पाणि रक्तानि पीतानि कृष्णानि शस्तानि
सैव पुष्पाणि पुष्पाणि कृष्णानि कुर्वन्ति भर्तु
प्रोथ अरु गंडस्थलके पुत्रके मारणे वधबंधनम्
वाले अरु ननु कटके फलका नाश करते हैं और घाटके
स्थानों के कृत्तिकाके स्वामीके नाश करै है लोक
कोउ काली रोहिणी उपरंत इनो विषें फल निंद्य है अरु
घोडे रत्नण सदा शीम है अरु ये स्निग्ध सब रूपवाले
श्रेष्ठ है और श्वेत वर्णके घोडे को फल लाल पीले काले
शुभ नहीं है और सभी रंगोंके घोडियों को पुष्प काले
वर्णके होवे तो स्वामी को मृत्यु तथा बंधन कराते हैं

© Dharmartha Trust J&K. Digitized by eGangotri

गैर जिनांघोड़ेयांके मुखविषे गंठ अधर इनोंविषेंश्वेत।
वर्णके पुष्प होवे सो घोड़ा स्वामीको सब दिनविषे वा १
सनमहीने विषे अर्थको देणेवाके हैं इतिपुष्पाध्यायः
घोडेयोंके पुल्लोंका श्रेष्ठ अरु निंद्यकहाहै लक्षण अब
हिणकणेका लक्षण संक्षेपकर्के कहते हां १ नाभिस्थान
ते प्राणवायुको ऊर्ध्वहृदयकोजातेहोयको कंठ अरु शि
रके संयोगते योशब्दहोताहै तिसकोहेषितहिणकण
नाम २ योहिणकणगंभीर अरु बड़ास्वरमधुर अयगु

अथहेषणेशुभेषांपुष्पाणयथोक्तेशुभाशुभा
णि तेदिवसेमासेवासमभिरथंप्रदाभुवः
इतिपुष्पाध्यायः ५ शुभमशुभमेतद्वक्तेपुष्पा
णांलक्षणांतुरंगाणां वक्ष्यामि हेषितानाल
क्षणमथुनासमासेन १ नाभेर्देशाहृदंवायोः
प्राणस्यावनोहृदयम् कंठेशिरसिवाताना
नशब्दस्तंहेषितंविद्यात् २ गंभीरःसमहा
न्स्वरस्तुमधुरःस्निग्धोघनःसंहतः सिंहव्याघ्र
गजेंद्रदुंदुभिघनक्रौंचस्वभावाशुभः येषांते
तुरगाययशोर्थसवेदाःसोभाग्यारामप्रदाः
संग्रामेविजयश्चतेनरपतेः सैन्यंचसंवर्द्धते म
विच्छिन्नस्तनुरुक्षजर्जरखरःक्षामस्तथागद्गद
स्तस्मोधानवराहजंबुकखरोष्ट्राणांनशस्तस्वनः १

कस्निग्धमघन अरु मिलाहोया सिंह चिता हाथी नगारे
वलक्रौंचपक्षि इनकेस्वर समशुभ हैं ३ जिनांकेऐसे।
घोड़ेहैं तिनांको यश अर्थप्राप्ति सदा पहदेते हैं गैर
सदर ऐश्वर्य राजके अरु युद्धविषें जयकोदेणेवालेक
हेहैंन ऐसेघोड़ियोंकरके राजाकी सेना वृद्धिहोतीहै
४ योछिन्नकटेहोया सूक्ष्मपोशरुखा अरुबुड्ढकोप्यारै
खोराकुषा गद्गद ऐसेहिणकण गैरकाक सर गिदड़ खो
ता ऊट इनकेतुल्यशब्दहोवे तोअच्छानहीहै ५

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ हो॰ २७ पहेहिगणकगणके लक्षणकहेयाहै अबयोगंधकरकेहोया
लक्षणकहतेहैं ओरकरि पसालिद पसाव पुत्र इनोंकी
सुगंधिघोडेयोंकी बुद्धिमानजाणे ९ इतिहेषिताध्यायः ९
अबगंधिकहतेहो कमल कुमुद नाणा हून चंदन कुग्य
27 इनोंकी सुगंधि मद्य मधु मझीर वा मद कोगाइ फुल मा
लती चंवा इनोंके पुष्पोंकी ओर हस्तिके मदकी घोडेयां
के कदंब बिल्व अर्जुनवृक्षके पुष्पोंकी अरु वसंतऋतु
विषे फुलेहोये वनोंकी सुगंधीवालेयोहे १ पुन्नाग अ।

पतेहेषितलक्षणंनिगदितंगंधोऽद्यवक्ष्यते ९
ओत्रस्वेदपुरीषमूत्रमुखजंगंधेविडंवाजिनां
इतिहेषिताध्यायः ९ कमलकुमुदमधिंश्च
दनहीरगंधा दृधिमधुकूटजानांमालतीचं
पकानां गजमदतुरगाणांनीपबिल्वार्जुना
नां मधुसमयवनानांपुष्पितानांसुगंधाः १
पुन्नागाशोकजातीकुसुमकुवलयोशीरप
द्मासुगंधाः पानीयैःप्रोक्षितोर्वीमुकलितव
कुलामोदिनोयेववाहाः धन्याःपुण्यामनोज्ञाः
स्ततमखयधनदाभर्तुरानंदिनस्ते मंगल्याभूप
तीनांप्रमुदितमनसोराजवाहास्तुरंगाः २
खपवकुणपगंधामत्कुणास्वक्तगंधाः ।

अशोक चंवेली कमल इनकेपुष्पोंकी खशपके अरु
कीसुगंधीवाले अरुजलसींकरकेसींचितकरी पृथिवी
कीगंधि अरुप्रफुलित वकुलवृक्षके पुष्पकी सुगं
धिवाले योघोडेहैंन सोधन्यहै पवित्रमनकोआनं
दकरेहै अरुस्वामीको पुत्रसुखधन आनंद इनकेदे
णवालेहै ओर राजाको मंगल कल्याणरूपहै ओर
प्रसन्नमनवाले असेघोरे राजाके वाहन स्वारीयो
ग्यहोतेहैं २ खपव वगल कुणपरासस मत्कुण
चर्म रुधिर इनोंकी गंधिवाले ॥

और गधा ऊंट सूकर उलू विष्टा मूत्र इनकी गंधिवाले
और मास थोम मत्स्य बकरेके अंडकी गंधिवाले ऐसेजो
डे सैकडे अशुभांके निंद्यकर्मकरणेवाले हैं सो त्यागने
योग्यहैं इतिगंधाध्यायः ७ येसे बदलोंकी पंक्ती आ
काशविषे सूर्यकोछादनकरदेती है तैसेही छाईघोडे।
योंके शरीरविषे उत्पन्नयोलक्षण है तिनको छुपायदेती
है १ सोछायापांचप्रकारकीकही है एकपार्थिवी दूसरी

खरकरभवराहोलूकविण्मूत्रगंधाः पललल
शुनगंधाः मत्स्यबस्ताण्डगंधाः अशुभशतकरा
स्तेवर्जनीयास्तुरंगाः इतिगंधाध्यायः मेघा
वलीयथार्कंगगनस्यछादयेत्तथाछायाः
छादयतिसकललक्षणमश्वशरीरसमुद्भूतं
साछायापंचविधाहिपार्थिवीवारुणीतथा
ग्नेयी वायव्याचैवभवेन्नरगाणानाभसीतप
गतिसः २ त्र्यवाः श्रेष्ठाः परेद्वेनिंदितेमहाम
तिभिः तासांलक्षणमेतच्छुभाशुभंवेप्रवक्ष्या
मि ३ स्निग्धास्थिराचमहतीवर्णैर्नानाविधैःसु
गंभीरा नयनमनोह्लादकरीप्रशस्यतेपार्थिवी
छायाः ४ सलिलसलिलधाराभासरोरुहाभा
प्रसन्नसलिलाभा ।

वारुणीतीसरी आग्नेयी चौथी
वायवी पंचमीनाभसी एहे पंचछायाघोडेयोंको होती
या है २ योएवं कियांत्रयकहियां हैं सो श्रेष्ठकहियां हैं
और परकीयां दोयनिंद्यकहियां हैं महाबुद्धीवालियोंने ति
नांके लक्षण चंगे और निंद्यत कहिआ है ३ योचिकनी
अरुस्थिर बडेविस्तारवाली अरुबहुतप्रकारके रंगो
वाली और गंभीर और नेत्र मनको आनंदकरनेवाली ए
हे पार्थिवी छाया बहुतश्रेष्ठकही है ४ सहितजलके यो
जलधारा तिसकी आभा औरकमलकी शोभासम और

© Dharmartha Trust J&K. Digitized by eGangotri

निर्मलजलकीमाई प्रभा अरु चिकनी थिंदी स्थिर एक
स्थानविषे एहेवारुणी वरुणकीछायाहै सोवहुतश्रेष्ठ
कहीहै ५ प्रभानकेसूर्यके मूंगा लाहारस पद्मरागम
णि इनकी प्रभाकेसम योछायाहै सोप्रकाशवाली यो
देयाकोआग्नेयीछायाशुभकहीहै ६ औरकठिन भिन्न
मलिन एहेवायव्या वायुकीछायाहै सोनिंद्यहै शुभनही
और हस्त चंचल सूक्ष्म अरु अप्रगट एहेआकाशकीछाया
है एहेहितकारनहीहै ७ येछौहेकेलक्षणकेजानणावा

स्निग्धास्थिराप्रशस्ताविज्ञेयावारुणीछाया ५
बालार्कविद्रुमाभालाक्षारसपद्मरागसकला
भा आग्नेयादीप्तिमतीछायाशस्तानरेंगाणां ६
परुषाभिन्नादीनावायव्यानिंदितान्छाया हस्ता
चपलातनवीवाम्भकानाभसीनेष्टा ७ स्नानस्य
पीतस्यतथापराह्ने समोस्थितस्यापितुरंगमस्य
मेकस्यनित्यंहयलक्षणज्ञैश्छायापरीक्षेतसु
भाशुभावे ८ इतिछायाध्यायः ८ विषमैः
पदविन्यासैर्नोच्चैर्ललितैः समैः वल्ग
मैनोह्लादकरीयागतिःसाशुभामता १ शि
खिनकुलवृषोष्ट्राश्वद्वंद्वैसमतत्परा शार्
भगतिसमानावानराणांचतत्पराः २

लेहैंन सोस्नानकीयेहोएकी जलपानकीयेकी सायं
कालविषे स्नानहोयाउठ्याहोवे भोजनकियाहोवे मे
घोडेयांकीछायाशुभ अरु अशुभ वैद्यबुद्धिमानपरीक्षा
करे ८ इतिछायाध्यायः ८ अवगतिकालक्षणकह
नेहां विभागकरकेहै पैरोंकाटकाणा अरुवहुतउंचे
नहि औरमंदरवणावारसेवरखना अरुनेत्रमनकोह
र्षकरणेवाली ऐसीगतिवालाहै सोश्रेष्ठकहीहै १
मोर नकुल बैल ऊट चित्रा हंस हस्ति इनकेतुल्यगति
औरशार्दूलअष्टपदमृगकेसम गति और वांदर २

© Dharmartha Trust J&K. Digitized by eGangotri

सिंह हंसोंकी चालके सम गति जिस घोडेकी होवे सो
राजाको जय सुख ऐश्वर्यको वधानेवाला है ३ यो गति
टेडी अरु सूव आगेपीछेपाण अरु संववहुउवे अथवा
वहुत मंद और गति सुंदर नहि अरु विकृत यथार्थ ना
हि अरु वहुतकरडी अरु वडे घने बाल रले मिले अरु ८
वडुउची असी गति श्रेष्ठ नही है ४ इति गतिकाध्यायः
त्रय प्रकारका सत्त्व कहियाहै सतोगुण राजस तामस ति
नोंके भेद सात छे त्रय इसीतरां सात सुद्ध सात अरु छे २.
तोगुणके त्रयनामसके भिन्न २ कहे हैं १ ब्रह्म ऋषि महे

मृगपतिगतितुल्या याहतिर्यस्य सो सौ जयसु
खविभवानां वर्द्धकः पार्थिवस्य वक्रा सवस्खलि
ताविषमावाह्यशफाः श्रेष्ठसौष्टवा विकृता
अतिविकटासंकीर्णा गतिरत्युच्चा न सा शस्ता ५
इति गत्याध्यायः ४ त्रिविधं सत्त्वमुद्दिष्टं राजसम
थतामसं सत्त्वतस्तेषां भेदास्तत्र सप्तषट्त्रयएवच
नैकशो विहिताः १ ब्राह्मं तथार्षमाहेन्द्रं याम्य
कौबेरवारुणमेव सुहान्येतानि सुर्गांधर्वंस
ममेचैव आसुरराक्षसपैशाचसार्प्यपैत्राणि
पाक्षं चैव २ षड्राजसानि त्रीणि तामसानीति
मानीयात् पाशवमात्स्यवनस्पैवरुहं वसत्वानि
षोडशैतानि ३ कथितान्युत्तममध्यमाधमा
नि विधात्क्रमेणैव कामाद्यपेतः स्मृतिमान
कोपीसब्रह्मसत्त्वः सविनिर्जितात्मा

इ यम कुवेर वरुण गंधर्व एहे सुद्ध सत्व है असुर
राक्षस पैशाच सर्प पित्री पक्षी एहे छे राजस सत्व
है २ पशु मत्स्य वेरुह एहे त्रय तामस सत्व है एहे
सोलां भेद सत्वके हैं ३ सत उत्तम राजस मध्यम
तामस अधम पाणे क्रमकरके योघोडा काम तें रहि
त अरु स्मरण सम याद रखना क्रोध नहीकरणा अरु
मन जीत्या होया सो ब्रह्मसत्व कहाहै जिसविषे राग
प्रीति द्वेष विरोध अहंकार मद मोह अज्ञान एहे।

© Dharmartha Trust J&K. Digitized by eGangotri

धा. हो. २५

29

नहिंहैन जिसकों सोघोउशमुनिमतवैहै ४ योघोउगतेज
वाला सूरवीर प्रताप ऐश्वर्ययुक्तहै तिसकों इंद्रसत्ववा
लाकहतेहै योमायाछलनैरहितहै अरुरागद्वेषमोह
इनोंकरकेवर्जितहै तिसघोउेको मुनिजन धमकासत्वा
श्रसकहतेहैं ५ जिसघोउेके प्रगटहोवै प्रसंनता अरु
क्रोध कामी अरुस्मृति स्मरनीवालाहोवै तिसकोंकुवेर
सत्वकहतेहै योघोउशसूरवीर पवित्र धीर्यवाला गौरज
लवहूतनप्याराहोवै तिसकोंवरुणसत्वकहतेहैं जिसको

द्वेषो न रागो न मदो न मोहः स्याद्यस्य तं वै मुनि
सत्वमश्वम् ४ तेजस्विनं सौर्यविभूतिमंतमैंव
वियंवाजिनमैंद्रसत्वम् मायाविमुक्तंगतरा
गमोहं तेयाम्यसत्वं मुनयो वदंति ५ प्रहृष्टःप्र
सादकोपःकामीस्मृतिमान्कुवेरसत्वोश्वः शू
रः शुचिर्वत्वशेजलप्रियोवरुणसत्वस्तु संगी
तमाल्यस्रजाप्रियश्चगांधर्वसत्वः द्वेषः रौद्रः
प्ररंभ्रोवाजी स्यादासुरः सत्वे छिद्रप्रहारी
सुमहाशनश्चसत्वप्रियोगात्मसत्वपश्चः भी
रुरश्चशूरः सुमहाशनश्चपैशाचसत्वोथभवेन
रेणः प्रतिक्रुपितभीरुशूरः शुचिर्दियोभवति
नागसत्वश्च दुःशीलः पितृसत्वः प्रियाशनो
दुरुपवर्यश्च सततावहारैर्मैथुनभयवान्पल्पश्च
पाक्रतसत्वम्

गायनपान्हू वस्त्र अरुपुष्पमाला
सत्ता इहहोणपारे जिसको सोपूरंगंधर्वसत्वकहिया
है देवसत्वकेपहेलत्तणकरैहैन वराभयानकस
रूप सूरवीर अरुवैरक्रोधकरदुःसह पैसाघोउदैसत्व
कहियाहै योदायदेखकर प्रहारकरणा अरुवहूतखोना
मोनाप्यारा ऐसारानससत्वकहियाहै डराकल गौरकाय
रवहूतभोजनकरना पैसपिशाचसत्वघोउाकहाहै वहु
तकोधीडरणा शूरवीर पवित्र ऐसाघोउा नागसत्वकहाहै
जिसकाखोटाखभाव खोनावहूतप्यारा गौरउलटे उपचार
करै ऐसेलत्तण पितृसत्वकेहै योनिरंतरभोजनकरणे

© Dharmartha Trust J&K. Digitized by eGangotri

विषें प्रीति मैथुन भय चंचलताकरकेयुक्त होवे तोषण
तनपत्नीसत्वजाणे भूखजडता डरणा आलस इनोंकर
केयुक्तहोवे तोपशुसत्वजाणे भोजनकरकेपीडित औ
रडरणा पाणीवहुतप्यारा पसलक्षण मत्स्यसत्वकहा
है निद्रा अध्यान आलस इनोंकरके वैरुद्ध्यसत्वकहिया
है इतिसत्वनामाध्यायः इतिश्रीगणकृतेआयुर्वेदेसि
द्धियोगसंग्रहेमिश्रकाध्यायःसमाप्तः मिश्रकेलक्षण
सर्वकहेहैंन अवमहादोषकरके योलक्षणहैं सोसुणो
और दशाकाविभाग अरुजिनोंकाफल दोष योतेउके

स्तेनाऽऽलसभयालस्यैः पाशवसत्वविजानीयात् आ
हारार्तो भीरुप्रियसलिलो मत्स्यसत्वश्लेषः नि
द्राध्यानालस्यैर्वैरूप्यसत्वेसमुद्दिष्टम् सत्वनामा
ध्यायः इत्यायुर्वेदेगणकृते सिद्धयोगसंग्रहे
मिश्रकाध्यायः मिश्रकेलक्षणंमोक्षंमहादो
षोद्भवंशृणु दशाविभागफलदा दोषाःतेत्र
यः स्मृताः १ सर्वकालफलायेचयेचोत्क
टफलास्तथा तेह्ययानामहादोषाः स्वामिनोनस
त्वावहाः २ शूलप्राणहरायेच महादोषंतमा
स्तते अतोषानामहादोषान्महादोषांतमोस्त
था ३ नामतःफलतश्चैवकथयाम्यनुपूर्वशः ये
प्रसितविषमस्फुत्किंदंतः करालीतथाहीनदं
तोपिदंतो ह्यधोभग्नदंतश्च नैस्पष्टितैः

अनुसारकहियाहैसो १ अवमहादोषकेफलकहते
हैं येहैमहादोष सदाफलकेकरणेवाले येउवेउत्क
टनिंद्यफलवालेहैं सोयोउयोंकोमहादोषकहेहैं सोभ
तीकासुखकेदेणेवालानहीहै २ येहेनिश्चयकरप्राण
कोहरणेवालेहै सोमहादोषतमकहेहैंन ३ तिनोंको
नामतेअरुफलतेआदतेमैंकहताहों ४ जिसकेको
लेचरवप अरुसिपीकीन्याईदंत विकराल तैसेही
छोटेदंत वा वधेहोपदंत ऐसाचोडा और जिसके
भनेहोएदंत अथवागिडगएहोवें सोःइहदिक
हाहै

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ ज्यो॰ ३॰ जिसके दंतपालीमें एक छोटे अरु एक बडे होवे सो क
राली है जिसके दंत भजे होवे वा पतित होंवा तिसको
रदहीनिक हाहै अथवा जे दे एक पासे दंत होवे और
जिसकी धाडीविषे जानुविषे हृदयमें काकसविषे
आवर्त होवे असे छोरे और वृषण अरु दंत इनोके स
हित और दांतोविषे जनमेया होवे अथवा एक दंत अरु
एक अधिक होवे अरु जिसके अरु एक मुष्क वा एक ल
वा होवे वा दयमुष्का वाला अथवा कौडे की नाई वा
लो वाले मुष्क अरु होवे जिनोके अरु रोमां वाले तैसे ही
विरूपाकार के चित्र वाले यो है और नकुल संज्ञा काक २

विवृद्धिहीनस्त्वथ कारदंतः ककुत्राक्षिकाकसा।
वर्तिनो वा जिनाः वृषणदशनसयुता येव जाता
दिनेवैव हीनाधिका गो कमुष्का स्तथा लंबमुष्का
स्तिमुष्काः कोषसन्निभो यस्य मुष्को भवेत्तास्तथा
लोमशो विहृभिन्नस्य या चित्रितानकुलसंहिषका
करेवा बनेवैकपिंगेक्षणा वानरा हा स्तथा भि
केरालकमार्जारनेत्रा नेत्रा मिश्रकेशा जटाभि
केशा श्च मीमंतकेशा ह्याः अवगंदुखरस्वरा मा
नो रपाताविनाकेशवाले श्च जानाः स्तथा प्रोथता
ल्वा शुनिह्वा शिरः स्कंधमध्योरक्षुसा हयास्व म
वर्णिन शोर्षिणा पुच्छेन वै अरदमपुच्छोथ ललाट
रोमः

लई सहा इनोके समनेत्र और एक पीले नेत्र वा इनों
ला और वानर के नेत्र समनेत्र और सूर उल्लू बिल्ला इनों
के समनेत्र और जटा करके रले मिले केश जिनों के मे
...... अरु स्त्री के जटे की नरां वाला जिनों दे
से चोरे और अवगार ...... तोता कुत्ता बिल्ला इनों की
नरां पाद जिनोंके और बालके मार इनोंथी विनाजन्मे हो
प और जिनों दे अथ नासा के उपर तालु ओठ जिह्वा
फिर तोतों लिया अरु सूषण कालेहोवे जिनों दी ईया
दे अरु शिर वा कंध और रंग का के होवे जिसको उका
वे और मस्तक वहन प्रकाशवाला होवे लम होवे।

© Dharmartha Trust J&K. Digitized by eGangotri

औरस्थिरऊरुष्ठभेदवांवालांहोवें औरगौवत्सखेतगये
कीन्याईष्टहोवे नमरद औरत्रयशिरवाला अरुमुष
ल्यासंज्ञावाला अरुजिसकीष्टविषे तिस्कासारभूत
होयाहै औरयेजुप्रेतापनीतहोउहेंन औरजेउत्पव
संकीसुगंधिवालेहेंन अरुयेजीयांहोउीयांदोगर्भेवाली
यां अथवाबहुतगर्भाकरकेयुक्तहै एहेमहादोषक
हेहेंन औरशृंगवाले त्रयकर्णीवाले औरदोयखुरवा
वालेस्तनींवाले पंचसंवेवांवालेजन्मे एहेइतनेविशे

षिन्नीनष्टागौरखरामष्टः नपुंसकःस्यात्त्रि
शीर्षमुष्कल्या वारोहकोयस्य हतस्पृष्टे प्रेतो
पनीतास्तुरगास्तयेस्यु र्येदग्धवर्मोपमगा।
श्चिनस्त्रस्य याहिगर्भाबहुगर्भास्त्रमंते महा
नः कथिताश्चदोषाः शृंगीत्रिकर्णीद्विखुरी
स्तनीचस्यात्वमः पंचशफोजिनीव एतेम
हादोषतमाह्ययानोस्पंचराष्ट्रंचविनाशयं
ति एवंसर्वेमहादोषामहोदोषतमास्तथा
नामतःकथितास्तेषामधुनाफलमुच्यते श्रु।
तिंतेदेशानेंवाजीभर्तुः सर्वार्थनाशकरःक
थितः विषमदशनैःस्तनचूः सुतनाभेःस्त
विपाशकरः विरलाविषमादंतास्तीतारानायस्य
वाजिनः

षकरकेमहानदोषहै वाजीयांके एहेनुहां
होवें तोराजाकों अरुदेशको नाशकरदेतेहैं एहेस
भमहानदोष अरुमहानअतिदोषकहेहेंन एहेदो
षनामतेंकहेहैं अबइनकाफलकहदाहै कालेदंतोंकर
केयुक्तयोहोराहै सोअपणेस्वामिके सभअर्थनाश
करनेवालाकहयाहै योघोड़ा विषमकालोंदेवउदे
दोवालायाहै सोअपणेस्वामीके पुत्रकेनाशकरणे
वालाहै अरुयास्त्रिपीनरादंतांकरकेयुक्तहै सोभर्ता
कोनाशकरनेवालाकहयाहै ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ हो॰ ३१ 31

जिसघोडेके विरले अरु विषम वरवय होंय अरु विवे
होनदंत सोकरालिनामक हेयाहै सोघोडेयोंविषेनि
य स्वामीके अरु कुलकोनाशकरनेवालाकहेयाहै
जिसघोडेकी दोनोंदंतपंक्तिमें एकअधिकवडदंत हो
वे औरछोटे होवे तिसकोकरालनामाकरकेजाणे अ
पर ऊपर ऊन संज्ञाकरके याअपरतलेकीविषेअधिक
होवे सोस्वामीको तथाकाअन्नके भयकोकरताहै यो
उपरकेदंतोंविषे होवे तो तिस्काभर्ताशत्रोंने हारेयाजा

स्वकालीकुलश्रेष्ठंनिहन्यात्स्वगणायमः ऊर्ध्वा
भ्यां दंतपालिभ्यां यस्यैकाप्यधिका भवेत् ११ तं
करालं विजानीयाद्दंतयोनरसन्निते अपरकरा
लीभर्तुः स्वदंतकुत्रोनरेग्रह्दशाने ष १२ एककरा
लीवाजीभर्ताजीयेतनस्वपरैः हीनैर्दशने
वीजीभिवक्रोदारहषणःकथितः १३ अधिकदा
शानप्रजाघोभर्तृद्रोवर्जितस्वरगः दंष्ट्रावण
बांदंताभस्मतेयदिपंततिवाक्षस्य १४ एकद्विंत्रि
वतस्तोमहत्स्वयंतत्त्वजानीयात् १५ यदिपंचम
मश्चोलवेनेन स्फुटोत्तरंगास्य नचवंडवाम
यिगक्रतिमरंद्रवृद्धिः कुलानकरः १६ अथपंच
मनवर्षप्रवृत्तेः स्वामस्वगृहक्षणो सो ॥

नाहै योघोडाकमदंतोंकरके युक्तहै सोस्वामीकेमित्र
कोनाशकरहै अरुस्त्रीकोदूषणलगानेवालाकहेयाहै
अरु जिस्कादंतअधिकहै संतानका भर्ताकेनाशकर
णेवालाहै ऐसाघोडात्यागनेयोग्यहै जिसघोडेकियां
दांत अथवादंतभजेहैं वा गिरगयेहैं एकदोवा तीन
वार वर्तीमें नरमरावडाभयजाने सवपंचमवर्षविषे
अरुकोमलवक्रजानत अरुप्रगटनहिहोन घोडेको अ
कघोडीकोवीनहिप्रापहोता सोरंद्रवृद्धिनामघोडाक
हेयाहै सोकुलकेनाशकरनेवालाहै ॥

© Dharmartha Trust J&K. Digitized by eGangotri

अरुयोचोउरापंचमेवर्षविषैं होइ विषैमेंशुनमेंअरुहनपु
कहोताहै अरुदूषणअंरु जिसकेउराहै सोचोउरा गृह
विषै वरमें वाहरविषै सोउत्तमश्रेष्ठ राजाकीस्वारीयो
गपहै सोराजवाहप्रश्रहै जिसचोडेकेनल एकसम
दंतनहीहै एकपासेतें नीहणयारावाला दंतहोवे सो
स्वामीके धनकोनाशकरनेवालाहै योफल आवर्तव
कोकेविषै आवर्तोकाकहियाहै सोईहनोंकाकहियाहै
जिसचोडेकेअंरु कारेमोटेवालोंवाले अरुजन्मेदहै
दूषणवालेकेअंगमेंहोवे तवसोचोउरासभकेनाशकरणे

१८

नमेरेगृहेप्रवासेसउत्तमोराजवाहनं एका
नल्पदशनोवाजीविनापहोभवेद्धनैः धम
लमावर्तनामावर्तैस्तेवतत्कथितं दूषणं ।
कटिनोस्थलोप्रजातश्रुष्कस्थलोमसोस्यातो
मर्वतयद्धत्सोप्रजातदशनस्त्रदिनरश्च २०
विषमाद्भूस्त्रास्त्तनयः स्यात्रेष्ठनवस्थितोविव
र्णाश्च २१ हविधास्त्रदशनाभवेन्निजातस्यसद
दशनैः हिवाजातोवलहीनोनचस्थिरपरा
क्रमः नागरैक्षोभमाणोपिशोभांशोतनाप्नुया
च २२ अथिकांगोहीनांगोनश्चुभावेनोदयायमो।
स्यात्तो एकदूषणोतिदुष्क्रोदोवेनोमस्ततर्भारवो २२८
लेवदूषणाश्ववानीकपिदुष्कोयस्थलोमशोदूष
णो ।

वालाकहेयाहै अरुजोदंतोंकेसहितजोअरदिनविषै
जन्मेयाहै औरजिसकेदंद वरवधहोवे छोटहोस अरु
यथार्थस्थानविषैनहिहोय अरुअंगमाउराहै जिसकेइस
नरोकेदंदहै सेउराहेदांसहितजन्मेयाहै अरुदिनेजन्मेया
है सोवलकरकेहीनहोताहै अरुपराक्रमस्थिरनही
होता अरुश्रृंगारपालनकियाहूआवीशोभाप्रकाश
अतिकांतिकोनहिपामहृदा जिसचोडेकेअंगवधहोवे
वाघटहोवें असेघोडेनिंद्यहोतेहैं अरुशुभकेदेणवाले
नहीहै योएकदूषणअंरुवाला अरुएकअंरुकोशवा
ला रहहोई सहितदेस्वामीकोनाशकर्तेहै यालंबेअं
रेवालाघोडा अरुयोवादरके अंरुकोशवाला ॥

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ टी॰ ३२ 32

अहजिसके अंगरोमांवाले होंन योद्धोज्ञाकाले अहविच
मित्रफलकोंपावाले होवें यहेभर्त्तीकोंसहितकुलकेना।
शकरणेवालेकहेंन यद्योज्ञा नील सेज्ञा इलड उलूकआ
काक विल्ला बांदर सूर इनोंकेनेत्रोंकीन्याईं नेत्रजिनांके
यहेसभपापरूपहैं अहसभअशुभकेकरणेवालेकहेहैं।
हैंन स्वामीकेकुलकानाशकरणेवाले ओरयुद्धविषेवै
रीयोंकरकेजीतजातेहैंन ओरयोपकपीलेनेत्रावाला।
कावराहै तिसकाभर्त्तारणविषेकालकोप्राप्तहोताहै
तिसकारणते ऐसायोद्धा नगरमें अहयुद्धविषे नहींप्रा

यस्यासितविद्रुफलोज्ज्वलेक्षणेन स्वामिनंसकुलं न
कुलमहिषाभनेत्राश्चोलूककाककनेत्राश्च
मार्जारवानरनेत्राः सूकरनेत्राश्चयेप्रोक्ताः प
नेसर्वेपापाः सर्वाशुभकारिणःकथिताः भ
नेस्वकुलंनकराजीयंतेतेपरैश्वसंग्रामे अश्वपि
गलेक्षनेत्रोयुद्धेसम्भवेद्वन्द्वैः तस्मान्नगरेस
मेरसतैरणेनप्रवेशयस्तंनसर्वदैतेनरणेरणोजे
महस्तरणमोमूढः वेपवयोनवश्वेतलजटा
स्वंलसनेहरेसीमंतजटाकेशाभंजिनेकेशा
श्रमिश्रकेशाश्च पतेवर्णाश्चेषानंदतिक।
दाचिदपिभर्त्ता शार्दूलाभोवाजीविभातेवाजि
भिर्विवर्णाभैः यस्त्वसदाभाभिःस्यादवगाहमते
विज्ञानीयात्। २८

सकारण योद्धाओरघोडेयोंकेकै
सहीरंगवाला वानहिंकिसा मोमूढकहेंयाहैं अहये
शवयनको अहमस्तकोनहिंजानता सोजड़ अयसकहा
है ऐसघोडेकों दूरदेशविषेंत्यागदेवें येघोडे गुनकी
न्याईंवालोंवाले अहजटाकीन्याईंवालोंवाले जिनांके
भनेदकेशाहोवें ओरजिनांदेरलेमिलेकेशाहोवें ऐसे
घोडेत्यागदेने इनोंकास्वामी कदेवी आनंदकोनहिं
प्राप्तहोताहै यांघोडासिंहकीप्रभावाला ओरयांति
घवर्णघोडेयांकेकहेहैन तिनांकाकेपुत्रकेकहिंप्रा
हे येआरनाशुभप्रकारवालाहोवें तिसको
जाणे।

© Dharmartha Trust J&K. Digitized by eGangotri

पडै श्रपणे पतिको युद्ध विषे नाश करता है और का
र्य को सिद्धि के कर्ण विषे नहि है और जिस राजा की
नगर में देश विषे बसती नास होजाती जिसके ऐसा
घोडा होवे खोते के समसार वाला ग्ररु तिसके समवर्ण
रंग वाले मंडलों कर के यो होवे तैसे ही कलूक ये र
चिन्हों कर के युक्त है सो स्वामी को कुल के पुत्र संबंधी
यों के सहित खाता है यो बिली की नेत्र वाले संव
होवे सो श्रपणे पति को बहुत भय ग्ररु क्लेश युक्त दे
कर देना है यो केशों ग्ररु वालों कर के विना जन्मेया

पद्यस्वामिनमाजौ त्तिप्रं हन्यान्न कार्यसिद्धिः
स्यात् नगरे राष्ट्रे वसतिर्यस्य विनश्यन्सोश
ना खरसारः खरवर्णैर्मंडलैर्योभवेत्तथाही
नैः सकुलभर्तैः खोदति पुत्रसहबांधवैः।
नी मार्जारविच्चवर्णोभर्तैः कुर्याद्भयं महा
क्लेशं केशैर्वालैश्चविनाजातास्त्वनपत्यतांकु
र्युः कुस्ताग्रोथः त्यपेयत्स्वामिनमश्वः सर्वा
पदं सुसतेग्रष्टौयस्यतुकुलोविज्ञेयःसोपि
भर्तृघ्नः कुसेनतालनाश्वः स्वामिनमात्मा
मेवपश्चिविषमे हन्त्यसावमरोषैधुनकि
नविग्रात्मपापात्मा यस्मिन्कस्मिन्वर्णेकृति
नि हृत्स्नरंगमोभवति ।

होवे सो पति को संतान ते रहित करता है जिस घो
डे को टांगी काली होवे सो श्रपणे स्वामी को पुत्र सं
बंधी यों के साथ हरनिकास देता है जिसके ग्रठा
स्थान काले होवें सो वी भर्ता के मरणे वाला जाने
यो घोडा काले ताल्लू वाला है सो श्रपणे भर्ता को
ग्ररु श्रपणे ग्रापको कठिन मार्ग विषे और युद्ध
पाथ के मारे रणा विषे सताबी प्राप्त कर देता है
ग्ररु पापी शरीर है जिस किसी रंग वाले घोडे की
काली जीभ होवे ऐसा घोडा शुभ कार्य के करणे वा
नहीं ता है ।

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ सोस्वामीकेसभजोमुर्ख्है तिन्हांकेनाशकरणेवा
हो॰ लाकह्याहै जिसघोडेकेग्रउस्थानकालेरंगकेहोन
१२ सोभर्तोकोसदावधसमुग्रकुवंधनकोकरताहै जि
33 नांकेखारवेसिरलिंग१नोंविषेकालारंगहोवे सेस्वा
मिकेनाशकर्णेवालेहैं योघोडाहोरकिसीरंगवाला
है सिर और दुब होर वर्णकेके युक्त होवे तब सो स्वा।
मीकोपुष्टविषेनाशकरणेवालाहै विभूतिपेछायी।
कीरखावालियोंको ऐसाघोडात्यागनेयोग्यहै यो

नवेषशुभोस्यभर्तुः सर्वार्थनाशकरः ३५ कुलो
ऽवधंवधापुपदं वा स्वामिनः सदाकुर्यात् ॥
स्कन्धशिरोमेढ्रमुष्कवयेष्वसालेन भर्तुर्घ्नः
वर्णेनान्येन हयः शिरसा पुच्छेन वाम्यवर्णे
३६ न भर्तुर्ह्रस्वसममरे विवर्जितो भूतिमिच्छे
द्भिः यस्यैकवर्णस्य हयस्य दृश्यते पुच्छस्य
चाग्रं सितमन्यवर्णिनः ३७ हयस्य दृष्टे यस्य भ
तौ हतोनेत्रतेनरणे सो श्वेतोपनीतमश्वं।
विवर्जयेत्सर्वदोषकरं ३८ वालाः केशाश्च शि।
रोयस्य च वैदग्धचर्मगंधास्तुः तस्य तुरगस्य
भर्तुर्निसंस्खलनप्रियभवनं वैष्णीतुरंगी ॥
वमलप्रसूतांदग्धाच्छि सुमांसहिनांद्विजेभ्य

घोडाएकसारएकरंगकाहै अरुद्वेवकाअग्रपासा
श्वेतरंगकाहै या और वर्णकाहोवे जिसघोडेकी
दृष्टविषे तिसकास्वामीमृत्तहोवे सोऐसाअशु
नहीहै श्वेतोपनीतघोडाकहियाहै सोसभदोषों
करनेवालाहै तिसकोत्यागदेवे जिसघोडेकेवा
ल सिरकेकेश दग्धहोपचर्मकीगंधिवालाहो
वे तिसकेस्वामिकारनिसप्रग्रिकोभयकारणहो
ताहै योघोडीमलमासविषैसूप तिसकोवर्छेरेसा
थ ब्राह्मणोंकोदेवे वा त्यागदेवे ॥

© Dharmartha Trust J&K. Digitized by eGangotri

जिसघोडीकोबहुतगर्भहोनदे अथवा बहुततिस
कोंतिन्होंकेसहितनरदेशविषेंत्यागदेवे जिसघोडे
मध्येविषें शिरमें ललाटकेऊपर कटकेमध्यविषें
योऊठहोननिकलेहोवे घोडेकोअग्रभागकीन्या
ई वलीकीतरां आमलेकीन्याई अरुमनकेदेफल
केतुल्य अरुयोवमेकेकीलोंकी तरां अंडुदमूंग
कीन्याई अर्दुदरसोलीकीन्याई हलकी अंगुलवाऊ
र योशृंगअमे जिसघोडेकोहोवे तिसकोशृंगीअ
श्वकहतेहैं येघोडेयांकेचिन्हजाननेवालेहैं सोघो

भवेद्बहुर्या या वहूभिस्सगर्भैर्हयं त्यजेन्नामपि
तत्समेतं ललाटदेशे शिरसस्तवेवा कट
स्य मध्येथ समुत्थितं वा। हयेविषाणाग्र
निभं वलिर्वा धात्रीफलतां गोस्तनसन्निभं
वा स्याच्चर्मकीलाभमथार्बुदं वा शृंगं तदहुः।
लांगुलसन्निभं वा॥ तद्यस्य तं शृंगिणमश्व।
माहुरात्तः स राष्ट्रस्य विनाशहेतुः कर्णाभ्या
से करणीयस्सो मो जायते त्रिकर्णोन्नृप। ४२
तिं वा पवसहितं राष्ट्रं च विनाशयेत्तिप्र
गोणफलल्याद्विखरीगोविंदखरोपमस्ल
कोपखरी एताव पिभल्लै द्वौ शृंगीवद्धाजि।
नौत्याज्यौ ॥४२

डादेशकेनाशकरणेकामूलकारणहै। जिसघो
डेकेकानपास हसराकर्णजन्मयाहोवे सोत्रिकर्णी
कहेयाहै सोराजानूं संबंधियोंके और देससहित
सत्ताकीनाशकरदेताहै योघोडागोखरकेसमान
गोवालामंदवालाद्विखरीकहेयाहै अरुगौंडके
खरवाला औरजिसके मस्तककेपास मस्तकहो।
वे सोउपमस्तककहाहै येदोनो उपमस्तक अरु
उपाखर भर्तीकेनाशकरणेवालेहै येदोनोंघोडे
कीन्याई दोनोत्यागदेनेयोग्यहैन।

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ हो॰ ३४ जिस घोड़े के गोके स्तनों के तुल्य स्तन होवें मूत्र को
शक्रवर्ती विषे स्थित सो घोड़ा स्तनी कहेया है सो
सभ देश को नाश करता है जातु अरु कूर्च के गोर स्त
34 वों के पास भौर पैर होवे जिस घोड़े के सो पंच सफ व
हेया है सो शृंगी की माईं त्याग देने योग्य है यो प्रका
श वाले ईश्वर का युक्त है सो सहृदस संवधीयों के स।
हित नाश करता है ऐसे को सदा ही त्यागे जिस घोड़े
को शृंङ्ग परा उलटा विकृत रूप होवे खवे पासे कर के उ
डे के पासे खवी अति कूटके कोण में मध्ये के भाग को
गो स्तन निभौ स्तनौ स्य मूत्र कोश स्य पार्श्व संस्थौ
त सो ऽश्वः स्तनीति कथितः कृत्स्न राष्ट्रं विना
४२ शयति। जान्वोः कूर्चाभ्यासे तथा शफाभ्यासे पा
देनामेन हयः पंचशफः शृंगीवत्याज्या प्रदी
मपुच्छसूदराः सहृत्याते सहृदतस्तं परिवर्ज
४४ येत्सदा शृंङ्गं तयस्य प्रतिविकृतरूपं वामेन।
पार्श्वेन हनु प्रदेशे वामाति कूटस्य ललाट। ४५
भागं संस्थ शयातं भवती हयस्य ललाटदी
मोथ भवेद्विषी लोभर्तुः सदा प्राणहरः प्र
दिष्टः। सदैव वृद्धिं कुरुते रिपूणां विवर्ज
४६ येत्कलहस्य मूले अलाबुपुष्पाभ सरोम
वेशा जनस्य रोम खवाभ्यनेथ वा स्थिता।
स्पर्श करके जिसको होवें अरु जिसका मथा प्रज्व
लित होवे अरु क्रोध युक्त स्वभाव वाला है सो स्वा
मी के सदा ही प्राणों के हरण करणे वाला कहेया है।
सो घोड़ा शत्रुओं को वृद्धि करता है ऐसे घोड़े को ल
डाई के मूल को त्याग देवे। जिस घोड़े जिस स्था
न विषे रोम ना होवें तिस स्थान में दीपके फूल।
वा तुर प्रभा वाले फूल गुहा में अरु खवे नेत्र वि
षे स्थित होवे चित्र कृष्ण भेद सम होवे जिसको।

© Dharmartha Trust J&K. Digitized by eGangotri

सोअपणे पतिकों पुत्रसंबंधियोंकर्के नाशकरता
है गौरीश्वरकीन्याईं जिसएष्ठविषेलगे घोडेकीए
ष्ठमडेरंगकी होवे तिसकोगौरीश्वरजाणे तिसघो
डेकेलक्षणजाननेवालियोंने हरतेही त्यागणेयो
गहै जिसघोडेका लिंगस्पर्शविषेकोमलहोवे
अरुघोडेयांविषेंबाहरनहीनिकसदा तिसनिंद्य
नपुंसककों इंद्रबुद्धिकेवणवरहरतेहीनिकसदे
वे जिसकादेहसाराश्वेतचिटाहै अरुसिरकालेर
गकाहै सोघोडात्रिशरीनामकरकेकहेयाहै सो

गौरीश्वरस्यैवहियस्यहस्यातेवाजीविवर्णे
स्थएष्ठवेशे नैविद्धिगौरीश्वरएष्ठमश्व
नामः सहदेहयलक्षणैः । मेढ्रस्यहि
स्पर्शोयस्सान्नचनिरस्यतिहयास्य अष्ठभे
नपुंसकतंविवर्जयेदिंद्रबुद्धिसमं । सर्व
श्वेतस्यशिरोयस्य भवेत्कृष्णवर्णमश्वस्य
सहयस्त्रिशरीनाम्नानेष्टः सर्वार्थनाशक
रः पादैनैकेनसितोवर्णेनान्येनयः स्त्रि
भिः पादैः श्वेतैर्वाचरणैस्त्रिभिरेकपादो
ऽन्यवर्णस्यात् पञ्चहयलक्षणैः मुष
लीनामः सरोगमः कथितः भर्तृप्रको
शहस्तोविवर्जितः सर्वकालफलदस्स 42

हेज्ञानहीहै सभपदारथकेनाशकरणेवालाहै
जिसघोडेका त्रयसेवहोरंगकेहैन अरुएककवि
टवर्णकाहै पहेघोडा घोडेयोंकेलक्षणजानणे
वालियोने मुषलीनामकरकेकहियाहै सोघो
डास्वामीको डेरखजानेकानाशकरहै सोअसा
घोडासदाहीदुष्टफलदेणेवाला त्यागदेनाचाहि
ये । वालोंथिंविना जिसघोडेकेपिठ बाहु जा
येनस्थानविषे मृगकेचमकीन्याईं चिन्हहो
वे सोघोडाअग्निनिनामकरकेकहेयाहै ।

© Dharmartha Trust J&K. Digitized by eGangotri

पा॰ हो॰ ३५

35

सो वृद्धि वाले यों ने वहुत निंद्य माना कहा है जिस
के छूटे विषै होवे तो स्वामी का नाश करता है अरु
ओडियों विषै होवे तो स्वामी के भ्राता के मारने वाला है
अरु उस का पुत्र के विनाश कर कहा है यव जघन पा
दों विषै होवे तो स्त्रीयों को दुःख कर कहा है एह
महा दोष भयानक मुनीयों ने छे शृंगादिक कहे हैं
सो सदा ही बहुत निंद्य लक्षण योग्य हैं सो राजा
को और देश को नाश कर देते हैं जैसे गर्गाचार्य ने
अपणे ग्रंथ विषै कहे हैं सो ई फेर इस ग्रंथ विषै गणने

श्रोणीमध्यगानित्राभेः पृष्ठस्कंधांसजघनु
देशोत्थ यस्य तुरगस्य भवेद्विनीसतं।
निंदितः आवर्तैः ५३ पृष्ठमत्तेर्विनाशो भ्रातृव
धः स्फिक्प्रदेशसंस्थेन अंसे पुत्रविनाशनः
जघने दारदोषश्च ५४ । एते महादोषतमाः
स्मृताः शृंगादयः षट्कथिता मुनीन्द्रैः
ते वर्जनीयास्तु शुभाः सदैव नृपं च राष्ट्रं
च विनाशयन्ति ५५ । यथा गर्गेण यत्प्रोक्तं
तदिदं वो व्याख्यातं पुनः न वैषां विद्यते किंचि
न्निष्ठानायलक्षणं ५६ । सर्वदेशप्रभवेषु
कानेनीयास्त्वाश्रमाः तान्नृपः स्वस्ति
मान्नो न स्पृशेच्च कदाचन ५७ दृष्ट्वा सूर्यं निरि
क्षेत स्पृष्ट्वा स्नानं समाचरेत् पूजयेच्च द्विजा
न्प्रेष्ठान्प्रदानैः कांचनादिभिः ५८

कहे हैं इनों के हटाने वास्ते कोई कछु लक्षण नहीं
सभ निंद्य लक्षणों के यत्न यों होडियों विषै निश्चय
सो त्यागणे योग हैं अरु ओडियों को राजा और राजपु
त्र वजीर कदेवी नाकड़े अरु देखके भी सूर्य का दर्श
न कर लेवे ये कर स्पर्श करे तो स्नान कर लेवें अरु श्रेष्ठ
ब्राह्मणां को पूजा कर दानों कर के सोनि आदि लेकर
प्रसन्न करे।

© Dharmartha Trust J&K. Digitized by eGangotri

तिसकारणते तिन्होंको शत्रुओंके देशविषे छोड़ा
यकर्के शांतिकरावे देवताशिवादितिनको नमस्का
रकरके और नियमव्रतादिशांतिकर्मकर्के ब्राह्मण
के पूजनते यहे सम्म दोष शम होजाते हैं मांसकी
ल रसोली फल आवने वक इनोंको छेदने साथ।
दग्धकरके फेर अग्निविषे हवनकरके ब्राह्मणोंका
पूजनकरे राजाको अरु प्रजाकी रक्षा विषे योग्य
यानयोहे तिसको और योनित्य हि धर्मके मार्गवि
षे प्रीतीवालेको और जय होमके यत्नपरके ऐसे

तस्माद्देशान्तरिपोर्देशे तस्य शांतिं प्रयो
जयेत् देवानां प्रणिपातेन नियमैः शांति
कर्मभिः एवं प्रशाम्यते दोषो द्विजाती
नां च पूजनात् मांसकीलार्बुदं छित्वा उ
ष्यमावर्तमेव च स्ववर्णेन दहेदग्नौ ह।
वा से पूज्य च द्विजान् ततः प्रजारक्षण
तत्परस्य धर्मे च मार्गे निरतस्य नित्यं होम
जपे यत्नपरस्य शान्तो दोषाः प्रशाम्यन्ति न
रणमेमास्या। अलब्धमनरम्भेव न दोषैर्लि
प्यते ल्पः यद्वा वैवाहिताग्निश्च द्विजो वा
वेदपारगः इति महादोषाध्यायः महादो
षाः समाख्याता स्तालरागमतः शृणु ता
लरोगाद्धिवाहानां शुभाशुभफलप्रदः १

राजाको चोरियों करके प्राप्त यो दोष है सो शम होजा
ते हैं योराजालोभिना होवे सो दोषों करके स्पर्श नहि
होता जिस ब्राह्मणने अग्निहोत्र किया है अरु वेदों
के पार अंतको जानता है तिसको वी यह दोष नहि स्पर्श
करसकदे इति महादोषाध्यायः महादोष मैने क
हेहैं अब ताल विषे योग है सो मैं रते सुण चोर
योंके ताल विषे योग है सो शुभ अरु माड़े फल।
के देणवाले हैन १

© Dharmartha Trust J&K. Digitized by eGangotri

घो० स्त्रो० २६ विटा लाल पीला श्वेत काला चित्र मिश्र अथवा विटा २
अरु औररंग घोडेयोंकेतालूके रंगसंननंतकेजाणे
तिनाविषेंलालश्रेष्ठ है औरदूजेश्रेष्ठनहीं हैं अब
कुछकश्वेतादिवर्णोंकाविशेषकहताहों जिसकेता
लूमें अथरेखावा वारलवणतो सोऐसाघोडातालू
केदोषकरके नहिंत्यागनेयोग्य जिसघोडेकाउजेहो
पकोलकीन्याई कालातालूहोवे तिसकेस्वामीका
थोडेहीचिरविषें राजसभयतननाशकोप्रापहोजा
ता है ५ जिसकातालूकालाहोवे तिसकेस्वामीकी

श्वेतेरक्तेपीतेस्यावंकृष्णेच चित्रमंडसिते
स्वमविंपविजानीयातालनिरागंतरंगा
णा १ रक्तेनेभ्यः श्रेष्ठपोषाराणाल्लनैव।
संस्पने किंचिद्विशेषमेषां श्वेतादीनाअ
वसामि २ लेखोस्तिस्वस्तसंवालस्यते
यस्यतालनि नसतालकदोषेणपरिमा
अस्वरंगमः ४ निर्वाणागारनिभयस्यस्या
तालवाजिनस्तस्य भर्तुरविरेणराज्यवित्त
सकलंविनाशमुपायति ५ भर्तुरवह्यात
कृस्नेतियककृस्नसतस्यविज्ञेयः कृस्नं
तेरितेककृस्नेपराजयस्वामिनोविघात् कृ
स्नातपविन्निमसमध्येषु दृवनालयस्यस्यात्
परिणद्धनालरस्याभर्तेक्लेशमहोदोषः

मस्तुहोतीहै जिसकेत्रेडीयांकालीयोरखांतालवि
षेंहोवें तोपुत्रकोनाशकरजाणे ६ अरुवलीयांकेम
ध्यविषेंकालावर्णहोनेते स्वामीकीधातुकरकेहार
जाणे जिसघोडेकातालूवलीयांविषेंकालाहै अरु
मध्यविषेंपुरुदवर्णीहै सोघोडापरिणद्धतालूकहै।
ताहै सोपहेस्वामीकोदुःखकेदेणेवालाहै ८ जिस
घोडेकातालूस्थानकहाहै ऐसारकमलकेदलकैर
गवालाहै। ।

© Dharmartha Trust J&K. Digitized by eGangotri

सो घोडा अपणे स्वामिकी हारनित्यकर्ता है ९ जिस
घोडेका तालुकालीयें बिंदु करके चित्रत होवे अथवा
उलाष के सम बिंदुओं करकें चित्रमिश्रा होवे सो उलमा
षतालु घोडा है सो भर्ताको अशुभ विषें सदा प्राप्त कर
ता है १० अठप्रकारके घोडेयों विषें तालुका रंगका
दोष होयाहै विरे अरु क्रौंचवर्णवालेको गौरसालारं
गवाले घोडेको जिसरंगका घोडाहै औरउसरंगका
तालू होवे सो कालेतालू करके दोष नहीं कहेयाहै

कुल्माषतालवश्चाः पर्यन्तः पद्मपत्रसंका
शाः यस्यास्यस्तु नित्यं पराजयं स्वामिनः
कुर्यात् ९ कृष्णैर्बिंदुभिरथवा उल्माषै
स्तालु चित्रितं यस्य उल्माषः स्तालरेषः
स्वामिनमशुभे नियोजयति १० अष्टाना
मेव वर्णानां निर्दिष्टा कृष्णतालुता
क्रौंचवाहस्य शोणस्य चहरेरपि ११ सर्वा
णांसमतनुच्छन्ते कृष्णदोषास्तु तालुनि प्रक
टादिनकृत्प्रदिनकरपद्मदलाभ प्रवाला
भे स्निग्धं न तु गंभीरं तालु शुभवाजीनां ते
यै उक्तं च शालिहोत्रेण समानवर्णवर्ण
न तालुके यस्य यद्भवेत् एकवर्णं तथा तत्र
फलमल्पं प्रवर्त्तते दशाहेत्रविभागेन ना
लगागफलोदयः

प्रगट होवें ऐसे रंगनै सेत्रप्रदिनकी अरु सूर्य अरु
कमलदल औरमूंगा इनके समवर्णसोभा होवे अ
रुचिकना चिंदा सत्स गंभीर ऐसा तालु घोडेका शु
भजाणे शालिहोत्रणे कहाहै जिसरंगका घोडा हो
वे उसीरंगका तालू होवे एकरंगका होनेकरके ति
सकाफल थोडा कहेयाहै ११ दशा अरु जिसवि
षजन्मपाइनके विभागकरके अरुलासकेरंगका
फल और मलके विषेंयोविन्हुतिनोंकाफल औ
रयेहलहणहैं।

© Dharmartha Trust J&K. Digitized by eGangotri

षा॰
हो॰
२१

37

अरु उर्मियां लेलांत्रय अथवा चार शुद्ध होन जिसके और
सर्वो रंगने का ले होवे सो दोषों कर के नहि लिपायमान
होत तिसको दोष नहि स्पर्श करते इति नालरागाध्या
यः। नालुके रंगकाल लक्षण कहे या है अब कुलों का
लक्षण कहते हैं ये चारु कांबोज वाल्हीक वनायुज कुल
विषे जन्मे होए अरु गांधार के कुल विषे उत्पन्न होए हैं ये
रहकुल के विषे जन्मे होए १ वंवे के देश के [illegible] सिंधु
देश के नैतर यो चार हैन यो कुल विषे जन्मे हैं उपकु

वनजानां फलेन हयघ्राणमदपिलक्षणं ३
र्धलिखस्थितसोवाशुद्धाभवतियस्यवै पर
नस्तु भवेत्स्पर्शेन च दोषैः प्रलिप्यते इतिना
लरागाध्यायः। नालरागः समाख्यातः कुला
नां लक्षणं शृणु हयाकांबोजवाल्हीकवाना
युजकुलोद्भवाः गांधारकुलसंभूतास्तथा
रहकुलोद्भवाः वापेयाः सैंधवश्चैव नैतिरा
श्चैव वाजिनः २ कुलनाम्नोपकुलनामेव
कासुपमेवकाः त्रैगर्ताश्चापरान्तेनेयाश्च।
सावित्र्यास्तथैव च २ यौधेयाः पावनाश्चैव
येचान्ये ह्रस्वयावनाः नोषाराः कांदरीया।
श्चनामदेयास्तथैव च ४ आवन्त्यौरस्यका।
सौराष्ट्र्याय्यवमकानका पार्वतीनरमाद्र
यामाद्र्यादक्षिणाश्चये ५

लह मेरे कुल उत्पन्न मेवक और उपमेवक के त्रिगर्त दे
शके अपरान्ते न देश के ऐसा पवित्र देश विषे जन्मे हो
ए यौधेय यावन यव देश के और ह्रस्वयावन के।
नोषार बरफानी देश के और कंदरा के और नर्मदा दी
के किनारे अवंती देश के विषे होनेवाले कापमी
र के मकानक देश के पर्वती न्द्रवनी उत्तर मद्र।
देश के दक्षिण मद्र के ५

© Dharmartha Trust J&K. Digitized by eGangotri

अन्तर्द्वीपदेशके घोडे कैकेयदेशके अंबष्टदेशके वा
सन सौवीर दारदसैरिक ६ लहक पेरावतसंज्ञावा
ले मालवके विंध्यापर्वतभूमिके कलिंगदेशके मु
ण्डाके काशीके ७ कलिंगदेशके कथनके उपहृत
क सुराष्ट्रदेशके मालवके कुरुक्षेत्रके पंचालदेश
पंजाबके प्रथकदेशके कुक्कुणदेशके हूसकुक्कु
णके हिमवन्तपर्वतके येउ११ नोंस्थानोंविषे जन्मे हो

अन्तर्द्वीपोद्भवा वाहाः कैकयांबष्ठसंतकाः ६
वासन्तकाश्च सौवीरा दारदाः सैरिकास्तथा
लहकैरावना वाहा मालवा विंध्यकास्तथा
कालिंगा मौण्डाश्च वाणाणस्तथैव च ७
कौलिंगाः कथनाश्चैव ये वोपहृतकाह्वयाः
सौराष्ट्रकाश्च मालवाः कौरक्षेत्रास्तथैव
च ८ पांचालाः प्रोथकाश्चैव कुक्कुणाहू
सकुक्कुणा स्तथा हैमवनाश्चैव ये चान्ये नाम
गयोद्भवा ९ चतुःपंचाशदस्थानांकुलान्येता
नि लक्षयेत् कुलानि नव चान्यानि घोटका
नां कुलोद्भवः ९
भावयेत् यतस्ते संतयाघोषं
अतः परं प्रजनैश्च प्रसंग च प्रवक्तने ११
यथोद्दिष्टकुलगणं पृथक्त्वस्थ पृथक् पृथक्
कांबोजाः सममहाललाटनयनस्कंधमहाव
क्षसो ।

पहैन ९ पहै वंहजा ५४ घोडेयांके कुलदेखलेवे उ
दिवालापुरुष औरनऔकुल होरघोडीयांके कुलविषे
अवरसतेंपरे
उत्पन्नहोपदेहैन ९ भिन्नभिन्न अंगअंग
प्रगटयाचिन्हलक्षणोंकरके
कहताहों जैसेघोडेयांके कुलकासंबंध कहिया
है सोसभ वलोवलीमेंरतेंसण ११ कांबोजजा।
तिकेघोडेअसैहैं वडेविस्तारवाले मथे औरअली

शा॰
हो॰
१८

कंधवक्षस्थल जिनका ऐर बहुत लंबे हैं का ऊँचे मु
ख ऐर बड़ा हैं बल तेग ति वेग जिनों दे ऐर छोटे हैं
अंडलिंगमूलक जिनका ॥ ऐर सुंदर खुर वे अष्ट
ऐर श्रेष्ठ बड़ी या विसाल जंघा जिनों के कंधे सुंदर
गर्दनी या जिनों किया ऐर सम भद्दंत चिनों कर के हजि
नका युक्त है सेव जिनों के पके हैन ऐर उरु के नेत्र
के सम है अग्नी जिन कीया ॥ चिटे ऐर लाल रंग के।
होने हैं अरु समर्थ वाले होने हैं अरु काले रंग के ऐ

दीर्घग्रीवमुखा महाबलजवा ह्रस्वांडमेढ्रा
नना श्रीमंतस्सुमहत्स्वभद्रचरणा दीर्घैः
स्कंधैर्भुजैः सर्वांगजनहर्षिता टढ्पा।
कामंडकनेत्राश्चैव ॥ श्वेताश्च शोणाश्च
भवंत्सदीनानकृसवर्णाननिवर्णेन स्नि
ग्धैश्चक्षुश्चैव मृदुरोमकेशा ह्रस्वेन दष्टेन
स्स्हूलवृताः ॥४॥ सत्त्ववंतो नागाः प्रियदर्शो
नास्नेनि सर्वभर्त्वेषु गामनोज्ञाः तेजो।
स्विनः सारयुताः सुशीलाः श्रेष्ठाः स्वरू।
पेणाकुलेन टमाः ॥ समवृत्तनाभुजं।
वाहनागाः ह्रस्वकर्णिकाखुराश्च पीना
स्तनुलाघुला : सुखुराः पाकर्णास्यः
॥५॥
रंनिंघवर्णों के नहिं होने ऐर गिरे छोटे ऐर बाल
रोम जिनके कोमल हैं दृष्टि छोटी है ऐर गिर द
है ॥४॥ ऐर हलके रूप अरु गिर्द हैन ग्रंग जिनके दंत
ण मैं प्यारा है देखना जिनों का स्वामी के बस है अरु स
नको प्रय है तेज कर युक्त है बालक कै युक्त है शील
स्वभाव वाले हैं अरु रूप कर के श्रेष्ठ हैं अरु कुल कके अंग
विनै है ॥५॥ बराबर है नाभु ऐर जंघा गिर्द है समग्रंग
अरु छोटे हैं न सुवावता सब संधियां जिन कीयां अ
रु मोटे सत्स्य हैं उव जिनके सदा स्वर हैं अग्ने की
मार्ई खुर के न जिनके ॥५॥

अरु लोंबी वडी यां है अरु उदर वडा है हनु दोऊ वडी है व
डे ऊचे हैं अरु चोडीयां को देखकरके वी वहुत हिणकदेते
ही हैन १७ मुखजिनका सुंदर नहि है पाद स्थिर हुए हैन
उचे करके संवेंको चलते हैं सूरवीर व बहादुर है और स
तकरके हौलि है वाल जिनांकी ऐसे घोडे कांबोज जाती वो
के कहे हैन १८ यो वाल्हीक घोडे हैन सो वी कांबोज के
घोडियों के तुल्य हैन समअंग वर्ण रूप जिनांदे और प
हेउन के वय है अगले वे अरु दृष्टां वहुत लंबीयां १९

स्समहाहनुकयोग्यामहोदरास्तेमहाहनूरुक्षा
या अनंसवडवामपि दृष्ट्वा नेनातिहेषंते १७
उष्ट्रमुखा स्थिरपादाः सुः कृत्वा गमो कृतालयः
शूराः सुखेसवारा वाह्याः कांबोजास्ते समा
ख्याताः १८ वाल्हीका कांबोजैः समानसंख्या
नवर्णरूपाश्च तेषामयविशेषो दीर्घांगादी
र्घनरदृष्टाः १९ परिणाहयामासो किंचिद्
स्वामहन्हणाः शूराः ह्रनाश्चिवुके योन्नतदी
र्घग्रीवास्तुकेशाश्च २० मधुपिंगलानदीनाः
क्रुद्धास्तेदंतवादिनः कथिताः मनेश्ववल्ल
लाः स्पर्भमहाजवाः रूपसंपन्ना २१ वानायुजाश्च
लघवः प्रचंडामध्यप्रमाणाश्च चपलानदीनाः

और फेरने घोडे थोडे हैन अरु हिणकदे बहुत हैं अ
रु वडे बहादुर हैं कांडी आल वडी ले वी हे वाले हैं सो
णे हैन २० मखीरके समपीले रंग वाले हैन खरदीरे
न क्रोधी है अरु दंतां को वजाने वाले कहे हैन और अ
पणे स्वामी के प्यारे हैन अरु वडे वेग और स्वरूप कर
के युक्त हैन २१ वानायुज घोडे छोटे अरु हलउ के
अरु नातो बहुत वडे नातो बहुत छोटे मध्यम कद
वाले होते हैन चंचल बलवाले और गिरदार हु
ए ऐसे विषे तुल्य होते हैन अत्ती जिनकियां सुंदर
होनीयां हैन।

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰
हो॰
३९

39

अरु अंडेते लिंग छोटे हैं अरु कांण खेडे रखदे हैं न २२
अरु जिनका अग्र का पासा उंचा है अरु त्रिक पीछा हो
ला है और भार को सहारते हैं अरु अहुसत्ववाले हैं मो
टे स्कंधोंवाले हैं न अरु स्वकी स्थिति जो उपके हैं न गेर
वहते काले रंग के होते हैं २३ उपांउष्यान जिनके कर
ठेंगीगे हैं गेरवाल वडी होती है मेचवदल अरु हाथी
के समुशद वाले हैं अरु निर्भय है अरु क्लेश के सहारने
वाले हैं अरु सिंह की न्याई अहंकार युक्त हैं अहंकारी हैं

हृताः यताः कायसमाः स्वनेत्राङ्गुष्ठांउमेष्ठा
स्वयंशक्रकर्णाः २२ पूर्वार्द्धकायेषु समु
च्छ्रितास्ते हस्ताः त्रिकेभारसहाः स्वसत्वाः
स्थूलैस्थपादैर्दृढपृष्ठिकाश्च कालाश्चवा
र्णावहृशोभवंति २३ उपांउदेशेविकटाः स
श्रीघ्रामेचैभनादाश्चनशंकिनस्ते सोंताश्च
मेंद्राःखनेविभांतिदर्पोज्वलद्वह्निसमान
रूपाः २४ रुयेयोक्तेनशक्तानेनसहतेव
यंत्रणं स्वायुसंहत्नगात्राश्चसर्वेभ्योप्या
यिकास्तेव २५ अथपर्वतदुर्गाणांमध्ये
नेछ्टियाविते मृदंगसहशापार्श्वेसव
र्णासहशाश्चते २६

अरु जागी होइ अग्नि के समरूपवाले हैं २४ अरु रथ
विषे योजोडना है तिसको न हिसहारदे अरु बंधनभी
न हिसहारदे देह जिनांदे केवल नाडीयों से हि प्राव
णवाले हैं अरु वेगविषे सभनों ते वडेवेगवाले हैं न।
गेर पर्वत किले उनदे मध्यविषे दोडने की इच्छा न
हिकरदे कों कर सखकर के ही ले चजाते हैं न अ
रु बलीयां जिनकीयां मृदंगवजंतर है तिसके स
मचोटदे हैं न अरु वर्णमें नेके तुल्य हैं २५

© Dharmartha Trust J&K. Digitized by eGangotri

अरु घोगां थार् जाती के घोड़े हैं सो बहुत रंगों के होते हैं वड़े देहवाले अरु सुंदर स्थितिवाले वलकारक हैं अरु अगला पासा गर्वित सर्पकी तरां उठ्या रखदे हैं पिछला पासा विषमचढदे हैं वो शवहुत रहे २७ यो सारकूलके घोड़े हैं तिनके पट सुंदर अरु पिठां वड़े विस्तारवालियां कन निक्के देह गिर्द संवकारे पके अरु आगा उच्चा रखणा अरु कारी ग्राल सोणी ऐसे हो ते हैं २८ चेवेके घोड़े का ऐसे चिन्ह होते हैं सवाउनस

गांथारा बहुवर्णाः शरीरवंतः सुसंस्थिता वलिनः दृप्तोदग्राः पुरतः पश्चाद्विषमाया माश्च दीर्घाश्च २७ सारगाः सुजवनाः सु दीर्घपृष्ठाः सुपंरूकर्णाश्च हूनागाहृष्ट पादाः पृथ्वीहृदयसुग्रीवाः २८ चीपेया स्थिरपादाः सुवर्णा जंघासकृष्टिकावलि नः स्थूलास्त्रिकूटशरवा स्त्रेजोजवसारगु णास्तः २९ सैंधवकूलजा वलिनः सत्त्वा स्टकसमधकमेघपूरश्च दीर्घग्रीवा सुखास्तः स्थूलास्तालमहाकायाः ३० तेनिरकूलजा जविनः स्थूलहनुग्रीववालकेशास्तः पृथु वक्षो जवनास्त्वाभारसहाः सुदृगाश्च ३१

मतरूप अरु जंघां सुंदर संघ की यां सैंधियां सोनीयां अरु वलवले अखीमोटियां अरु पंख पुठ पुठीयां टूंगी यां अरु तेज वेग गति पुरुषार्थ तेजोवाले होते हैं २९ ये सैंधव देशके घोड़े के कूलविषे जन्मेदे हैं सो वडे व लवाले ग्रंडकोष अरु लिंग पहेळोर अरु कारी तेसु त्वलेखवा गेर अखीयां मोटियां अरु देहवडे विस्तारवाले ऐसे होते हैं ३० तेनिरकूलके यो घोड़े हैं सो वडे वेगवा ले अरु मोटे हैं रोडी कारी वारा रोम जिनांदे अरु वडे

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
५०

50

विस्तारवाले हैं वक्षस्थलपर नेत्र जिनांके वडनभा
रखुरदरे हैं और देह जिनके सुंदर होते हैं न ११ ये कमलज
के घोडे हैं न तिनकी काठी गोल होती है मुख बडे वि
शाल अरु बालल लम्बे अरु सूक्ष्म हैं रोम तथा केश जिनां
दे और गिरदे हैं पर अरु स्कंधों की संधि अरु ललाट जिनां
दा ऐसे एक हैं न १२ उपकमलके विषे जो पैदे घोडे हैं
सो कमलज के घोडियों के समचिन्ह लक्षणों वाले हैं अ
रु कछुक आगे ते विस्तारवाले हैं देह अरु बाल हो लि

कमलजा ह्रस्वग्रीवा आयतवक्त्राश्च दीर्घवा
लाश्च तनुरोमत्वक्केशाः ह्रस्वोरुस्फिक्का
मध्याः २२ उपकमलजाश्चाः कमलजैः समान
लिंगाश्च किंचिदायतशरीराः लघुगतय
स्तनुसन्नाभारमहाकुक्केशाश्च ते ११ मेचक
कमलजाः सुमहाहनुदीर्घग्रीवाकामहोद
रकाः उष्ट्रमुखा बहुवर्णा मध्यबलाः शंकक
र्णाश्च २४ उन्नतगात्रैः ह्रस्वैः कूर्चैः खुराश्च वि
पुलजघनाश्च विस्तीर्णा चिक्कवर्णाश्च मे
चकामध्यमेधास्ते २५ उपमेचकाः स्युः ह्रस्व
ग्रीवावक्त्राः स्थिरसुखवेशफाः सुदृगावह २६
लटकाः स्फिष्ठिका उष्ट्रमुखाः स्तनगाः

कोमल सत्वस्वभाव और भारके सहारणे वाले और लउ
के ऐसे कहे हैं न ११ मेचक कमलके यो घोडे हैं बालों अ
रु खालां काठीयां अरु छातीयां बडे विस्तारवालियां हैं
मुख मांस अरु बहुतेरे रंगावाले बलयों उ मध्यम करीके
उरखदे हैं न २४ अरु देह अरु का उच्चे रखदे हैं अरु गिट
छोटे सुंबों लोके और पर बडे मोटे अरु चिकने कलीवडे
विस्तारवाले मेचक मध्यम में पार्श्व दिवाले होते हैं २५ उ
पमेचक घोडे ऐसे होते हैं काठीयां उच्चीयां अरु वक्षशिर

© Dharmartha Trust J&K. Digitized by eGangotri

सुखवोरे अंगकोमलकटिस्थान मध्येके अरुकर्णो
केवीचहैसोचिटेहैंन अरुसंवकीयांसंधियांवीपेत
अरुमुखवेनहारेहोतेहैं १६ त्रिगर्तफलकेघोडे शोहे
केवांगुर मुखअरुवाल आलकेवाल अरुनासाके उ
परकेस्थान औररंगपढे सभशहेकेतुल्यकहेन और
संवपके औरक्रोधिनहिंऐसेकहेहेन १७ जेघोडे
आजानेयहैं तिनकेसंववडे अरुपृष्ठ अंडस्थान प्र
वलवलवान और मुखलंबे अरुसुगंधवालग्रीवा का

त्रैगर्ताः शशवदनाः शशवालधिकेश
राः शशग्रोथ्याः ह्रस्वपादा अक्रूराः शश
वर्णाः प्रायशः कथिताः १७ येचाजानेय
वाहाः ह्रस्वपादास्ते प्रवालपृष्ठकाश्च सुदीर्घ
खाः सुगंधाः सुग्रीवाह्रस्वपृष्ठास्युः १८
साविज्ञेयास्तुरगा विपुलग्रीवा विनानना
शूराः मृदुंगा ह्रस्वपादा महोरसः सुप्रमा
णाश्च १९ सकथ्यूरु ह्रस्वदीर्घाः स्थिरमां
सादीर्घवालाश्च चारुनयना सुगंधास्ते
हेतुवल्लकेश्चनिर्मांसाः ४० यौधेयाभार
सहाः सुश्रुणाहृनायतोद्यतग्रीवाः उष्टाय
नवल्कास्युः स्थूलास्तनुसूक्ष्मरोमाणः ४१

डीयांसोणीयां औरपिछांछाडीयां ऐसेकहेहैं १८ जे
सविजफलकेघोडे हैंन जिनकीकाडीयांवडेविस्तारवा
लीयां मस्तकविन्हांवाले शूरवीर अंगकोमल संवमो
टेविस्तारवाले अरुछातियांवडीयांसुंदर प्रमाणवाले
औरलंकूपरहस्व पहेलवेमांसथिर औरवालवडेलंवे
अखीयांमोलियां अरुदेहसुगंधवाले औरकोडीनेमुख
थोडेमांसवाले ४० येयाधेयफलकेहैंन सोभारकेस
हारणेवाले अरुसंवगोलतनसोने औरकाडीयां उटाय
कारसवेदेहैंन अरुमुखलेघोडे अरुकसोणा औरकोथीवे
गवाले औरवालछोटेनेसूक्ष्म ऐसेकहेहेन ४१

© Dharmartha Trust J&K. Digitized by eGangotri

श्रा॰ हो॰ ५१ और ये यवनदेशके घोड़े हैं सो तिनांके विस्तारवा
लेहैं पट्ट वक्षस्थानमध्य अतियां अरुसोण हैं न
सव गामेव जिनोंदे और चालवडी होलि औरकर्ण
स्वेवखेड़ेरखेदे हैं ५२ अरु देखनविषे प्यारे सोण
औररंगसुंदर औरप्रगट वडे विस्तारवाले मुख देहवडे
औरतेज सत्वधातवलकरके युक्त त्वचाचमडीपतला
रोमनमेंअैसे होते हैं ५२ जेड़ेघोड़े समुद्रके टापूके
विषे वरते हैं जेडेयवनदेशके सोहृत्तविशेष तिनके

यावनत्तरगा विस्तीर्णजघनवक्षोललाट
नयनाः स्युः पीनाः स्कंधिकाश्च बालत्वा
क्षमाः शक्तकर्णास्ते ५२ प्रियदर्शनाः सव
र्णास्पष्टायतनमुखा महाकायाः तेजः स
त्वोपेतास्तनुत्वचः सूक्ष्मरोमाणः द्वीपेसमु
द्रस्यचरंतिवाहाः संनर्जितास्तेमधुनाच
एवं नीतास्समुद्रं च यवनेन देशांतरंगमी
नांजनयंतिपुत्रान् ५४ तेयावनास्तानिक
सन्तकाशास्तनुहस्वरूपाः स्वमहाजवाश्चः ते
याः प्रकृत्यानिलपैतिकास्ते कपित्थसात्म्या
स्तुरगाः प्रदिष्टाः ५५ तेत्रैव हंसयावनाः स
न्ताश्च स्नेहयास्तद्रस्तांगाः सुभागाः सुम
साराः सुभप्राफाः स्वनवाः सवर्णाश्च ५८

फलोंकी सोसुगंधिमदहै तिसकरके जेडे एवंपी
इतहोके चलेगये हैं सो फेरसमुद्रको तरकरके य
वनदेशमें आइकरघोडियांके विषे पुत्रान्पैदेकरते
हैं न ५४ सोयावनकहेन अरुतिनाकी उनकोहीकह
ते हैन औरस्वरूपजिनाके सूक्ष्म अरुवेगगतिवडूत
अरुपित्तवानस्वभाववालेनाण अरुकैथ्थुकेफल ति
नाको अैइगुणकरते हैं अैसेकहे हैं ५५ तहांहि पवनदे
शाविषे हंसयाननामककेघोरघोडे हैंन तिनकेअंगा
छोटे हैंन औरणरीरदेहकासारपकेआइ सवेवेगगति

© Dharmartha Trust J&K. Digitized by eGangotri

वर्णीऔर रोमवाल केश औरवाल मेथायाराणमक्लिष्ठ
ट्टि रूप पहेसभसुंदरहोतेहैं अरुदर्शनविषे वहुतसो
णहै अरुमनको जाननेवाला औरतेजयानबलवेग
स्वभावरनोविवालेकहेहैन ४७ तषारदेश वरफाने
मुलखकेघोडे बलवेगपराक्रम युक्तहोतेहैं शरीरवडे
होतेहैं औरभारको अरुमार्गकेखेदकोसहारणेवाले
होतेहैं औरवलीया वडीयांविस्तारवालियांवाले ४८
मिकपकीवालेहैं औरवलवाले वीर्ययुक्त अरुवहु

सुभरोमवालकेशाः सुभगास्तुसमेधसः स
रूपास्तुः प्रियदर्शनामनोज्ञास्तेजोवयस
त्वसंपन्नाः ४७ एवंतुषारकास्याजववा
लसत्वान्विताममहाकाया भाराध्वक्लेशस
हास्तुषारकावहुसिवरूथवः ४८ दृढ
मेदसःसुशीलाबलवन्तस्तेमनस्विनस्थि
राः पृथुजघनाःस्थिरपादाःसुकृष्टिकस्तुः
त्वगैस्तल्पाः ४९ अथास्तकोदेरयादृढ
पादासूक्ष्मवालरोमाणः मृदुत्वचःसुशी
लाः सुकृष्टिकाकायवंतश्च ५० वाहास्तना
मेदेयाः एवंशरीरेशुभसंस्थितास्तेस्तुः पश्चा
दैशुनविषमास्तन्दराहूस्वपृष्टाश्च ५१ आवे
ग्याः पृथुजघनामहोदरोरस्कदृढपादाः ५२

तेचित्ररंगावाले जंघालेवीर्या अरुसंवयुदृढपके दृढ
संवौकेजोड अरुगतिविषें पवनकेवरावर ४९ कांदर
देशकेघोडे प्रेमकरहेहैन पैरसंव दृढ रोमवाल महीन
त्वचाकोमल अरुसील अरुसुंदर सवकेजोडअरुवडे
देहवालेहोतेहैं ५० जेघोडे नर्मदादेशकेहैन सोअ
गलेदेहकेहेसकाके स्थितरहतेहैं अरुपीछाहोलाओ
गावचलेहोतेहैं उदरसमलीका पिठांकोटियांवाहो
तेहैन ५१ येघोडे आवंतीकेहैं तिनकेपहुवडे अरुदृढछा
तीःहेवडेहोतेहैं ५२

© Dharmartha Trust J&K. Digitized by eGangotri

शा०
हो०
४२

42

काश्मीरदेशके घोडे नेत्र सुन्दर मस्तक वडे विलारवा।
ले और संवसेदार वराबर मिले होय तल अरु मुखमा
डा गैरवैपडा अग सूक्ष्म छोट कंन सिद्दे खडे ५३ घोडे
सकानक जेडे सकानदी के किनारे जन्मे देहैन तिन्हों
का अगला पासा उंचा हुंदा है अरु पिछला हिस्सा नी
दा है ५४ अरु घोडेंको देखकर गैर घोडीयां देखके
हिणकवे हैन कर्ण खडे रखदे हैन और कोमल तेल
मेहूं कर्णके दोनो भाग जिनके गैरकाडी और जटके।

काश्मीरा मुखदास्या विपुलललाटाः सुसंह।
ताः सुदृढाः इष्टायतवक्त्रास्तुः स्तब्धांगाश
ऊवर्णास्ते ५३ अश्वाः सकानकावेशकान
दीतीरजाससुदिष्टाः पूर्वोहे समुदग्राः प
श्चार्द्धे वा नतानुविनः ५४ हेषन्ते प्रत्यक्षं।
दृष्ट्वा वडवां चंचाकर्णास्ते मृदुदीर्घवि।
दुग्रीवा बहुहासा उदग्रगात्राः स्युः ५५ बाह्ल
पार्वतेया वलान्विताः स्निग्धबालकेशा
श्च हृतनासे रदफपादामहाजवाश्चैनि वि।
ख्याताः ५६ आजानेयास्तेषां कथितानि कु
लानि वैश्यकेन षड्विंशतिरश्वानां समु
दायो वक्ष्यते त्वधुना ५७ आजानेयास्तुंगा
हदफधन चरणा वर्ष्मवंतस्तनेत्राः ॥

समनेत्र अरु देह जिनके ५५ जेडे पार्वत कान्हवती
घोडे हैन सो बहुतवलवाले गैर छिंदे हैन वाल अरु
रोम गैर आलके केश जिन्हांके गोल है पैर संववडे तेय
के गैरवडी चालीवाले प्रगट कहे हैन ५६ आजानेय जा
घोडे हैन होरने घोडे के कुल जो हैं तिन्हांने मित्र कुं
वेकरे हैन अब छवीस प्रकारके घोडेयांके समुदाय सु
निके हां अब कहते हैं ५७ आजानेय घोडेके ऊंचे गैर
पक संव होते हैं . . . अन्तीसातिया अरु वडे

© Dharmartha Trust J&K. Digitized by eGangotri

ंगकरकेयुक्त ग्रहश्रेष्ठप्रकृति गुणोंकाजोसंग्रह
सवगुणाकर्के युक्तहै लिंग छोटेयुद्धविषैं स्वामी।
के अधीन औरवडेवेगकीगति वालवाले पराक्रम औ
रश्रेष्ठस्वभावयुक्तहैं शील वडीआयुवाले रोगतिना
कोंथोडे होतेहैं औरमिलेहोपते छोटे चने पिंडसंव।
कर्णी जिनादें औरबलतेज यानबल सारकर्के युक्तहै ५
और इंद्रके जीतनेवाले औरदुष्पारनकोसहारतेहै ४
और सुगंधिश्रेष्ठवाले हैं औरशरीर सत्वस्वर छाया

भूयिष्ठंवर्णयुक्ताः प्रकृतिगुणगणैरवि
नाद्गस्वसंस्का संग्रामेभर्तेवश्याः प्रबलज
वयुताः सत्ववंतास्सुशीलाः आयुष्मंतोल्प
रोगाः स्वसेहताद्गस्वह्रष्टश्रवकर्णाः बलते
जसारयुक्ताजितेंद्रियाद्गस्विपासस्सहाः ९६
शुभगंधाः शुभकायाः शुभसत्वाः शुभस्वराः
शुभछायाः शुभलक्षणाश्चशुभगानकर्के
शास्तेजितक्रोधाः ९७ निस्मिनाशुभिन्नका
याः संत्ताजानेतिविह्वलायस्मात् आजाने
आबाहास्तस्मादेनेसमुदिष्टा ९८ यतेवि
भिन्नदेहाविनिर्गत्ताज्ञागताश्चमृत्सवशी
यावत्रेष्टभर्त्ताभवेत्प्राणान्नमुंचंति ९९
आजानेयहयानामेतत्संवेसमासतः कथितं

लक्षणगति यहेसभशुभश्रेष्ठकहेहैंन जिनांदे औरल
शकेनही कोधीवी नाहै ९७ यवनीतशासककर्के देहक
टयावीगयाहै तववी अपणे आपकीस्वरतकोंवानाम
नाणतेहै जिसतें तिस्कारणतें तिह्नांथोडियोंको आ
जानेयकहयाहै ९८ यहेरसजातीकेघोडेयोंके देह
कटेगयेदेहैंन औरआंह्रांबाहरनिकलगयेहेंन अहस्व
मृकेनिकट प्राप्तहोयाहैन तदवी जितनाचिरस्वामि।
पिठकेउपरस्थितहै इतनांचिरप्राणोंकोंनहींत्यागदे ९२
आजानेयजातिकेघोरेयोंघोडियोंका सभलक्षण ।

© Dharmartha Trust J&K. Digitized by eGangotri

संक्षेपथोड़ेमें कहेदितेहै और बाकीके योड़िओंके कु
लकाललक्षण विस्तारके भयतें नहि कहियाहै ५१ इति
कुलाध्यायः कुलाकाललक्षणकहियाहै अब आयुका
ज्ञानकहिंदाहै अवस्था आयुषाकाज्ञानजानणा दोप्र
कारकाहै एकबाह्य दूसरा अभ्यंतर बाहरलावाहरले देह
करके और अंतरका दंतों करके जाणीदाहै १ पहलेमही
नेके बचेके दंतकाले अरु कुछकबाहर निकलेहोय
करके जाणीदाहै औरदोमहीनेका लालरंगवाले दंतो।

विस्तरभयाच्चनोक्तं शेषाणां लक्षणं कुलं
५१ इतिश्रीकुलाध्यायः कुलानां लक्षणं प्रो
क्तं वयसो ज्ञानमुच्यते वयसोज्ञानं द्विविधं
बाह्यं वाभ्यंतरं स्मृतं द्विष्टम् बाह्यं बहिः शरी
रं नमाभ्यंतरमपिहि दशनैस्स्यु १ प्रथमेमा
सिस्राव: संदेशैः किंचिद्रक्तैर्ज्ञेयः द्वितीय
नैर्हिमासः षट्पक्षो मध्यमे जाते: २ प्रतिष्ठ
तैः संदेशैः समसैर्मध्येस्तनस्थ येमासि ३
णौ मध्यमदशनैः संदेशैः पंचमेमासि ३ ल
स्यालस्य सस्तुष्मा गजिद्धा रुणानपांदेश
रणौ श्वेतदशनैर्ज्ञेयः षण्मासिकशावः ४
प्रोद्भिन्नैरंत्यभवैविज्ञेयः सप्तमासिकोवि
नैः

करके जाणीदाहै औरबकुकारले दंदजमणोकरके त्रय
महीनेका प्रतीतहूंदाहै २ चौथेमहीनेविषे मध्यके
दंदोकरके रूणोऔरबराबर होतेहैन पंचमेमहीनेवि
षे समभणोजो मध्यकेदंत अर्धीनता संदेशमीनताला
णवालेहोतेहैं ३ नवछेमहीनेका बचा बच्छिराहोवे तो
दंदोविषे संदरमहीनषरीयां लालरंगा लमभणोवाली
यां वा नहिलमने वालियां होतीयांहैं अरु सफेद हो
तेहैन लावे दंदोंके अग्रभाग तिनोंकरकेजाने ४ य
बकनोंके दंतबाहर फुटनिकल तोवृद्धिवालेयोने।

© Dharmartha Trust J&K. Digitized by eGangotri

सतेमहीनेका जानलेणा जब छोडा हेठले उपरले वि
देदंतोंयुक्त होवे जिनकों क्षीरदंत कहते हैं तब अठ म
हीने कहियाहै ५ नवमेमहीनेके बछेरेकों मेंहणोंसो
भाकरके युक्त दंतोंकरके जानने योग्य है दशमे महीने।
विषे प्रगट है चिटा बछेरेका दंत और तिसके उपरंत
कोश देखीदा है ६ पहिले वर्ष विषे दंत चिटे होते हैं
और दूसरे वर्ष विषे कषाय गैरंगके दंद होते हैं तिसके
भजकर्के फेरदंत जम्मे होन सोत्रयवर्षका घोडा कहे

योदंसाभ्यांतुरागः शुक्लाभ्यामष्टमासिकः
कथितः ५ ज्ञेयास्तु शिशुनवमे सहैणैः
परिभैतैश्च स्फुटशुक्लमध्यदशनो दशमे
परितस्तु लतेकोशः ६ सितदशनः प्रथ
मेब्दे कषायदशनो भवे द्वितीयेतु पतितो
त्थितदशांदशास्त्रिहायनः कीर्तितस्तुरगः ७
मध्यमदशनैः पतितैरुत्थितैः स्याच्चतुः समो
वाजि पंचाब्दिकस्तु कथितस्तु तोत्थितैः
पारिभैतैश्च ८ तस्मिन्काले वाजी पतितोत्थि
तसर्वदंतो बलवान् स्निग्धास्तिवर्णदशनो
लष्टः सर्वांगसंपन्नः ९ हर्षफलोदंष्ट्रावान्स
त्त्वसमृद्धितेंद्रियः सत्त्वोमाच पंचसमो भव
तिहयस्तेजस्वी सर्वकर्मसहः १०

या है ७ जब उपरके बछकारले दंद भजयान तो चार
वर्षका घोडा होता है यह भजनके फेर जमे होय दंतों क
रके युक्त होवे तो पंचवर्षका घोडा जाणे ८ जिसका
ल विषे घोडेके दंद भजनके फेर जम्मे हैं तब घोडा ब
लकर युक्त होता है शुक्लनेत्र रंग दंद स्थिर चिकने हो
ते हैं हर्षकरके युक्त होता है और सब अंग यथार्थ पू
र्ण होजाते हैं ९ सब फलोंकके युक्त दाडांवाला होता
है और सब इंद्रियोंके कर्णोंकरके युक्त होता है और

© Dharmartha Trust J&K. Digitized by eGangotri

शा. हो. ४४

44

रोमसंचरणवाला होता है पंचीवर्षोका घोडा ऐसा हो
ता है और तेजवाला सभ कर्मको सहारनेको समर्थ
होता है १० छेवर्षका घोडा रंगोंल लक्षणकरके जाणी
दा है देदलोरे कोमल सुंदर वणावर और तेमोटे उथ
के समचिटे चिकणे अरु दंत मूलविषे खवे है ऐसे
होते हैं नवकिशोरवस्थाका जाणलेवे ११ जब दंतवि
टेलेवे हली तणमिलेटे और ते ती हणदंत वेषु में स्थि
त विस्तारवाले हफहलनेवाले नहि अरु विवमैसे व

ह्रस्वलनव: सुसमा: स्निग्धा: तीक्ष्णविभा:
स्तहणा: मूलेषु वर्तते सितिमादंताके शोरका
लेया: ११ पीतास्पटी चोष्ठसमेसहनास्थली
हणाग्रसंस्थाविपुलाहफाश्च मध्ये विभक्ता
रवमूर्द्धिनिम्नाश्चुनो स्थितात्ते दशनाप्रवि
ष्टा: १२ प्रथमे द्विपोदसे शुवर्षे वर्षे च सप्त
मांतेषु संजनमथस्यभवेत्सुशष्टादारभ्यदंते
षु १३ कालाहरणी शुक्ला चावण्यमलिकाव
शतेश्च छिद्रे चलने पतनं नेक्रमयषष्ठ्यैज।
नानोन १४ स्याहृष्याहृष्यशंकासारहाल
रुणसंस्थिता: दृश्यं तेवाजिन: केचिन्सामाह
नकरा भृशा १५ वयपरीतेष्वरोमदंतचेष्टा
बलाधैनेव वह्नियोगो ॥

तो है न और कुछ परंते नमे होय ऐसे दंट गिरके फेरउ
ठे जमे होय कहे है न १६ पहेपहले वर्षमें दंतोंमें वि
क पैले मध्यके अंतके योमें चोडे करते अरु छेमा
वर्षतेलेकर कालहरणी शुक्ला काचमालिक शंख
परे चिन्ह रंगोंका क्रम करके छिद्र होणा हलना स
भजाना परे होता है १४ केघोडे उडे नहि परंतु उकी
सार लवते हैं न केकहे हृजनवानाके सहश लवते हैं
ऐसे घोडे भ्रम के करनेवाले होते है १५

© Dharmartha Trust J&K. Digitized by eGangotri

घोडेकी उमरकोपरीक्षा षरवालदंत उखारवल
इत्यादिकोंकरके ओर अग्निसंयोग चिन्हविशाम्रत्र स
मर्थ इनाकरके ओरचिन्होंकरके घोडेकीपरीक्षाजा
नणेवालेपरीकरे १६ रेखावडीओरदेही नीलेरंगकी
सोकृस्नाजंजनहै अथवाभ्रमकेसमरंगहै वीणा।
केरंगवागुरेखा हरणीचिन्हकहेयाहै ओरजोशुक्ला
है सोदही अरुरुग्य इनके तल्प कबके कोइके स
मरंगवाली है जोमत्तिके समहै सोउह्निवालिया

सेस्यानविणमूत्रसमर्थनाभिरघस्सनसै
रपरैखलिगै १६ रेषायतातिर्यगरिष्टवा।
णाकृस्नाभवेतषट्पदसत्रिभावा नेत्रीस
वर्णाहरिणीप्रदिष्टाशुक्लोदधीनीरसमान
वर्णा: १७ सितसिद्धार्थकवर्णाकाचाको
चितकोद्रवसवर्णा: यामत्तिकासवर्णास्ते
यासामत्तिकानिभणे: १८ शंखशंखदलो
पममूलषलेदंतमध्यजेछिद्रं विंघाखलिनै
खलिनैपतितैस्तपतनमितिव १९ एवंकृ
स्नाहरणीशुक्लाकाचायंमात्तिकावैव शी
खोमंडलवलत्रूश्रेणाश्चेषांक्रमःकथितः २०
षष्टेष्टेपंदशोणसप्तमेमध्यमेशुदसनेषु कौ
स्नाष्टमेनववर्षोविज्ञेयापारमत्तेषु २१

नेमात्तिकाकहिहै १९ जेदुषीषंखाहै सोशंखके खंडके
तल्पहै अरुजोदंतकेमध्यमे उखलकीतराछिद्रहोवे
सोछिद्रहै जेउदंतोकाहलानाहै तिसकरके चाल
नाजाने अरुजोदंतोकाफुटपैणा तिसकरकेपतनजा
णे १९ इसप्रकारकृस्नाहरिणी शुक्लाकाचामात्तिका
षीखा मंडलवलके श्रेणा परैक्रमसकरकेवाहैहैन २०
घोडेको छैमे सातमे अठमे वर्षविषे वछकालेदंतो
में कृस्नानामचिन्ह जाणीदाहै २१

© Dharmartha Trust J&K. Digitized by eGangotri

शा. हरणीनामजोहै सोघोडेके वछुकारले औरपिछले
हो. दंदांविषे नवमे दशमे ग्यारमेवर्षमें श्रेष्ठवृद्धिवालादेख
४९ लेवे २२ इसीतरांमिलनानामजन्नन बारमे तेरमे चौदव
45 र्षविखें घोडेके ऊपरकेदंतोंके वछुकारवा कनारेवि
षे जानेविरूद्ध २३ काचनामघोडेयांको पद्राँसोलासता
रांवरेविषे अगलेमध्यकेदाडांविषे देखीदीहै २४ जो
मालिकानामकहीहै सोघोडेयांको अठारमें उन्नीसें ५
वीमेवर्षमें दंतकेवछुकार औरकनारेकेविखेकहेहैं १

हरणीनवमेदशमेवर्षेकादशेनवर्षेषु सं
दंशमध्यमांत्येषुवाजिनालक्षयेत्ततः २१
एवंमिलनाद्वादशमेनवर्षे त्रयोदशेचैववत
र्दशेषु संदंशमध्यांत्यमुखोऽद्वेषुमस्तु
स्यिनोविह्नितरागमस्य २३ काचापंचदशे
वर्षेषोडशसप्तदशकेचवाहानां अग्रिम
मध्यमदशनेषुपारिभद्रेषुवादिष्पा २४
अष्टादशमेचैकोनविंशतितमेचविंशति
मे संदंशमध्यमांत्येषुवाजिनांमल्लिकाकथि
ता २५ एवंक्रमेणभावंक्षिद्रवालक्ष्युतिंवदं
तेषु शैलीशैलीपद्धतिनवाहानांनिर्देशप्र
तः २६ लिष्टःसंहरणिमासोमदमुदितगजा।
भोदनादःसमावालेनसीसमनपक्रः परमजव
वलः
इसीक्रमकके जोशंखकहेयाहै सोइकीमें
वारीमें त्रैयेंवर्षविखेंहै औरचोवी पंजी छवी वर्षविषे
लिहृकहिग्राहै सरूमनाहै अठाईउननीवर्षविषे वा
लनका दंतोकाहलानाहोताहै घोडियोंको औरत
रिकनीवनीमेवर्षविषे दंतगिरजातेहैंन पछेघो
डियांको त्रयत्रयवर्षीकरके श्रेष्ठवृद्धिवालाकहेहै।
वे २९ कालिकनामाजोदंतचिन्ह सोछेमेवर्षतेहोते
हैं निमवालाघोडाअमाहोताहै समत्रचिन्हसभमेहैं।

© Dharmartha Trust J&K. Digitized by eGangotri

मासवाला और मदअभिमान हर्ष इंद्रियका और हाथी अ
हवदलके समधाहू हिएाकना वीर्य तेज धात बलसत
पराक्रम और बडे वेगबलकरकै युक्त और देहसभ अंगसार
वाला और भूखवलक्षाभार मार्गशीत भयवान रनोंके सह
रनेवाला और सभइन्द्रियां यथाधिकार करके युक्त रंना
चिन्होंकरकै युक्त होताहै अरु भय किसीका न हिमानना
कालिकाअंजनवाल ऐसा कहियाहै २७ हरणीअंजन
वालाघोडा दृढमाससवाला तेजयुक्त बलवाला होताहै

सर्वसंपन्नकायःस्नस्नुग्राधसीनानपप
वनसहः स्वप्रसत्रेंद्रयोयोलिंगैरेतैरुपेतो
भवतिगतिभयःकालिकांजनोश्वः २७
स्थिरमांसस्तेजस्विबलवान्स्नस्मामहाध्व
भारसहः स्वपस्तोवनवादःसत्रहरणांज
नोवाजि २८ बलजवतेजोरूपैःप्रहीयमा
नेन्नमस्तकेवलिभिः वाहललाटपतितैत
युक्तांजननविघात् २९ मांसवपुजेवहीन
स्तावानस्थूलजानकल्कीवा दुर्वर्णदीर्घद
शनस्याकावांजनोवाजी ३० पतितैर्वतैः
पतितश्वासृद्धोविंशकेचैव गजमानुषयो
श्चोक्तेसमाःशतंविंशतिश्चपंचदिनं ३१ उक्ते
शालिहोत्रेण यथान्नंणावर्षशतंविंशद
र्षशतंगजे ।

और तथा भुवलक्षावडाभार मार्गक्लेशके सहारनेवा
ला स्वरूपवाला बढलोकीन्याई हिएाकना ऐसाहोता
है २८ शुक्लअंजनघोडा बलवेगगति तेज पहेघटजा
ते है मस्तविषे फुरडीयां सिरविटेवालोंकरकै युक्त ऐ
साजाणे २९ मासशरीरवालघटगए और जानूमोटे
होजाते है नपुंसक रंगविगडजाताहै दंतवडे ऐसाघो
डाकाचअंजनकरके होजाताहै ३० अरु दंतोंके गिरने
करके पतितका मरजाताहै अरु आयुघोडाबत्तीवर्षकी
होतीहै और हाथी ते मनुष्यांकी परम आयु सौवर्ष और
बीहीवर्ष पंजदिनकहिहै ३१

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
४९

46

शालिहोत्रमेंकहियाहै मनुष्योंकीआयु सौवर्षहाथि
योंकी छेवीया औरगौकी चौवी औरखोतेकी अठकी प
चीवर्ष ११ ऊंटकीसोलावर्ष औरबकरी भेडकी बारव
र्ष औरखचरकी वीसवर्ष घोडेकी बत्तीवर्षपरमआयु
कहियाहै घोडेकोंवारका औरमंदश सब सारपहै वर्षों
केआश्रयतेहोतेहैं १४ त्रयघटजानाचूहिवचजाणा
इसगतिनजानुकारके फेरअंजनचिन्हकोकहो १५ ये
उदरभजके फेरजन्मदेहैं अरुकिशोरवस्था छेवर्षके

वर्तविंशगवांश्चैव खराष्टपंचविंशति ११
षुनिर्घोडशवर्षाणिहाटशाजाविकेनथा
आयुर्विंशतिवर्षाणियथावाश्वतरेस्मृते ११
नष्टहयेभुहाविंशतसमाचुविर्पीयते वारके
मानुराश्वस्यञ्चवसारसमाश्रयात् १४ त्रयं
हृहिंगतिनाबाननतोञ्जनमादिशेत् १५ षु
नोस्यिताहिनायेचभांतिकेशोरकाश्का ते
लवाये श्वयोहूतेंअंजनेनलक्षुहपपने १६ सा
रंदताःस्थिराश्चेताश्चनालीनणायमस्थिताः
क्रमात्तेषांत्वयंयांतिअंजनेनपरिक्षियते १७
पात्येवसारदंतस्यवर्तामतुराश्रये जीणिव
र्षाणिनाश्चेवहेलेवेषुविनिर्दिशेत् १८ एव
मेतत्वारकाःसारंदताप्रकीर्तिताः वारका
सवदंतस्यवर्तश्यकालकोऽवाः १९

घोडेदंतकीन्याईलखनेहै सोसबकहेहैन अरुजिनांवि
षेउसनहोयाअंजनसाई प्योडीछोटीरेषीदीहै १६ औरजे
सारदंतहै सोस्थिर हलटैनहिविटचने औरअगनेन्दखे ऐ
सत्रपती जागाविषेस्थितपकेहैन तिन्हकी अंजनस्याई
यथाक्रमकरकेनाशहोतीहै १७ सारदंदवालेघोडेकाव
रदहापका ... निकसजातीताकात्रयवर्षका अरुयाल्प
वपुनहै तिन्होंकादोवर्षकाकरदेवे १८ इसप्रकारक
केवारका औरसारदंतकहेहैन वारकको औरसबदंत
वालेको चौथवर्षमेंकालकाकालाचिन्हप्रगटहोताहै १९

© Dharmartha Trust J&K. Digitized by eGangotri

सतेवरेहैचोडेके दंतोंविषे हरणीव्यंजनप्रमाणहोतेहैं जोश्र
गटऔरजोख्याकह्याहै तिसतेकनारे औरवडाशूफारंग श्र
रुश्रच्छानहि ४७ औररंगकाविरला औरद्रुगाऐसाहोवेतो व
नायाहोया व्यंजनचिनाजाणे ऊनाकीआयुकाज्ञानवाहर
नैवल औरनिर्बल ४८ तेजस्वर वालछायाकांति रंगरूप
प्रसन्नता पहेवाहरनेदेखकेके बलते प्रबल विचारके श्र
वस्था उमरकहनेयोग्यहै वालवान् हृष्टपुष्टहै ४९ इतिव
योध्यायः आयुकाज्ञान दोप्रकारका बाहरका श्रवहंदर
का शरीरऔरचिन्होंकेयोगकारकेकह्याहै श्रववर्णोंका

सममेहरणीतस्य संदंसाश्रयणी भवेत् सम
तस्थानविश्लिष्टतीक्ष्णाग्रमशस्तं ४७ विवा
र्णमतिगंभीरं कुचिमंव्यंजनंविदुः येषांवयो
विनिर्देश्यंपवहिर्देशाबलाबले ४८ तेजःस्वरा
गतिश्छायावर्णरूपप्रसादनः बलाबलवयो
वांच्यबालमध्यमवृद्धता ४९ इतिवयोध्यायः
कथितेवयसोज्ञानंबाह्यमभ्यंतरंतथा काय
व्यंजनयोगेनवर्णानांलक्षणंशृणु १ वर्णास्तु
वर्णश्चभवेद्द्वितीयोभेदस्तृतीयकश्चितस्तु
थः चित्रस्तथापंचमकस्त्वसारोवर्णप्रकारा
कथितस्तु पंचः २ श्वेतःशोणःकृष्णोहरिणो
वर्णोभवंतिचत्वारः तेयाम समानवर्णास्त्वके
सरोमवालेषु ३ हारक्षीरशशांकशंखरजा
नप्रालेयवर्णाःसिताः घ्याद्वालकसदाउमी
कुसुमबंधूकास्त्रशोणाःस्मृताः ॥

लक्षणसुणो १ एकयोरंगहै औरपीछेतेहमरारंगहोता
है दोभेद त्रयभेद वारभेदएहैकहेहैं औरपंचमाचित्रमि
श्रणहै २ चिटालालकालाहरा अथवा हरणकेसमवर्ण
पीतवर्ण एहैचारप्रकारकेवर्ण रंगहोतेहैं समरंगहोणा
तवा सिरकेबाल रोमदेहकेबाल तिन्होंकरकेजाणे जिस
रंगकाहै ३ चिटारंग फलेहचिटकेहार औरदुग्धचंद्रमा।
शंख त्रण वरफ इनोंकेसम है प्रफशोणरंग जैसालाल

© Dharmartha Trust J&K. Digitized by eGangotri

भा. खाकाशम और दहीनीकाफूल और रलाऊ इनकेतुल्यकहेया
टी. है अरुकुसुंभरंग सुरमा कोकिला वदल भ्रमरके हाथीके दां
४२ तहोनाहै और पीतरंग सुवर्ण और रजागी होइ अरु गोरोचन
केसमहै ४ इतने शुद्धके वलरंग है अरु अनुवर्णभेदकों
47 ग और विचित्र बहुत मिलेहो परंगमारा पदहै संयोग मिले हो प
कर्केहोतेहै ५ जिसकाएकरंग अनूपहैते नवाचमउ हो
रंगहोहोवे जिसको अनुवर्णजानें और भेदसबरलेमिले
रंगोकारकेकहेहैं ६ दोत्रयवारतांकेरंगोंके विद्ध औ

कुसुम्भंजनकोकिलांबुदनिभास्तंपंगनागो
पमा हेमाभाहरयः प्रदीप्तकतपगोरोचना
सन्निभाः ४ एतेशुद्धावर्णाअनुवर्णाश्चभेद
वर्णाश्चविज्ञाःसाराश्चैषांयोगेनैवप्रजायन्ते
यस्यैकवर्णरूपयस्तकचान्यवर्णानीभव
ति अनुवर्णंतंविद्यादिदंसर्वैर्विमिश्रैश्च ६
हिविचनिभिवर्णैर्निचितोयोविदुभिःसचि
त्रस्त्र ऐतोमवर्णमृदुलयुक्तःसारःसमा
ख्यातः ७ बहुत्रमलैमेहनमेछायायमुक्त
त्रिगुदप्रोथैः पद्मोपमैस्तककर्कैःसितके
सरतत्रजवालैस्तु ८ नातेस्तम्भेकेविद्ध
त्वेवम् कर्कस्यपस्तनउरसकुलेगुदसकः
लेगुदसक्यिवल्कदेशाश्च निचितःकुसैर्वि
दुभिरथवारक्तैःसरुक्कूटस्तरंगः ९

कर्केपुरकरोवे सोचित्रवर्णकहेयाहै जोचित्राहै अरु औ
रंगाके मरलमतालोककेपुरकहै सोसारावर्ण प्रगटके
हेयाहै ७ जिसकेपोटेके नवा आदीके उपरके पत्तलिंग
के उरकास्थान अरु सब गुदा और पहकमलके नलसां
गकरके पुरकहोणा अरु विरंगकेहोणावाल और माले
जिनको सोककेवर्णकहेयाहै ८ कोइकनातेकहतेहैं जो
अरुजिसककेवर्णकेघोडेका शिर माथागुदा पुटांके जा
हस्थान और समयापरहै कालेरंगके अथवा लालरंगके

© Dharmartha Trust J&K. Digitized by eGangotri

विंदुग्रोंकके चिन्हि होवे सोकल्माउघोडाकहियाहै
जिसघोडेके रोमवालकेश सिरके चिटे होंन गैरकाले
होन त्वचा लिंग नेत्र होठ सब जिनोदे ९ समरंगके घोडेमु
नियोंने कौंचपत्रक कहे हैन १० जिसघोडेके चमडा वाल
रोम पसम काठीके वाल लिंगनेत्र सब सिंदुवारश्वेत
वर्णके समरंगवाले योंकरके प्रकट होवे हैन सोसिं
दुवारकनामककेशास्त्रविषे कहे हैन ११ जिसघोडेकी
खलडामेकेरंगकोहे प्रकटुकरोडे सुइघेतवर्णके

सितरोमवालकेशा: कृष्णत्वक्‌गुह्यलोचनो
ष्ठखुरा: पनेमुनिभिर्वाह्या निर्दिष्टा: कौंचवय
शास्तु १० त्वग्रोमवालकेसरगुह्याक्षिखुरैस्तु
सिंदुवारनिभैः योश्व: ससिंदुवारकनामा
शास्त्रे समुद्दिष्टा: ११ ताम्रत्वक्तस्तु श्वेतवदन
च सिंहरोमाय: वालैकेशैश्च सितै: सिंहयो
न: समाख्याता: १२ श्वेतोल्पपीतशुक्लस्ताम्र
त्वक्चैव सोस्मृतो गौर: शुक्लोल्पकृष्णवर्णस्तु
ह्यगौर समुद्दिष्ट: १३ यस्यान्यवर्णस्यापिहिशु
क्लवर्णकेशाभवंतीहसम्भुनकेशा: यस्यान्य
वर्णस्यापिहिकृष्णवर्णा:केशास्तुवाष्पेननके
शाकोश्च १४ योवहुवर्णैः केशैः समिश्रकेश
स्तुरोमभि: कथित: वहुविधिवर्णैर्वालै: सोश्व
कोमिश्रवालस्तु १५

प्रकटुरखेसिंहके रोमांवाणुररोमावाला गौरवालनेकेश
चिटेयोंकरकेप्रकट है सो सिंहपोतनामककेप्रगट कहे
हैन १२ जो श्वेत प्रकट्योडापीलारंग प्रकटत्वचा तामेकेरंग
कीहोवेतो सो गौरवर्ण कहेया है जो चिटा प्रकट कृष्णक
कालारंगहोवे सो अधगौरा गैरवर्णकहियाहै १३ जिस
होररंगदे घोडेके चिटेरंगकेकेशहोवे सोसुनकेशघो
डाकहियाहै प्रकट जिसहोररंगदे घोडेके कालेरंगके।
सिरकेवालहोवे सोअनकेशघोडाकहियाहै १४
जेघोडावहुतेरंगके वालोंकरके प्रकटहोवे सो मिश्र।

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
५८
48

केशचोड़ाकहियाहै जोवहुतप्रकारकेरंगवाले बालों
वालाहै सोवीमिश्रवालनामकरके कहेयाहै १९ जि
सकेरोमलाल औरथोड़ेकालेरंगकेहोंए औरकालेव
वावाल जिसकेशरवहोंए अरुनेत्रकालेलालहोंन
सोचोड़ारोमकनामपंडितोंनेकहियाहै १६ योकाला
वहुतहै उनोकानाम वलरोनेकालरोमककेकहिया
है जिसकोभाषाकरमुश्कीकहतेहैं सोईलालअरुकाला
वलवर्णाहोंन सोमहीकारोमककहेयाहै सोदावी

रंकोलस्कलवर्णोरोमाक्तस्मानवालगुस्य
केशाडरः कृष्णनयनरक्तवाजीसोप्युक्तोरो
मकःप्रोक्तः १६ कृष्णाधिकमलथवेषांमपि
तःकालरोमकोनिगुतो: सचरक्तासितनु।
लोमहीकारोमकःप्रोक्तः १७ कृष्णैःपुलैः
लतजैरजविहाममिश्रकेशारात्तरगाःअ
श्वरगणाविभासखश्चकात्तकृष्णवेलो।
मः १८ नेवापिहिवहुकृष्णाःकालश्चकस
तिताःस्तनावाहाः वहुपुत्राःश्वेनश्चक।
नामानोवानिनःकथिताः १९ सितरक्तासि
ननुजैःसमैस्तुयःकृष्णकेशाडरनयनः २॰
कृष्णनकैवभवेत्सतुरश्चकपाटलोवाजी
कृष्णनक्तिनाकेलतुरहः पाटलोहयः।

रंगवालाकहतेहैं १७ कालेचिट्टेवालोंकर्केयुक्त औरलाले
मिलेवालोंकरके मिश्रकेशाचोड़ाकहियाहै औरजोस्क
रकुश्मरंगकेसमवर्णो औरत्वचाकालीया अैसेचोड़ेको
अश्वनामकहेहैं १८ अरुसारीवहुतकाले कालाव
केनामचोड़ेकुहेहैन औरजेहे वहुतविटेहैं तसेश्वा
नांलेनामचोड़ेकहेहैन १९ जोचोड़ाविटा अरुलाल
कालेवालोंकरकेयुक्त समभतलाहैं औरकालेकेशहैंव २॰
नेत्रलवाहोंन जिसके सोक्ककपाटलचोड़ाकहियाहै
औरजिसकीत्वचाकालीहोवे औरचिटेलालरंगके

© Dharmartha Trust J&K. Digitized by eGangotri

वालरोमहोन सोघोडापाटलनामकरकेकहियाहै
औरजोवक्त्रचिटेरंगकेवालोंवाला सोईहोवे सोसु
मनपाटलनामवाला घोडाकहियाहै २१ जिसकेवक्त्र
नलालरंगकेवालहै अरुयोडेचिटेहैन सोरक्तपा
टलघोडाकहियाहै जोपीलेरंगका अरुकालोंवा
लोंकरकैयुक्तहै सोनिश्चयकरकैचक्रवाक संज्ञानाम
वालाकहियाहै २२ जोघोडागौरवर्णका कालेकेश
अरुवालोंवालाहै सोअंजनकेशकहियाहै अरुजो
घोडापीलेलाल श्वेतवालोंकरकैयुक्तहै सोसिद्धार्थ

श्लोकः शुक्लैःसपत्रवक्त्ररोमभिःस्यात्सुमनःपा
टलोवाजी २१ वक्त्रभिश्शोणैस्तनुजैरल्प
सितैरक्तपाटलोवाजी पीतःकालैर्वालैः
सोऽनुक्तश्चक्रवाकस्य २२ कृष्णकेशवालै
रंजनकेशस्तुरंगमागौरः तनुजैपीतैर्गौरै
र्वालैःसिद्धार्थकःप्रोक्तः २३ रक्तैःपीतैरसि
तैर्विपुलोवयोभवेद्देवः असितान्यसुतः
शोणःसहस्रश्यमतेबुधैः २४ श्वेतैःपीतैः
स्तनुजैःकालनकमिश्रकेशरोयस्तु से
यःसर्वजनीटःपीतश्वेतोतनवारूः २५
हरिरक्तपीतरोमारक्तनवक्त्रःकुरंटकःसो
स्युः हेमग्रीवसवर्णोरक्तनवककद्रुरोन्ते
यः २६

कनामकहियाहै २३ जोघोडालालपीले अरुका
लेवक्त्रहोन सोविपुलनामहोताहै जिसघोडेके
कालेश्याोरे अरुलालहैं सोबुद्धिवानोंनेसहस्रश्शक
हियाहै २४ जोघोडाचिटपीलेवालोंकरकेयुक्तहै
नवाकोलोअरसिरकेवालरलेमिलेरंगके और नि
केश्वेतपीलाहै इसकै सोसर्वजनीटसंज्ञानामसनाण १२
जिसघोडेकेहरेलालपीलेरोमवक्त्रवालाल सोकुरंट
कघोडाहै जोहेमकीग्रीवाकुपाडीकेसमरंग अरुलाल
वमन्ना सोकद्रुवर्णकाजानो २६

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा० घोड़ेयोंके समरंग श्रेष्ठ हैंन जैसे सुंदरकांतिवाले
श्लो० स्थिरते चिकनेशरीरवाले हैंन तिनावर्णोंकेबीच चिटाश्रे
५९ ष्ट है तिसकारणते सोध्रुव है जेड़ा कदीबीनाशनहीं
होंदा १७ और सभनेरंगोंविषे श्वेतवर्णकासंयोग
श्रेष्ठ कहियाहै जेड़ा श्वेत चायकेविच श्वेतदरदहै
तिसकारणते श्वेतवर्णबहुत श्रेष्ठ कहियाहै १८
कोइक कवी ऐसे कहता है बहुतेकहनेकरकेक्याहै
घोड़े जिस२ वर्णकेहैं उसीरंगोंकरकेनामकहेहैंन औ
रजिसवस्तुकेतुल्यवर्णहोवन तिसकेहि नामकरेनाम

सर्वेवर्णाःशस्तास्तुरंगाणांसुप्रभाःस्थिरा
स्निग्धा तेषांश्वेतःश्रेष्ठोयतोध्रुवश्चाव्यय।
श्चासौ १७ सर्वेषांवर्णानांसंयोगःश्वेतसं
युतःशस्तः यस्मात्सितेपिण्डलस्तस्माच्छ्वेत
प्रधानतरः १८ किंबहुनायेनाकास्तुबहा
यावर्णनामभिःकेचित् इष्यस्यप्रसद
शास्तन्नामानस्तेतेया १९ सर्वेषानाःश
पीतोहरयःकनकप्रभाःसेंदूरहंसाय
मस्यवालाःकर्काःश्रमूलनणाविसोः २०
शुकपत्रनिभाभानोःकिंशुकवर्णाहयाकृ
नामस्य श्वसिताभ्रनिभावरुणाःसरूप्तद
वर्णाःकुवेरस्य २१ एतेवर्णारत्नाःशुभस्वरा
वर्मैकायमस्वास्थ्य।

ताणे १९ देवतेयोंकेवाहनकेघोड़े जोकेवर्णकहते
हो सारेश्वेतरंगकेघोड़े ब्रह्माकेहैंन इंद्रकेघोड़े सुत्रे
केरंगकेकहेहैंन यमराजकेकालेरंगकेघोड़ेकहेहैं
औरविलोकेघोड़े कर्कपद्मके समरंगवाले औरशुभ
चिन्हवालेहैंन २० सूर्यकेघोड़ेतोतेकेफंगोंकेबरा
बररंगवाले हरेमलेरंगवालेहैंन और अग्निकेघोड़ेपा
लासदेफुलकेसमरंगवालेहैंन वरुणकेकालेरंगके
बदलकेसमरंगवालेघोड़ेहैंन कुबेरकेकमुदकेघोड़
वानापकेतुल्यवर्णहैं २१

© Dharmartha Trust J&K. Digitized by eGangotri

रंगो रंगों वाले घोडे शुभ हैं सर्वआवर्तों दक्ष वनि
नोट और रंगों देवतियों के भिन्न २ वाहन कहे हैं ११
वर्णाध्याय: देवताओं के वाहन ये घोडे और य
ज्ञ के योग्य घोडा परमात्मा अभिषेक करने योग्य और उ
पोषाश्च १ अरु छत्र वाहन योग्य न हि वाहन योग्य वाजी रा
जा सेनापति का घोडा वजीर कार्तिके के वाहन योग्य २
रंगों घोडियों के जो शुभ निशान होते हैं लक्षण कहे हैं
सो भिन्न २ कहता हूं ३ जे उपद्म कमल कियारीयों
के सम रंग वाले और कंगणी के दाने वा गुरु वर्ण होते।

एतेषां देवानां पृथक् पृथक् वाहनाः कथिताः ११
वर्णाध्याय: देवोपवाह्यं तुरंगं यज्ञार्थ वा
यतः परं परमात्मवाभिषेकाः पुरोधीयत
थैवच १ मानार्हं च वाप्यवाह्यं च वाजीराजेन
थैवच सेनापतेरमात्यस्य युवराजस्य वार
ने २ वाजिनां सप्रवक्ष्यामि शुभनिश्चांके पृथक्
पृथक् ३ यः पद्मकिंजल्कसमानवर्णः क
गुफलाभः शुकपत्रवर्णः ३ कोल्पलाभः
शिखिकंठनीलो वैदूर्यवर्णो नयने च यस्य ४
रक्तास्तु पीताश्च सिताः सिताश्च भवन्ति वाय
स्य हृदयस्य पादाः ताताः स्वरक्तान्न तु नाल
जिह्वः सलक्षणो हि प्रशस्तविमुखो धीरः ५ शु
भ्रास्तनं यस्य भयेन दीनाः क्लिष्ट नितंवः एवं व
वः स्वरगः।

के परके सम रंग है रंग और लाल क
मल के रंग वाले और ये मोर के गले के तुल्य काले रंग
के हैं और वैदूर्यमणि के वर्ण के रंग हैं नेत्र जिसके ४
और लाल पीले चिट काले रंग के हैं सब जिसके लो
मा तिसा वाले हैं अरु लाल रंग के हैं मुख तालु जीव
निन किया और सुंदर लक्षण और सो ए हैं न और प
वित्र धीरज युक्त ५ उसके पाछे की कर के है हाय वक्र सरण
ने घोडे हैं हः खी हो के खडे होना तैं हैं न सो मल मूत्र।
को त्याग देते हैं।

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ टी॰ ५० ऐसा शोभावाला देवा ध्यकहियाहै ९ कालेमेघकेरं
गकी शोभावाला औरचित्रैरंगकेमंडलोंकरकेभूषित
श्वेतघनधौतेहाथवंशौ औरचित्रैनेत्र औरपवित्रहै पू
वीर औरसिंह औरहाथीकेनखशाहूहिणकलाजि
मका ऐसाजोगणध्यमेयत्नकेवालेकहियाहै १
ककेजोहै जिसकेसमस्तअंगकमलकेसमहै औरगति
स्वरवालकातिसभाव सदाहोए औरश्रेष्ठस्वरग्राव
नेरत्नाकरकेघ्रकहै सोघ्रोहितने ऐसाजोगवाहा।

मूर्त्तंगरीषंचसमुत्सृजेतिश्रीमानसदेवा
स्वरितप्रदिष्टः ९ कृसांबुसमःसितमंड
लैर्योविभूषितःश्वेतशफःसिनाक्षः शूरः
शुचिःसिंहगजेंद्रनादःस्यादृष्यमेयोविन
यप्रवाजी १ ककैःपद्मनिभोगःशुभंग
यस्वरगतिश्रुतिमान्तःकार्यःसमुद्रोयाक्ष
शुभलक्षणवन्तुमेधत्रः ८ श्वेतरक्तकृष्णसंह
रितंवानमकोवनश्चचेष्टश्रुवर्णोंमेदेवा
विचित्रवासासमेतवा ९ पद्मःकमादेकंत
मेघरात्रैमेधावनेवालघुरीषमूर्त्तं शुभौ
ष्ठसुनावानत्रनालजिह्वंभद्रमहावेगमगु
कलंच १० छायाप्रमत्तंसमतिसमभद्रुति
महाबलंस्थिरगतंत्रकदेवताए ११

नकारना ८ श्वेतलालकालासवजा ग्रथवानपैहो
ऐसानेकेरंगकीन्याई शुद्धग्रत्रुवर्णोंलियाहोयाऔरग
ग्रथवाविचित्रवस्त्रांरंगवाला कमारयेउकेहेन ९ पहें
नेउकेहेन रंगोनेपककोई शोभवुद्दिवाला औरमलमु
रयोगकारनाहै ग्रहसुंदरलालवर्णोंके गोष्ठसमावशुं।
नाल जीवाजिसकीया औरभद्रकल्याकककर ग्रकवने
वेगवाला सदाशाहूनिमका १० सदाछायाप्रभाकाऔर
दशमतवगसरूप श्रेष्ठवदिसदाकोतिश्रामाऔरबल ग्रहे
स्थिरै विकनवालग्रकप्रती ११

50

© Dharmartha Trust J&K. Digitized by eGangotri

अहलत्तणवाला मणकोवेगालगानेवाला औरसुंदर
हैनमेघकापटा गतिवाल अरुआवर्तआगुवाला और
ऐदकेसहारणेवाला औरप्रसिद्धअंगोवाला सदाश्र
तीकोणजिसके १२ आजानेयजातिकानिरोग्य जिते
द्रिअप्रमस्वभाव बहुतसाराथिरहैन अवस्थाकरकेथि
नहबैद्धबुटेहोपअंग अरुवडादेहवाला १२ सभप्रका
रकेयोदोषहे तिनोंतेरहित औरसभशुभलत्तणोवा
ला सुंदरस्वभाव औरअंगतिस्कुप्रतिनहिहोते और
श्रेष्ठअंगपलेपनवाला सूरवीर १४ ब्राह्मणजाति अथ

शुभलत्तणमनोज्ञेशुभेषुइंगुभंगतिशुभा
वेनं आशुमन्तंतानेसुविभक्तांगशुभानू
के १२ आजानेयमरोगंजितेन्द्रियंअप्रिक
महासारं स्थिरवणायिनवयस्यसंसहतांग
महाकाय १३ रहितंसर्वदोषैः सर्वैःशुभ
लत्तणैःसमायुक्तं सुमनसंविदनांगंप्रि
यगंधविलेपनंशूरं १४ ब्राह्मणमथवा
क्षत्रियमकर्कशांगंधमतिरूपं कुर्याद्धय
राजानंताहशमुपरीधकेराजा १५ ईद
ग्विधगुणायुक्तेनयनमनोनंदनेसदाहृष्टे
तृणबुनापरमाश्वसंवेरंगेष्टदेवमयः १६
यस्यान्तेरगस्यभवेह्वणोहयमकेचहूवणाभ
रकंवालाकाभंस्थेनंसर्पणोसोमनिभं १७

वाक्षत्रियकौ धीलअरुगुणपवित्र सुंदरसुगंधि सुंदर
उद्दि अरुरूप अैसाघोडे यांकेविषे राजा जिसको अैसे
राजालत्तणोवालेको ···· घोडेयोंविषे सरदारवणा
वे १५ इसतरांके गुणोंकरकेयुक्त औरनेत्र मनकोआ
नंददेणेवाला अरुसदाहीप्रसन्नमनलावा १६ अव
परमाश्वकेलत्तणसुणा सभदेवमय अंगोंकरकेयुक्त
जिसघोडेकेरंग सोतनके होवे सुर्यअरुचंद्रमाकीसा
ई अग्निवालाल याआनकालकेसर्पकेसम औरचिटा
मणवेद्रमाकेरंगकोसाई १७

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा॰
हो॰
५१

51

सोयहहेजोअ परमात्मस्तुतियोंने सूर्यचंद्रमायेंतन्मति
मकाकरियाहै औरब्रह्माय्यीआदिलियेदेवताहै सो
तिसकेसभअंगोंकेविषे निवासकरतेहैं १८ यहेनृप
नामकरकेजोहै तिसककेसहायकरे जोदेवतेयों
कायुद्धविषे जीतीदाहै औरयज्ञस्वर्गकारस्तादै पुण्य
पवित्रहै और सोराजेयोंको परमश्रेष्ठवलहै १९ जोनि
श्चयकरकै इसकोजानदेहैन अरुउसकोजानकरकै यत्न
नेपूजाकरे सोराजाधिराजहैइकेसमपृथ्वीकास्वामी।

सोमार्कयोःप्रसूतिर्यएवपरमात्मपद्धतेःक
थितः ब्रह्मादयोस्यदेवाःसर्वेंअंगेषुनिवसं।
ति १८ नृपोहोषजयोधनदेवानामहवेसहा
यतःस्वर्गपथःपुण्यःपार्थिवानांपरंबलं १९
यएवमेनंजानीतेज्ञात्वायत्नाद्यजनयेत् स
राजराजोभवतिशक्रवत्पृथिवीपतिः २० शु
एवाभिषेकान्तरांकीर्तमानमतःपर २१ मु
क्तावलीशंखहिमेंदुसन्निभमहाबलंमहाम
पार्श्वशायिने ज्ञातेसगंधस्रक्कलोद्भवंशुचि
शुभंप्रभात्रुकमनोवरूपिणा २२ प्रमानतो
दुष्प्रभनालदंतिनेजोवपुःसारवलेरूपंते
सत्वानितेदृष्टिमनोभिरामेलिहेप्रभावतेग
तिसौरव २३ श्रीमंतेधुतिमंतेजितेंद्रियंस्पो
घिकमहाकाये

इंद्रहै २० अबजोराज्याभिषे
क योग्य होइकेलक्षणकोसुनो २१ मोतीयोंकीमाला
शंख बरफ चंद्रमाइनोंके वरणरंगवाले को बडेबलवा
लेकोकल्याणमूर्तिवालेको अरुयावनीकरके निरूपनहि
वनेगावालेको लमावाला सहदगंधि अष्टकलविखेज
न्म पवित्र सरवीरश्रेष्ठ प्रीतीकोणवालेको अरुवरूता
रूपवालेको २२ औरप्रभमन्दरामस्या औरठनालूदंतवाले
को औरतेजसेदृष्टमावबलमनदृष्टिइनोंकरकै प्रके
और मनको सुखदेणवाला हर्षवाला औरशुभहै।

© Dharmartha Trust J&K. Digitized by eGangotri

आवर्तवाला हो औसेको और शोभावालेनूं कोतिवा
लेनूं जितेंद्रियों स्वभाववडे शरीरवालेनूं औसेघोडे
कों युवराज टिकेके राज्याभिषेक योग्य विखेकरे २४
फटक वर्फ शंख रूपा निर्मल और चंद्रमा केतुल्य वर्ण
और नवीन दाडूनिके फूल मुंगा प्रातकालके सूर्यकेसम
रंग २५ भ्रमर कोकिला सुरमा सर्प वदल हाथी इनकेतु
ल्यवर्णशोभा और स्वर्ण मनशिला नागी होइ अग्निकी
शिखा लाटवगुरहो ओडेनूं २६ और मनके हरणेवाले और छ
रहाथीकी न्याई चाल और यथार्थ भागवाले अंगसदाही

युवराज्यस्यलक्षण्यस्यवनमाभिषेकंहयंकुर्यात् २४
स्फटिकतुषारशंखरजितामलहारशशांकस
विभं अभिनवदाडिमीकुसुमविद्रुमवाल
दिवाकरोपमं २५ अलिकिलकोकिलजनभु
जंगमेघसमप्रभं कनकमनःशिलाज्वलित
वह्निशिखासदृशतनुरंग २६ मनोहरंसिंहग
तेंद्रगामिनेविभक्तसर्वांगयवंशदायगं स
स्निग्धरोमाणमस्फुकेश शुचिंतवान्वितंतवि
धमंतुदसंने २७ वपुपकलनेदांतश्वरंमेयावि
नेयभागुकंशुभंगायशुभपुंडुंमात्रामसंवाजि
नंकुर्यात् २८ अथकमथवापाटलमरिष्ट
कपीतवर्णमथगौर रोमकमथवासारवि
वंवाक्रौंचपत्रवा २९ सखुवारंटकपादसूर

जितेंद्रियस्यशीलवं ॰

सभनेवे अगेचलना संदर्शिदेखिकने वालरोमसंदर
अस्तकेकल और पवित्र वेगवाला तजीजाति मेघकी न्याई
हिनकणा २७ अरुस्वामीके अधीन श्रेष्ठकुलका इंद्रि
यजीत शूरवीर बुद्धिवाला अरुसुंदरकोनिश्चक शुभ
श्रेष्ठगंधि मस्तककापटा औसेघोडेकों मानदासाथ
ही रहणवालाकरेराजा २८ सब्ज्वर्ण अथवा पाटक
अरिष्टरटके रंगकापीला और वर्णकारोमकसारवि
ययंकोंचपत्र पदेसभपरिलेकदेहैन औरहोलिमरव।
करके वलनेवाला अरुसुंदरपकेवाल शूरवीरवहादर

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ जिनैंद्वि मूल संध्यावाल पृष्ठ जिसकी अरुहोरने केणी
टी॰ छैनद्विचलना वडीवालवालाहै १॰ जिमैंयवडाअष्ट
८२ विकट वेड करेउवाला मनके हरनवाला प्रसिद्ध सो
वी भुजनाग्रकीमाईहै राजाजिसघोडेको गेपवाग्रका
52 तेलकेस्थानकरे ११ जो शुद्धस्फटिकेरंगकीमाई विद्रु
लाल काला सवजरंगका शुभश्रेष्ठछाय प्रभाकाभे
द प्रगटजाति श्रेष्ठ अवस्थावाला श्रेष्ठ घोडा मंत्रीका
वाहनकरे १२ योविदेरंगदा कमलकीसुगंधि गौरव्रा
मकेरंगके लवातालु मुखसंव जिसके अरुतेजवा।

शुभगाश्चिंतसल्लक्षेनाश्वेवंष्टष्टांगशीलेषु १०
अश्वाश्चिंतेप्रकृष्टेविकटोपाङ्गमनोहरस्यातं
माना ख्येश्चसमंतगोवाग्रहयकर्यात् ११
शुद्धार्कैनिभंश्चेतलौकेशस्फटिशुभच्छायं ला
तेवेवंयस्यहयंसचिववाहनंकर्यात् १२
श्वेतः पद्मसंगंधस्ताम्रत्वकूतालवदनखुरः
नेत्रस्तीशुभनादः सहयः सातकोल्पतेः १३
शंखच्छिन्नसलाटे वर्णारः सप्रदक्षिणाव
र्तः केलहंसस्वरोयोयसस्मान्नाहिकोल्प
पतेः १४ सोवर्णपृष्ठवर्णोमेहाललाटस्व
नः शुभच्छायाः मणिवैडूर्यनिभाक्षः सा
दीर्घपुच्छोनेत्रैराद्यः १५ जोमूलवर्णीघन
वाघ्रदेवीमधास्यगंधोगजेंद्रसगामी ।

ला श्रेष्ठगाड्वाला सोघोडाराजाको ११
श्वेतघोरेकेमस्तविषे वारंवार प्रदक्षिणावर्तचौरे
वालेहोन अरुशब्दकरतेहोय हंसकीन्याई हिनकणे
वाला सोघोडावीराजाको सेनापतिककनीयोगहै १ ४
सवकेफलकीन्याई वर्णकरकेयुक्त अरुवडाविसा
लमस्तक और शब्द अरुशुभछाया अरुवैडूर्यमणिकी
शोभावाले नेत्र और वडा लंबपटवालानेत्रयुक्सा
ऐसावाहककरनेहै १५ जोघोडामेह्यवदलकेरंगका
अरुवदलकेगाजेनवागर हिनकणऔरमखीरहत।

© Dharmartha Trust J&K. Digitized by eGangotri

समगंधिवाले औरहाथीनें हंसकीन्याईंगतिचलना
औरहारपुष्पलेपन सुगंधिप्यारे जिसको सोघोड़ा अ
श्वराजकहियाहै राजाकेवास्तेयोगहोताहै १९ जो
घोड़ा इंद्रगोपकीछववहारीकेसदृशस्वरंगकाहै और
कमलसमानरवागरनेत्र सोराजाश्वकहियाहै औरयोशुद्धहै
सुंदरगंधिशुभशाद्र सोवीघोड़ाराजाकेवास्तेयोगक
हियाहै १० जोलालमोतीकेरंगका अरुवैडूर्यमणिके
रंगकियाअखी औरसनेपासकेकेशपाश शिपीयाके
परविषें विस्तारवालीयाजिसके १८ उससेघोड़ेकरके।

प्रियस्य मालस्य विलेपनस्य सोश्वस्य राजोऽस्य
पवाहनस्यात् १९ यः शक्रगोपवाहस्वाभः।
पाशवतलोचनः सराजाश्वः यश्चशुचिःशु।
भगंधःशुभनादः सोपिनृपवाहः १० शोणः
प्रवालवर्णोयोमणिवैडूर्यवर्णनयनोश्वः
दक्षिणकेशांतस्याःशुक्तिस्साहोयलायस्य १८
तेनतुरंगेणरणेनिःशेषंरिपुबलंविनिर्जि
त्य प्रमुदितनिजबलसहितः स्वपुरोन्टपति
समायाति १५ हेमनिभोऽरविवर्णोहरिण
गतिर्हरिणलोचनोहृष्टः तस्मलेवालेश्या
वितसिद्धिन्तियःसोपिराजाश्वः ५० श्वेतानि
वरणमस्तकशुक्लानितुरगस्ययस्यजायते
नदीमुखनामासौतुरगःसर्वार्थसिद्धिकरः ५१

रणयुद्धविषें वैरियोंकीसभसेनाको जीतकरके रा
जाप्रसन्नमन अपणीसेनाकेसाथ जैसेहैतैसही अ
पनेको आवताहै १५ जोसुवर्णकेरंगकेरंगका हरिरंग
का अरुहरणकीन्याईंगति अरुअक्ती औरसदाप्रसन्न
औरवड़ेवायुकेवेगमें दौड़नेकोइच्छाकरताहै सो।
वीराजाश्वकहियाहै ५० जिससेघोड़ेकेसवमस्याशु
क्लपैरेचिटरंगकेहोवें सोनदीमुखनामहै सोघो
ड़ासभकार्यकीसिद्धिकरैहै ५१

© Dharmartha Trust J&K. Digitized by eGangotri

पा॰ टी॰ ५३ जोपर्वतनकीन्याईउंचा अरुवडूनत शत्रूकाछिनकरणा व
डीवालशूरवीर औरराजाको आनंदहर्षकरताहै अरु
आप्तसन्नपराक्रमवलकरयुक्तहै जलकेफेरकुंवावयूं
डनकीन्याई वक्रकेफिरनेवाला अरुयुद्धकालमेपरा
क्रमावाला सोऐसाजोउंवी राजाधकहियाहै ५२ जि
नाजोदुर्याके देहकीउचाईहाथीकेवरावरीहै सोवसमु
द्रकीन्याई दूरोंवदेफेरेवाले औरदुहेगकर्के वोदरकीन
री छालमारकेचलना देखनाहाथीकीन्याई औरशत्रु
सेजपती हाथीनगारे वदलसिंहरनकेवरावरशब्द।

यत्सपर्वतमानोस्लेनतिहयोमहाजवः स्वरः
अभिनेदतिराजानेश्रावणान्सलवलसंपन्नः ५२
प्रतिलोमसलिलपायीमदगन्धसनोनेद्रोषः
येषांदेहमयुवतिगजसमाः पादाः समुद्रोप
माः ५३ उद्वेगलुनमेववानरसमसाहारण
प्रेक्षितं शरवकौवगजेन्द्रडमिद्यनव्यात्रेभ
तत्स्वराः ५४ रक्तोभिहरिणाथिपप्रतिवि
भैर्योत्रोपमैर्वाहभिः सावर्तैस्त्रशुभैः प्रधा
नकुलजाः स्निग्धपवर्णप्रभाः उद्धान्ताप्रिय
दर्शनाश्रशुवयः शामेमृगंगयेस्मयेयस्मात्सेन
पराजविनमखदाः सात्वाहिवेनेदशाः ५५
यर्भेरमतोलोकोनिश्चतिस्तत्रमस्थानोनभ
वेत्पमर्गोवावर्षतिकालेचपरजन्यः ५६

चोलना ५५ औरजेनेत्र प्रहदराणकेसम औरचोरकोयांछ
नाकीसोभाकेतुल्यवाहू औरश्रुभआवर्तीकरकेयुक्त
औरश्रेष्ठकुलविषेजन्मेहोय औरसंदर चिकना चिदारं
गतैर कांतिजिनाकी ऊठकीन्याई अतीजिनके देख
तेमसोता पवित्र औरश्यामसमाहारसगंधिवालेपटे
मनादिककेहंहै सेधान्यहै जेऊजयपराजयनसुख
रनकेदेनेवालेहैन अरुदेशमसुखकरके सम्पदि।
केकेवधतारे ५५ जिसस्थानविषेपदे हयराजशुभ
श्रेष्ठलक्षणावालेघोडे रहितेहैं उसदेशविषे लोक

© Dharmartha Trust J&K. Digitized by eGangotri

अपले १ यमें मुश्कर रहनेहैं अरु तेयोंमें अश्वों की हदीहो तीहै अरु अपयागदेशपइवनहीहोता गेरवदलयथार्थ वेलमें वर्षतेहैंन ५८ तिसकारणतेराजा इसप्रकारकेश इपलक्षणकर्कै तोयुक्तहैंन असेघोडे देशविषैआपही पयांको फलगप इनोंकेहैंएजनकेविषिमें ५७ जिस घोडेकेकणिकालेश्वेतमिलेरंगकेहोए अरु केशवाल। विटेरंगके अरु मध्यविषैपटाश्वेतहोवै इनोलक्षणाके कैयुक्त असाघोडेसभनावोंउविरेवेविख्यातस्यावकण कहेहैन महाइयराजावाहोपवाह्याध्यायः राजाके।

नविपद्यंतेनरकुणाः स्वहा जीवंतिवाजिनो नि
रुजः इयताजाइत्येतेवंसतिशुभलक्षणायत्र ५०
नस्माज्ज्ञानानंतरंनैवविधिइपलक्षणापेता
न गंधैर्माल्यवह्निभिः प्रश्नयेत्रागनानिषये
यणावैः कर्णैः सितैः केशैः शुभ्रैः श्वेतैः सवाल ५९
कैः सर्ववर्षेषुविज्ञेयाः श्यावकर्णास्तरंगमाः
इयराजावाहोपवाह्याध्यायः राजोपवाह्य
कश्चित्प्रदेशानधुनाश्रृणु प्रदेशान्वाजिदेह
स्यामोम्यवेतिविभागतेः १ नासोज्ञानातिमू
ढात्मालक्षणंनचिकित्सितं प्रमाणंत्रिविधं
वैवृत्तेत्वाणिचयथाक्रमात् २ जिह्वाकंठनिब
द्धातेयाहाविंशदंगुलानिगुणैः अयत्नालक्ष
रंगाणांजिह्वायाउपरिनिर्दिष्टं २ जिह्वाया

श्चाधस्तानस्तनापीठस्तनोहनुनिबद्धाः

वाहनयोग्यघोडेहैं सोकहेहैंन अबघोडेकेदेहविखे जोजोअंगस्थानहैं विभागकैके जोनहिजाननाहैसो मूर्खवैनइतिजिह्वाकिचिकित्सालक्षणकों कैसेजानैंना। हिनानुते प्रमाणत्रयप्रकारकाहै अरुतेत्रयीवयरैय थाक्रमतेजाणे १ जीवगलेकेविखैवद्धीहोइहै अरु बत्तीवालेयोनेवत्तीसअंगुलीप्रमाणकहिहै घोडेयां कीजीवाकेउपरलालकहियाहै अरुजिह्वाकेहेठस्तना पीठकहिहु अरु तिसविषैअंगुवालांवद्धीयांहोइयां। हैन तिनांके अगलेपासेविषै दाढांवद्धीयांहोइयांहैं

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा॰ वारे हैं अरु उपर विषे ४ अरु हेठके औरउपरके दंतवा
ह्रो॰ रा कहे हैं न अरु दंतोंके ऊपर पड़िन उन्नतानाम दंतवृह
५४ नेको कहते हैं ५ अरु जो दंतोंको ढकणेवाले हैं तिनां
54 को ओठ कहते हैं तिनाके दोनो पासकी संधियों विषे
वन्नीयां होया होउ किंवा स्ककणीयां वाकहिया है ५
जो हेठका ओठ है तिसके हेठ चिबुक ठोडी होता है अरु
उपरले ओठके ऊपर अथाणा कहिया है अरु तिसके ऊपर
मे घ्राणनाम कारके कहेया है अरु घ्राणके वर्त्तीयों विषे

दंष्ट्राललामाममेथ अथपरोतनाखनस्तल ४ अथपरो
नरेनोर्दंताश्चजनानितेनो द्वादशैव विनिर्दिष्टाः ३
परिष्टाद्दंतानां विनिर्दिष्टोऽन्नगोष्ठाजः ५ ओ
ष्ठौत्रविनिर्दिष्टौ दंतानाच्छादनौ तयोः पा
र्श्वे: ६ सृक्वौ चैव निबद्धे नरगाणां सृक्कणी
कथितौ अथरोष्ठास्याधल्लाच्चिबुकस्यादुप
रि चोत्तरोष्ठस्य ७ परिकीर्तितं प्रगाणं तस्यार्ध्वे
घ्राणस्तूक्तः घ्राणस्य तु पार्श्वोस्यातेयेना
साघुटौ तत्स्मृतौ ८ घ्राणस्य वोत्तरया
तौ घोणांते विजानीयात् घोणापार्श्वगते स
गेउपार्श्वे प्रकीर्तितो निघुटौ: ९ मध्ये नर
योः प्रदिष्टो नरगाणामस्कृपानोत उपरीत
योल्वयानयनेलावनयोच्छादनानि वर्त्मानि
अत्तोणां पक्ष्मलं मध्ये कृष्णां विजानीयात्
नदृष्टिमंडलेसु वर्त्मापरिक्षिनेन नयनरूपं १

नासापुट कहियते हैं ८ अरु घ्राणीयोंके औरघ्राणके मध्य
मे घोणानाम स्थान जाणों अरु घोडेकी घोणाके वर्त्ती
विषे गेरस्थानवनगोने कहे हैं न ९ चोटियोंके गढे
के वह्नकारमे अस्कपान कहे हैं न तिनांके ऊपर वि
षे अत्तीयां अरु अत्तीके ढकणेवाले वर्त्म कहे हैं न
१० और अत्तीयोंके कनीरचिटे अरु वीचमे काली
यां नाणलेव उसकेवीच दृष्टिमंडल है अरु वर्त्मो
के ऊपर नयनरूह दहे हैं न ११

© Dharmartha Trust J&K. Digitized by eGangotri

हैं नके ऊपर भ्रुवटै हैन अह अपांग हैन अह अलीयोंतेना
सोकेमध्यविषैं कनीनकाजाणो दोउयोंके १२ और भ्रुवटै
और स्कववतिन्हांदे वक्रकार अष्टवृद्धिवाले योंने ललाटके
देयाहै ललाटकेऊपरस्कववकेदेयाहै अहदोनोंकर्णोकेम
ध्यशिरजानलेवे १३ अहमध्यातिसकेहिगुणश्रितहै अ
हतिसमस्तककेवल्लीयोंविषे कर्णहैन तिनोंकेकन अह
शंखोंकेमध्यविषे दोउयोंके कटस्थानजाने १४ अहशं
खकट अहअपांगके पासस्थितहैन औरदोउकेशंखऔर

स्थानं भ्रुवोरन्तयोपरि वाह्यचाक्ष्णोरपाङ्गौ ना
माह्यौ रनेरन्त विघातकैनेनीकेषस ११ भ्रुवल
वयोमध्ये षं ललाटमिन्नु चाने शाले: स्ववसुप
रिललाटस्थानं पिरम्ब कर्णौ नैरं विजानीयात्
स्थान्मस्तकेनराश्रितमथ्यकर्णौ पार्श्वयोस्त। १६
स्स अथकर्णौ शंखयोरनेरन्त विघातकौटौन
रगाणां १४ शंखौन विजानीयादपांगकट
योःसमीपस्थौ शंखकटयोर्विघातउपविष्ठा
हान्निनःस्थितौ चाटाम् १५ हनुवक्रे विजानी
यान्हनुयोर्वीहातनस्थापि अथहन्वोगलनाडाः
संधिस्तनिगालरध्यतेनहेः १६ पार्श्ववट्ट
तस्थापि कर्णयोःखलु विहविघात मन्येत
कण्ठनाडास्थापार्श्वयोरशयास्तथाशिरसः २
स्तनरमणयोर्यस्थानां ग्रीवांसविजानीयात् ।

कटकेऊपरसंचाटानामस्थितहैं १५ अहखविषे हनुजाणो गं
डस्थानोंके बाहरहोतियाहै दोउयोंके अंगकेजानने वालि
योंने हनुअहगलकी नाडियोंकी संधीयोर निगालनाम।
कर्केकोहयाहै १६ औरदोउयोंके कनकेपीछे वलीवि
खेनिश्चयकर्के विडनामस्थानजाणो गलकेदोनोपासे।
कीयांलाडिस्थामन्याकहियाहैन तिनोंके दोनोंपासे अम १०
करनेहैं अरतिनांदेऔरशिरकेमध्यविषैग्रीवास्थितजाने
औरदोउकेअगलेपासे नवहोतीहै अहनव अहग्रीवाके

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
५५

55

मध्यमें काकसाकहिहै घोडेके १८ अथवा नेत्रगलके
पासहै अरु काकूदकाजो जिसको मत्रक कहतेहैं तिनोदो
नोंकेबीच काकसाकहीहै आसन और काकसके मध्य।
घोडेके ककूदजाणे १९ घोडियोंके अंगोंके जाननेवा
लेने ककूदकेअगे आसनकहियाहै अरु तिसके अगे
पृष्टकहिहै तिसउपरंत घोडेकेपृष्टवंशहै २० अरु अ
सककूदविषेवहेहोयेन अरु असमूल तिनोंके आश्र
येहैन दोनो उनोपास घोडेयोकागलहै अरु पंडितो

नेत्रपुरतोवहःस्यान्नेत्रयोःकाकसावहयोः १८
नेत्रककुदोश्चमध्येतु स्थानं काकसाकथि
तः आसनकाकसयोरपिमध्येककुदं हयस्य
याद्भुयात् १९ आसनमपिनिर्दिष्टं ककुदःस
मनंतरंप्राज्ञैः अथपृष्ठं जानीयात्ततो भवेत्पृ
ष्ठवंशमपस्य २० अंसौ ककुन्निवद्धौतथा
मूलाश्रितावेतौ प्रोक्तौगलोहयानांतिउ
त्त्वनिगालकंदयोर्मध्ये २१ वक्षोगलयो
र्मध्येकंठकेनादयोवृतः एष्टनसोश्चमध्य
क्रोडक्रोडारधःस्थितोवाहू २२ वाह्वोरपस्त
नस्थापितानानीमेविजानीयात् अभ्यंतरे।
वलाक्रोः किणाञ्जानावोरपस्त्रनोजंघे २३
पुरतेनैतविज्ञेयेकलेनथापृष्ठतस्थेव नेकू
वाउपरिष्टान्तथापार्श्वेदयस्थपलिहस्तः २४

नकंटके निगालकेमध्यमे गलकहेयाहै २१ वक्षस्थल
और नलकेमध्यकंटहै अरुकंठकेहेठ वक्षस्थलकहि
याहै हृदयऔर वक्षकेमध्य क्रोडस्थानकहियाहै
घोडेके हेठबाहुकहेहैन २२ अरुबाहूओंके हेठजानू
मानेजोगहै अरुजानोटेवलकाकिणानाम का
केहै और जानूओंके नलेजंघाहैन २३ जंघादेआ
गेनथा नेसहीपीकेपलाजाणे सोकुंवेते ऊपरहै
अरुहेटपलिहलकहियाहै २४

© Dharmartha Trust J&K. Digitized by eGangotri

पलिहस्तकेपासकूर्चशिरे स्थितहै तिसकेवक्षकारकि
णीकहतेहै अरुकूर्चकेहेठ ऊष्ठिका औरखुरसंधिसेव
कानोउस्थान तिसतेऊपरसुशिरावहै १५ औरखुरके
सवकेपिछलेपासे पार्सीशीर्षते पार्सीहड्डीकहिहै
सवकेहेठपादतलेहै तिसपादतलविषे मंडूकीस्थि
तहै १६ अरुदोउकेवाहूकेपीछेपतनकहेहैन अरुको
उ अरुउदरकेमध्यविषे जोउकाहृदयकहिउहिमान् १७
हृदयऔरनाभिकेमध्यविषे जदाहै तिसऊपर नाभी

पलिहस्तसमीपस्थोकूर्चौनस्मध्यजोनुकि
णी कूर्चादधः ऊष्ठिकावाखुरसंधिखुरपलेना
नवस्तशिरावा १५ अश्यष्टष्टतः खुरसेवपार्ली
शीर्षवपार्लीचु स्यादेवं पादतले पादतलेस
स्थितानमंडूकी १६ वाह्वोश्च पृष्ठतेवेकर्त्तौ
नरगस्तनिर्दिष्टौ क्रोडोदरयोर्मध्ये तरणाण
हृदिनिर्दिष्टोन्मतिमान् १७ हृत्ताभ्योर्मध्यग
तेजठरंजठराननोनाभिः पार्श्वतकौ तितेषस
ऊत्तयोः पृष्ठतस्ततः १८ ऊतौ ऊत्ते रुपरिकुक
वरसंत्तौकूर्पौनयोस्त्रिकमध्ये गात्रद्वयस्यसंधि
स्त्रिकमितिमभिधीयते नुरागस १९ जेघनतस्त
नयोनतलोभवेजघननीरोयः पृष्ठाउपरिस
उकनस्योभयतस्तुभासलेकथितेर १० विधा
रोहणी संधौत्रिकस्य वै पार्श्वयोरुभयोः ।

तत्रौतिसकेदोनोपासे कत्तकहेहैन अरुपिछलेपासे ऊलौ
हे अरुऊत्तियोंकेऊपर कुकुंदनामकहेहैन अरुत्रिकके
मध्यकूर्पककैकहेहैन अरुतिनांदोनोंके वक्षकारत्रि
कहै जिसकेविषे देहकेद्वयनोउंकी संधीहै तिसे
त्रिककारकेकहेयाहै १८ तिसकेपासजघनकहिहैन
अरुतिसमेहि जघननितोयहैन सोऊंवकेऊपरकहिया
है उसकेदोनोपासे भासलनामककैकहेहैन १० अरुत्रि
ककेदोनोपासेरोहिणीसंधियोविषे जाणे जोउके ।

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ टी॰ ५९

56

जघनतेलेकरनीरोधपर्यंत उछंगजाणे तिसकेहेठव
तिकावालोवालो अरुतिसउछंगकेहेठ गुदा तिसकरके
टकी होइहै अरुगुदा औरभासलाके हेठ स्फिकपिंडउठि
वालेतेकहेहैन ११ अरुस्फिकपिंडके दोनोपासे वद्धक
हेहैन गुदाकेहेठचोडेयाके सीवनीनाम कहियाहै १३
सक्थाकेमध्यविषै मुस्केहै तिनोदेआगे शिश्नलिंगहै
औरइनतेउपरअंत्रनीयोंकेमध्यविषैकहेहैन १४ अव
चोडकी सक्थिनी उपांडमूलविषै वनीयाहोईयोहैन

जघनान्नीरोधांतं उत्संगं विद्याद् यस्ततोऽस्य १
स्याद्वर्तिकासवालागुदं तु उत्संगतिष्ठं त्र गुद
भासलयोरधः स्फिकपिंडौ समुत्कीर्तिनौ नि
तंबौः १२ स्फिकपिंडयोरुभयोर्नितंबयेस्यातां
ववद्धकेतु पवमपानायसाद्विसेयासीव
नीनंदगाणा १३ शाकेसंधानरसंख्यामुस्को
शिश्नस्तयोःपुरतः एषोद्याप्यारंभो मध्ये
मध्यतरंविनिर्दिष्टौ १४ अथसक्थिनीनं रंगा
स्याडपाडमूलेनिवद्धेन उर्वौ वैवायस्मादाक्रा
नौ वंक्षणसक्थिनीविद्यात् १५ स्थरेते वंक्षसा
क्थ्योरधमतनः संविजानीयात् स्फराख्याथस्था
नरगाणाम दिरयोरधः १६ यस्य वैकायउ
न पश्चिमकायेपितन्नेयं १७ इतिप्रदेशाख्या
यः त्रिविधप्रमाणान्यत्र कथ्यंते मध्यकनीयस्य
आयामास्तेषां परिमाणश्चैवजानीयात् १

औरपदोकेहेठचोडयाकेवक्षसक्थिनीजाणे १५ औरवा
क्षसक्थिकेहेठ स्थसनामकरकेजाणे अरुस्थराकेतले
चोडयाकेमहिरानामस्थानकहियाहै १६ जोएवेदेहकी
कहेहैन सोईपिछलेदेहभागमेजाने १७ इतिप्रदेशाख्या
यः समाप्तः देहप्रमाण त्रयप्रकारकाकहियाहै एकश्रेष्ठ
हमरामध्यम नीमराकनीयकहोटा आयाम लंबाई उवाई लेफ
रवेलाणहै जानलेवे केयाकेमनविषै आयामविस्तारप्रयन

© Dharmartha Trust J&K. Digitized by eGangotri

खिलेकर वार्तिकानगर एकसैसठ १६० अंगुलीयांनिस
हैनाणोअश्वहैवडेघोडेकाप्रमाण २ अरुवक्त्र अठाईअंगु
लीयांकहिहै ग्रीवाकाती ३० अंगुलीलमीहै अरुकाकसा
छैअंगुलीयांकहिहै औरपिठकी हिअंगुलीयांहै अरुत्रि
कछैअंगुलीयांकहियाहै ३ नयनमुखकेवरावरजाने
अरुवदूक दशअंगुलीहै अरुवर्तिकामुखके विस्तार
जितनीहै घोडेकी ४ अगलेदेहकीउचाई पादतलतेले
करकाकसातनगर सौअंगुलप्रमाणघोडेका बुद्धिमानजाने

आयामः केशांतिस्मृतः प्रयाणादिवलिकांत
ल्य विंशानमंगुलानां षष्टिशतमुत्तमाश्वस्य २
अष्टाविंशतिवक्त्रं ग्रीवा त्रिंशदंगुलायामे
षट्काकस्यांगुलानि त्रिंशत्पृष्ठे त्रिकं षडुख्यो
ते ३ नयनं मुखवद्विद्याद्दशांगुलं सानथावक्त्र
केत स्याद्वर्तिका तन्मुखवद्व्यायामस्तनमाश्व
स्य ४ उत्सेधोऽग्रिकायतलाद्याधंतकाकस्त
यावत् अंगुलसतप्रमाणं वीजानीलत्तयत्या
त्तः ५ नक्षोशाषट्विंशतिरोमदेशा चैव वाङ्
र्ष्यानां प्रोक्तस्तवत्त्विंशात्यंगुलमानोनजा
नीयात् ६ षट्जानुसंधिकूकः कूर्चः षट्षो
डशांगुलायवा षट्कृष्टिका प्रदिष्टः खुरचषा
ट्चैवजानीया ७ उत्सेधवत्प्रदिष्टः परिणा
होस्यस्य स्थमध्येन्तु पर्वत्रिविधमानविनि
र्दिष्टोऽत्तमाश्वस्य ८

लोवे ५ अरुमोरेछकी अंगुली और रोमदेशकी इत।
नैही और धोरैयाके बाहुकीवी अंगुली प्रमाणजाने ६
औरछेअंगुली नतूओकोसंधिकहीहै कूर्चकीछेअं
गुलीहै औरजेघासोलांअंगुलीप्रमाणहै कृष्टिका।
छेअंगुलीकहियाहैन अरुखुरकी छैहिकहैन ७ घो
डेकीजितनी उचाईकहिहै उतनाहीघोडेका मध्यप्र
कारका प्रमाणकहियाहै ८

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ औरघोडेको प्रोथपरस्थितिग्रन्थीयोंके वर्मककुंदरा
टी॰ नाभिदेहेस्थिरा चयत्रय अंगुलियोंकहेहैन ९ उपरका
५२ गेरु औरकूंबूट लोंबा वहु कन्त गुदा घोडियोंके बारअं
गुलीप्रमाणकेकहेहैन १० प्रयानगेटुकाऊपरलाप्र
मा औरकूटशरव दोड़ी गल परे घोड़ेके दोदो अंगुली
प्रमाणकेहेन औरमयाकर्णविंदु कोउ परेहैं अंगु
लीलवेहैन ११ गडस्यणकति परे वुद्धिवालेयोंने
पंचअंगुलीकेप्रमाणकहेहैन काशी चलीचोणप

प्रोथः पृष्ठैवालिणीचवर्मनीचककुंदरे ना
भीचैवरनरागणाप्रदेशः स्यादंगुलः स्मृतः ९
उनरोष्ठोध्वीचैवसक्कणीचवदूस्तथा क
लोगदवबाहुनाप्रदेशाश्चनेरंगुलौ १० प्रग
नस्तकौ शौलौ चिबुकौगलपवच द्व्यंगुलौ
मस्तकोलकर्णौ विदुः कोटिश्चत्र्यंगुल ११ गडस्य
देवकतीवदेयापंचांगुलाबुधेः ग्रीवाहृणाव
बोणेचविज्ञेयाः षोडशांगुलाः १२ स्कन्धवाहा
दशकंठस्त्रिंशास्वर्णेनश्चैवच अंगुलस्यविं
निर्दिष्टंद्वादशांगुलमायतं १३ अंगुलंनाल
वाहानांविंशत्यायतमिष्यते निगालोंगुलि
देकस्तुप्रदेशोदेशपञ्चवे १४ एतत्प्रमाणवाय
वाजिनांमाध्यमानांततः प्रष्ठानंषोडशभागोने
प्रमाणांमध्यमेभवेत् १५

देसोलांअंगुलीयांप्रमाणकेहे लपट्य त्रयअंगुली अ
हविस्तारचैश वांगंअंगुली १२ स्कन्धवांगअंगुली अरु
कंठतेपार्श्वतलीयां तीसअंगुलीप्रमाणकेहे १३ सो
इंदुकानालत्रयअंगुलीहे अरुविस्तारदेहमीसअं
गुलीकहेयाहे अरुनिगालांरकअंगुलकेप्रमाणकाहे
परदेहकेप्रमाणकीसमाधिकहीहे १४ परहेप्रमाणअश्व
वेङ्गोडेके देहकानतनेनिश्चयतेजाननो योग्यहे अरु
अष्टन सोलमाहिसारतरमध्यम घोड़ेकाप्रमाणकहाहे

१५

© Dharmartha Trust J&K. Digitized by eGangotri

औरमध्यमतेअष्टमांशहिसा हरकाप्रमाण छोटेकाक
हियाहै घोडेकीपूर्वकायदेह शिर औरग्रीवाकाजोआ
ल पहेहोवडेहैन १९ औरपिछलेभागविषे पुछडेव
हे मुस्तहेउस विषेहैं पकजघनपदोंकाउपरलाभाग
प्रकृतिकहै अष्टमध्यमशरीरविषेहोणवाले नाश्आ
नेलेकरके संधिजोडहोमात परजंत भ्रवकेहैहेण
भ्रवनेरुपरघोडेके औरयो भ्रवकेहैन सोवधतेहैन १९
घोडेयोंकीत्रयवर्षनकर उवेआईवधतीहै औरचार।

मध्यमात्सहभागेनेप्रमाणंस्यात्कनीयसे १
वेकायशिरोग्रीवाश्वांगानहयेषुवयन् १६
पश्चात्कायाभवेसष्ठादेगांसेनचनेत्रिके म
वेन्मध्यमकायस्तुदेशात्तेनरकायस्तु १७
आनानसंधियोमानमिमेतमध्यमस्तूले भ्रु
वाहस्थेहयस्तीणिभ्रुवामस्यानिवर्द्धते १८
वृद्धिसैवाधिकीसेयाउत्मेयेनजवाजिनो
वर्षैस्त्रिभिःगयामास्यहीणाहास्यपचभिः १९
आपचवर्षसर्वांगैःसरद्योमानमहेति श्री २०
षेनेत्रविधातप्रयाणंसर्वेनपालुलाटांत:
मुहोविदुःनिगालःनेत्रप्रांतेद्वितीयतग्री
वाकेशाःस्कंधःनेत्रविधाहतीयमप्रयानो २१
नेत्रनप्रारःककुदृकाकसमंसेचनुर्थके २
वीगात्रविभागःकौडतेवपचमकथिते २२

वर्षांकर्के लेवावधतेहैन औरफेरकीमूटआईपंचोंव
र्षोंकर्के घोडियाकोहोतीहै १९ पंचोंवर्षोंनेलेकरसभअ
गोंकर्के पूर्णवधेयादाहोताहै सोप्रमाणकर्णोकोयोग
कहेयाहै अथनेत्रमोरेकाप्रमाणहै सर्वअगैरललाटहै २०
औरशिरविंदुःनिगालपहेहसानेत्र कहियाहै और
घोडेकाग्रीवाकेशमोडपेहतीसानेत्रजाने २१ जनु
छातीककुदकाकसनेत्रप्रम पहवोथानेत्रहै देहका १
वेमध्यभाग औरकोड पहेपंचमानेत्र कहियाहै २२

© Dharmartha Trust J&K. Digitized by eGangotri

औरदक्षिणपाते पार्श्ववलीयोंमे कक्षकक्षालियां पहेछे
मातेत्रहै उदरपृष्ठवंशाते नाभिकेसहित पहेसतमा
तेत्रहै ११ इसतेउपरांत्र ऋक्षीतेलिंग पहेअष्टमक्षेत्र
कहियाहै गुह्यपदवृत्तकांतस्फिक पिंड उपांडरोहणी २४
औरस्फुरापहेनवमातेत्रजाणे अरुस्फुराकेहेठकाभा
गकहियाहै १२ इतिप्रमाणाध्याय: प्रदेशकाललक्षण
एकेकहियाहै प्रथमेरते शुभकाललक्षणस्मरण योप्रमा
णकेरुपर अरुमस्तकेहेठ सोतेचिटा चिन्हवा वद्वन

लमापृष्ठकृष्णकत्तौक्षेत्रमष्टविज्ञानीयात् ३
दरमृष्टपृष्ठवंशानाभ्यासहसप्तमक्षेत्रं ११ १
ओत्तरोपरांत्र ऋक्षीरसालिंगावाष्टमक्षेत्रं ऊ
रुवृत्तकांतस्फिकपिंडेपांडुरोहणी १४
स्फुरंक्षेत्रंनवमंविद्यात्स्फुरायोदशमस्मि
के १५ इतिप्रमाणाध्याय: प्रदेशलक्षणप्रा
केशुभाशुभलक्षणस्मरण प्रयानोहंसवक्ष्या
मः श्वेतंश्वेतनरेचयत् १ नास्थरुमिनिविक्षे
येनस्यसस्थानजः फले २ कमलदलकलश
मंगलमुसलपताकाधनाकपाटैशी: प्री
हनच्छत्रशंखस्वस्तिकशृंगारवज्रनिभै: ३
चामरकूर्मोष्टपददेवदीवज्रोपमैर्हयाश्वरै:
ऊर्ध्वतिनयंभवतिविभवपुत्रायुपोत्रास्थ्य ४

श्वेतस्थांपुरुषाणा निसकानेसंस्थानविषेहोवें नेसा
होतिसकाफलहै २ कमलदलकलशकुंभहल मो
ला पताकछोटीधजा धनावडीलवी अंकुश सीसा
मथमूसी छत्रशंख स्वस्ती गंगासागरकेमुखकीआ
३ इनोके आकारोकेसरहशाचिन्ह तिनोकरके ३ चामर
चौंपिकछूकरी कलविदिका नखगर इनोकेस्वरूपकेऊ
३ तिलकोंकरके उर्ध्वरेखाउहैन सोस्वामीकोविजय
ऐश्वर्यपुत्रपौत्र इनोकरके पुरककरतेहैन ४

© Dharmartha Trust J&K. Digitized by eGangotri

अरु जो ग्रीवा के विषै छिद्र होवै है वा पाद पुंड्र सो अशुभ
निंद्य है विपरीत करै है अरु जो अति ऊंचे विस्तार वाला
तिलक नेत्रों के नाश करणे वाला जाणे ५ यो तिलक उ
लमाघ हुस्याकी तरां है सो क्लेश के देणे वाला है और मू
लते पडकी न्याई जो पुंड्र है सो दुःखों को देणे वाला है
और जैसे फार और संगल वागा है सो भर्ता को बंधन दा
करने वाले हैं ६ इहि चोडे के रतने पुंड्र शुभ ते अशुभ क

विच्छिन्नपुंड्रमशुभं ग्रीवायां पुंड्रेण भवति वैषम्य ५
अतितिर्यगायतेन तु विनाशं विजानीयात्
उल्माषेन क्लेशं मूलकवत्पीडयेन दुःखानि
शृंखलाभेन बंधनं स्याद्भर्तुः ६ प
लानि ल्लगगाणां पुंड्राणि शुभाशुभानि कथि
तानि धन्यायुष्माणि अंगुनाललामरूपाणि वो
च्यते ७ श्वेते ललाटमध्ये नानारूपं हृदयं यस्य
भवति नन्न ललामं विद्यात्फलं तस्य स्थानं ना
ल्लस्य ८ वेद्यार्थं वेद्यदिनकरं नाराव कूर्पं मल ८
लामं तं यस्यानंगासतस्य स्वामी लभेद्राज्य
पिरिकाकृतिवल्ललामका काभवति यस्य
विच्छिन्नं वामस्यं वा पललाहितं विनाशाय नि
हिप्यम् १० उत्कृष्टशालिहोत्रेण गर्गेणापि नैष्ठि
वच पवंपुंड्रविकल्पाश्च विद्धिं नेधजिनं तृण ११

हैं हैंन अव ललामों के प्रहुनें नियरूप में रकके कहते
हैंन १ चोडे के ललाट के मध्य श्वेतवर्ण अरु अनेक तरा
के जिसके रूप तिसको ललाम जाने अरु तिसका फल जिस
स्थान विषै होवै तिसके अनुसार है ८ जो वेद्मा के सम अ
र्धचंद्रमा के सम अथवा नाराच तलवार इनकी तरां ललाम जि ८
स चोडे के होवे तिसका भर्ता उसके के छिराज को लभता है
जिस चोडे के तिलक पीगणी ये की न्याई और काक की।
नरा और करिया दाह होवे अथवा वेद्य वाले होवे सो

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ हो॰ ५९ 59

चिन्हकेनाशवालेके पंडुरोंके विकल्पभेद शालिहोत्र अ
रुणानेकहे हैंन अवविद्धि अहृधनिकेलक्षणसुणो ११
सिरकंठ अरु केश सिरकेवाल औरवाल पांव उदर आसन
इनोस्थानोंविषें औररंगकाचिन्ह जिसकाहोवे तिन्हांचिन्हों
करके घोडेकों चिन्हीजाणे १२ राजातिसकुमार वडे आ
होआ रणविषेंशत्रूकेके जीतियाजाताहै औरशुभल
लाटघोणामस्तक ककुदियक इनोविषें जिसघोडेकों

शिरःकर्णानिकेशेषुवालपादोदरासने । वा
र्णान्यतेभवेद्यस्यतैरश्वैर्ह्लाश्विह्निनविदुः १२
तेमारूढोहयंराजासयत्नेजेयतेरणे स्वे।
ललाटेघोणयांमस्तकेककुदियके १३ भ्रु
वोःकर्णाग्रयोःश्रोथेमहृणायेवुवालयो व
र्णापरोभवेद्यस्यधनीसोश्वःप्रकीर्तितेः १४
धृतिनैतंसमारुह्यभग्नोराजानिवर्त्तते १५
इतिषष्ठाध्यायः इतिलक्षणमहोगंशुभाशु
भंकथितेमेतदस्थानं शृणुवभूनाशुनिग
दितामिमाविकित्संसमासेन १६ इतिसि
द्धयोगसंग्रहे अष्टांगलक्षणस्थानंसमाप्तम्
अत्रभिन्नचिकित्सायांनध्यायीमृशामयेद्विष
क् अनन्तैषांसमोपायःसंक्षेपेनप्रवक्ष्यते १

होरवर्णहोवे अवट कर्णाग्र श्रोथलिंगके अगे वलइनों
विषेंहोवे सोधनीघोडाकहियाहै राजाइसधृतके अ
रूढके वलाआउताहै १५ इतिषष्ठाध्यायः ६ इह अष्टांग
घोडियोंके शुभअशुभ अस्थानिंघलक्षणकहेहैं अवस्था
नीयोंकेकेकिहो इचिकित्सा विस्तरसंक्षेपककेसुण १६
इतिश्रीहेमसूत्रगणाकृते सिद्धयोगसंग्रहे अष्टांगलक्षण
स्थानंसमाप्तम् जोवैद्य घोडियोंके चिकित्साशास्त्रविषें
वत्तरनहिंहै औररोगकोंभिन्ननिश्चयनहिंकिया जिनों
ने सोरोगांकोंकैसेहरकरें इसकारणतें तिन्हारोगांके
समनकरनेकाउपायथोरेकारकेकहताहों १

© Dharmartha Trust J&K. Digitized by eGangotri

सश्रुतादियोंमुनिहैं तिन्होनेजोकहियाहै सोईयं
का आयुर्वेदरूपीसमुद्रवडेविस्तारवाला तिसतेंमें
रोगगणने श्रेष्ठश्रेष्ठयोगोंका पथ्यसमूहकडिलिख
याहै १ सोईदेखायुर्वेदकाज्ञान अरुभावतिसविषे
गनिवारे दुःखकरकेहोतीहै अरुइसमेंलोकसुख
पसन्नमनसेपढायकेविना यत्नहिअर्थग्रहणाकरलेवे
यरोगोंको आदिविषे निदानविधिकरके रूपतिस्का
यकरलेवे पीछेतेउच्चीततौ व्याधिरोगजानेयाहो

सविस्तीर्णोन्मुनिप्रोक्ताद्ध्यायुर्वेदसागरा
त् उद्धृतायोगरत्नानांगणाःपथ्यतमोमया २
ह्यायुर्वेदविज्ञानाभावदोगमयदुःखिना १
आनायासेनरक्षार्थंपरिलिख्यार्थसज्जनाः
रोगाणामादितस्तावद्रूपंसमुपलक्ष्येयो
त् विज्ञातस्तुततोव्याधिःसचिकित्स्योभ
वेद्ध्रुवं ४ सर्वेषांजन्तूनांसहजाधातवः
मेप्रोक्ताः आरोग्यस्यतुमूलंरोगाणांहेत
वश्चैव ५ यस्यैतेप्रकृतिस्थाश्चयोपित्तरग
स्थवातपित्तकफाः तमरोगंजानीयात्स
र्वक्लेशाधभारसहः ६ शीतलघुःतिक्तः
सूक्ष्मश्चारीविशोषगुणोवायुः ।

य चिकित्साकरनेयोग्यहोताहै निश्चयकरके ४ सभ
जीवांसाथहिउत्पन्नपहेधातेंफेरदीहैन रस रुधिर मा
स मिंका हडीयां चर्बी वीर्यवा अथवा वायुपित्तकफ
तेवपहे सुद्धसमहोनतो निरोगपताकामूलहै अरु
तेवपहेविकृतहोजावें किसीकेकारनकरके तदारो
गांकाकारणहोजातेहैं ५ जिसकोईके पहेरसवात
पित्तकफ अपनेस्वभावकरस्थिरहोन तिसकोनिरोग
जाणे केसाथीहै सोजोदुःख अरुमार्गदाश्रम अरु
भार इनांको सहारनवालाहोताहै वायुठंडाहै ।

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰
प्र॰
५९॰

60

ले तिक्तरस सूक्ष्मगति इन्नों विशेषगुणोंवाला है
पित्त लक्षण का अमला कौउ तिक्तरस है गर्भ अरु
शीघ्रकारी है ७ कफः ठंढा मिठा थिरवा वगनवल
वाला अरु वलवीर्य इन्नों को वधानेवाला है अरु इ
न्नों के वधानेवाले जो द्रव्य है तिन्नों के सेवन करने
के मिठे ते श्लेष्म अरु अमले करके पित्त अरु कौड़े
करके वायु वधते हैं ८ वात का चलने का स्वभाव है
अरु पित्त कफ का निश्चय स्वभाव कहिया है पर है।
दोवें कफ पित्त वायु करके प्रेरे होए सारे देहविषे फि

लवणाम्लमाधुर्यकारी वपित्तं कटुतिक्तमुले
व ७ शीतो मधुरः स्निग्धो बलकृत्कविवर्द्ध
नोद्रवः श्लेष्मा हद्दिलसेवमानैः साम्ला
मैः कारणैश्चैषाम् ८ वायुश्चलस्वभावः।
पित्तकफौ द्वावपि स्थिरौ प्रोक्तौ मारुतनु
नावेतौ शरीरमभिसर्पतः कृत्स्नं ९ वायुः
प्रकृत्या विकृतो यतो बली कुरोति रोगा
न् तस्मात्प्रयत्नं सततं समाचरेत्प्रभंजन
सेवनिवारणं प्रति १० नाभेरधः समीरो
निवसति पित्तं तु नाभिहृन्मध्ये हृत्कंठशि
रःस्थकफः सर्वेषु वसंधिदेशेषु ११ नत्वे।
नैः खलरहितः कायावयवः शरीरिणां
कश्चित्।

रने हैं वात जो है सो स्वभाव ते ही बल
वाला है जब विकृत होवे तब बहुत प्रकार के वडे दुख
दायक रोग करता है तिस कारण ते वायु के हटाणे।
वास्ते निरंतर उपाय करे प्रकृष १० वायु नाभि ते नी
के है टिकरहिता है पित्त तो अरु हृदै के वीच कार व
सता है कफ हृदय गला शिर अरु सभ संधीयों व्या
तो विषे रहता है ११ देहधारीयों के देह के बीच ऐसा
है न इन्नां त्रिरहित निश्चयकर के कोई नही अरु इ
न्नों की वृद्धि वध जाणा वा घट जाणा अरु अपने

© Dharmartha Trust J&K. Digitized by eGangotri

स्थानेते गैरस्थानविषे वलजाताहै सोईरोगजाणो
बुद्धिवान् ११ यदपित्तवातक्षीणनिर्वलहोए तदा
श्लेष्मवधताहै यदपित्तकफक्षयहोजाते तववात
वढ़तवधजाताहै १२ अरुवातकफनासहोजातेहै
तदतिश्चयकरजीवांको पित्तहूवधातेहै अरुजीव
कीयां सवसवधातें वातादिरसादि नाशहोजाते ते
दउस्कामरनजानलेवे अरुसमधातुओंकीयां समता
नत्पताहै सोईनिरोगिता रोगरहितजाने तिसकारणते

एषांतयो विवृद्धिस्तु तिस्रो रोगं विजानीयात्
क्षीणौ पित्तसमीरौ स्यातां यदि वर्द्धेत तदा श्ले
ष्मान् पित्तकफसंक्षयाच्चैव वर्द्धेत वायुरति
मात्रात् ११ वातकफसंक्षयाच्चैवमपि ज्ञेय
नो वर्द्धेत तदापि पित्तं सर्वेषां धातूनां तया
क्षमपरेण विजानीयात् १४ समतायां धातू
नां सा चैवारोगिता समुद्दिष्टा तस्मादतत्
वृद्धितक्षयसम्भवा विग्रहिता चैषां १५
रोगस्यात्तयादजीर्णादभिघातादधपीडना
द्रागात् अनशनाद्व्यायामादभोजनाद्दात
सरोधात् १६ वैषम्यादशनादतिशी
तनिषेवणात् कटुरसानाम् लवणः कषाय
रसानाममन्तनिषेवणाच्चैव १७

तिन्हांकी नाते वढ़हेहिजाते इनका तयअछाहै
इसते इनका समतावी वधजाणा अरुसमतावीचरमानाव
ढ़नवानवीहै १५ वढ़तहत्तवगलैते तयहोनेथानेते
अजीर्णरसते सटलगनेते अरुवढ़तपेंडावलनेकर्के
दुःखीहोनेतें भारतें अरुवढ़तदानवखोणेतें अरुवढ़त
इडानेकर्के अरुफाकेतें वायुकेरोकनेतें वेषम्यात् जांव
सनजां अनिष्योडा अरुजोवढ़तसवेरे जांवढ़तचिरभोज
नकरनेकर्के अरुभोजनकेउपर फेरखाणेते अरुवढ़
तशीतलकौडे रूक्षकीसेवातें ७

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
६१
61

और तिक्तकषायरसोंके बहुतसेवाकरनेकरके निश्चयतें
और बहुत लङ्घनके छोडनेते चोडेयोंकोवातकोपकरता
है इनाकारनोंकरके विकृतवायुके पहेवक्षमाण रूपहोते
हैंन सोकहतेहुं १८ शोषसोकता अंगजगडजाने अन्ना
नीयाआउनीया मलमूत्रबंधहोना आफारा अफरदेहटेठा
होजांदाहै वालखडेहोतेहैं दमग्रस अंगफरकणा क
बनवात पहेलक्षणवात कुपितहोयदेहोंदेहेन १९ इना
कारणाकेके पित्तवधताहै लूणाके अम्लकोउष्णसेवने

अतितीक्ष्णविदाहित्वादेवं वायुः प्रकुप्यति हि।
यानां रूपाणि तस्य च योः कुपितेस्मिन्निजा
यते १८ शोषः स्तम्भोऽन्नमनमानाहाध्माय।
नेत्रशोषश्च कार्यः सरोमभेदः श्वासः स्फुर
णं च कफस्य १९ लवणाम्लकटूष्णानाम
सेवनिषेवणाद्विदाहिस्य नैत्वायापाद्रक्ता
विदाहादतिश्रमाद्दहतेपित्तम् २० तत्क
पितं त्वलपितेस्मा स्वेदं करोति मूर्छामथ
दाहं चैव हृद्यानां च वर्णे मनं शारीरस्य २१
मधुरैर्गुरुभिः स्निग्धैः सपिच्छिलैः सेविते
कफः कुपितः प्रश्यायामाद्येषां रूपाणि पन्ना
नि हृद्यपते २२ हृद्रोगमनत्वे स्यात्कफप्र
सेके किमीनभिष्यम्

ते अरुअम्लबहुतसेवनेते अरुतीक्ष्णद्रव्यसेवनेकरके
रक्तकरविदाहकरा पचनवाले द्रव्यसेवनेकरके अरुदा
हकरवस्तने वहनेलेदेत २० इनाकारणाकरके कुपि
तहोयादापित्तनिश्चाकरके रूपासाँमूर्छादाह चोडेयों
कोकरताहै २१ मिठेभोरुषिंदेलेपाले द्रव्यवस्तुखाने
कर्के अरुकेवल एकस्थानविषे बैठरहणेते चोडे।
योंको कफकुपितहोके पहेलक्षणकरदाहै सोकहते
ताहै २२ नाबनेवालवयनाने अरुकफलालावगती
थारे अरुकृमदिनोते अरुरसवान वहनारीयांकोणेम

© Dharmartha Trust J&K. Digitized by eGangotri

मंदाग्निनिद्रा अंगनिश्चल शोन ग्रहमल लिंद पञ्चा
व इनोंका रुकजाना दाहै लक्षण होते हैं २१ योप्रहेलक्ष
ण कहे हैं इनोंसमनोंको कठे होनेकके थोडेयोंको स
न्निपातनाम संपकरोगकहे हैं इन अरुहैं लक्षणतें दो
दोवातपित्तवापित्तकफ इत्यादिक हैं हकहे हैं थोडेयों
को समस्तनोंके रोग होते हैं वात १ पित्त २ कफ ३ इनतेत्रय
प्रकारकहे हैं इन अरुत्रय हैं दवातपित्तवातकफ पित्तक
फ सन्निपात १ एहेसमस्तविधहै सोकहे हैं इन औरथोडेयों

मंदाग्निंवेतनाली सेलेभिरंशोपमास्तावम् २३
एतेषांरूपाणांसमेनिपातेववान्तिनोरोगाः
स्तुः सन्निपातसंज्ञा द्वंद्वेतु द्वंद्वजः प्रोक्ताः २४
वातादेः स्थितव्यः प्रोक्तस्त्रिविधो द्वंद्वजात्ति
ष्या त्रिभिर्दोषैरेकविधो ...थिः समस्तविधः
स्मृतः २५ अथ बलतरगस्य दुःखप्रदा
येषामस्याग्रहो करणोकोन्मादपत्ताभिघा
तोर्दिते कांगहिक्काद्विकस्तंभशीर्षाभि
तापातिसारा रुडस्कगल्मानप्रष्ठारा
स्तंभघराचीहतोऽमहि क्विकारी स्यगवासि
नोवातबलासकाष्यानशूलानिकंपस्त
थांजंभणप्रोष्यनस्वमसनं श्रुहः सर्वगा
त्रग्रहस्थाउदंविषमनतिमिरेमहा ·

कौवाखूकर्के रोग होते हैं सोकहते हैं जो अथवाको
दुःखदेणेवाले दारुकारुकजानान औरकंनखडेर
हणे शोष्यहोन उन्मादपानकीयेकीतरांमतहोन
औरपकपासामारे आजाना मुखफिर्केजाना और
त्रिकपासेफिर्केजाना हिडकी औरत्रिककारुकजा
ना औरसिरविषेंवहुततापहोजाना अतीसार
अडमनजाने चेष्टारहितहोनागोला मिरगी वि
हची नादहूआवमनहोजाना औरत्रिविषें
थंथाहोजानो औरहदेकारोग रक्तविकार और

© Dharmartha Trust J&K. Digitized by eGangotri

मा॰
नि॰
६२

62

उरणा वातवला सवातमाथि अफारा शूलपंक फ
माणीया.... डिगपेणा अवृद्धेरुकजाणा सारे अंगों
कारुकजाणा रसोलीग्रंथी अंगोंकाफरकणा नेहर
णी औरकोणींकारुकजाना हलना औरफुलना औरठं
डेहोजाणे ठोडीनहीहलणी औरदाढांरुकजानीयां डो
डीकारुकजाना प्रमेह मूत्रधातुविकार गुदाभ्रंश अ
तीसारकाभेद उदकारुकजाना औरदेहरूखरूखीको जडु
ताहोजाणी दम खेंग फमाणी मिरगी रोगहोणा इतने

स्तंभपैपमेतृष्याकंपायोनिश्चलंबेहुत्वस्तं
भूत्वोविशोषः प्रमेहोगुदभ्रंशोतीसागुल
मूलभनापष्टगात्रग्रहः श्वासकासोस्वंग
र्भितोलंगितास्रवपक्षाहपौधिलमा
हेपकोमेफ्रनिष्कामणारोमहर्षस्त्रकावा।
श्वेतोफश्चरोगास्त्विमेवातजाः १९ हृदय
गेहनतालदाहोथनीवाणकोषकपित्ता
भितापः पर्वविसर्पकोमूत्रकृच्छ्रंनेत्रेवा।
तिशोफोथरोमप्रमोहोव्रणास्त्वग्विकार
शिरोरोगपित्तोद्विपतयोगास्तक्ष्मयक्ष्म
क्षोमसरास्यापरोलवणास्यापदस्त्रच्छेरो।
गास्त्विमेपित्तजाः २० श्लेष्मिकाः खेलवा
लकंवानकजिह्वागलग्रहोगड्यहो ॥

औरअरुपित्तलाभागढिलाहोजाना अंगोंविषैअड़क
कि अंगकंप औरवाहरनिकसजाने रोमखड़ेहोजाने अ
रुनेत्रोमें काचफोलेका भेदहोणा औरसोजाहोणा इतनेरो
ग वायुकेहोतेहैं अबयोपित्तकरजोउदयोंकोरोगहोते
हैं सोकहतेहां हृदयपर बडे नालइनोंविषेंदाहहोना
रक्तपित्तसंताप वढ़तहोना जोड़ोंमें विसर्प नेत्राकेरोग
शिरोरोग मूत्रकृच्छ्र अतीसोविषे जेरोमवालकरजाणे
धारलहोणा पित्तग्रहकी नसोंकाउतरजाना वा खरक
होनी अतीयोमें अपमानहोणा अंधेहोणा मख्खीमा
र अज्ञान औरमदिरादेणकरके औरविकारहोजाणा

© Dharmartha Trust J&K. Digitized by eGangotri

और लक्षण देनेकके आयव रोग होणा और लक्षाव इतने होणी
पढ़ी इतने विकार पित्तकाके होते हैं २७ श्लेष्मकरयो रोग है
सो कहते हैं तालु गल विषे रोग जिह्वाका हकजाना मुंजक
हिडकी प्रलून ओठोंका रोग और उपजिह्वा जिह्वा विषे हसरी।
जीव होजाती है गलरोग जाणा अरंग डुरुकजाना और ग्रती
विषे दंतोमैं पीडा कंठशालूक गलरोग नेत्र अरु स्वरमें भेट
कीम्याइ पीडा और कृमियोंका विकार सोजा मंदाग्नि और नेत्र
श्वेत वर्णाके होने और रोहिणी नामरोग उपकाके और वि।

मुंजकाहिक्काप्रलनैाष्ठरोगोपजिह्वागलग्रहो
गडग्रहोलिसेथ्यनस्तथाकंठशालूलनेत्रस्वर।
स्यापिभेदः कृमीशोफमंदाग्निनानेत्रयोः शु।
क्लताश्वावप्रावारकौरोहिणीचै पयोआप
वीमंजनालेस्रुसिंहाणकाश्लेषमाघालस्था
ल्येपिरोगाः प्रभूतास्त्रिभिश्चैवदोषैस्तवानादि
भिः २८ इत्यायुर्वेदगणाकृतेसिद्धयोगानांसं
ग्रहेव्याधिनिर्देशोध्यायः एवमाकृत्नपित्तश्ले
ष्माणः शोणितावृत्तानस्त्विते अन्योन्यसंसर्गा
न्कुर्वंतिहिस्सम्यथारोगान् १ अस्यतत्रसर्वे
रोगेषुवाजिनांकीर्तितांक्रियाहिविधावी २
हावाभ्यंतरजानन्तनीयानविधतेकाचित

कारहोणा मुंजनाल नेत्ररोग और सीडवगाणा इत्यादिक औ
रभीरोगव देहोपरोते हैं इतिव्याधिकथनध्यायः वातपित्तक
फ रुधिरसाथ मिले हैं अरु आपसमें मिलनेते पहे निश्चय
कर जो आगेकहते हैंन रोगमतप्रकारके तिनांकोंकरते हैं
न १ अब उनारोगोंकी प्रक्रियाकहते हैं औडेयोंके सब
रोगोंकी रोतरांकी क्रिया चिकित्सा एकवाहरकी प।
कअंदरकी और नी सरीकोई नहिकही २ परमाणा मा
लमकरणी उटणामलना त्रुहालणा धोणावस्तकके
ओपरनेकमणा अरुचिकना अरुखेराकरणा ।

© Dharmartha Trust J&K. Digitized by eGangotri

शा. हो. ६१ हस्तफेरना केनाकरना अरुफेरणा अंगोकोंमलना तिस्म
यकरिकै वेधनकरना अरुअग्निकरसेदहकरयोकुवाचरडदेना
अरुलेपकरना अरुचलाना फेरना एहेघोडेयोंकी बाह्य
क्रिया चिकित्साकहिहै चारप्रकारकी मुनियोंनेकहिया
है ४ मुखवेधोना नृसवार धूमपिलाना देनानासादिक
द्वारोंमें अरुमलारुग्रो अन्नीयोंविविपाणीया गेरचट
नीया देणीया अरुपुंछकारीया तैलइत्नकिया अरु
शुष्ककाथ हाणकीया अरुऔषधमिलानी अरुकोणी

स्वेदाभ्यंगोन्मर्दनपरिषेककत्तादकर्माणि पी
डनपाणिविमर्दनंयज्ञाणएवर्तनंनचैव १
उपनाहवह्निकर्मप्रदेहंचंक्रामणादिक
रणाणाम् एषावनर्थविधावाकथिताक्रि
याऽऽमुनिभिः ४ मुखधावननावनधूमस्व
नेग्रासनाचलेहाश्च अस्थापनंचवस्तिः प्र
तिपानंकर्णतैलंच ५ प्रथमनमुत्तरवा
स्तिःवोद्दनमथभोजनंविरेकश्च अभ्यंत
रमाखलचैषापचदशविधक्रियाकथि
ताः ६ एषाहिविधास्थानांबाह्याचाभ्यंत
राक्रियाकथिताम् एषगुणाःखल्वस्या
स्तेकलेषुचमंतव्याः ७

विषैतेलसिद्धकियाहुआपाना ५ नसमुआरकोभे
द अरुमूत्रलेपछकारी चपालि हाना देणा बाया
देणा यथायोग्य जलावकरणा एहेपंद्रातराकी।
घोडेयोंकीचिकित्सा जाननेवालेने घोडेयोंकी ३
हेतोयप्रकारकीजोक्रियाकहिहै एकवाहरकी अ
करहमारीअंदरकी इनकाउणअपकल्पोंविषैं जान
नेयोग्यहेन ७

63

© Dharmartha Trust J&K. Digitized by eGangotri

घोडेयोंकोंफेरनेकरके और श्रमविषे अभ्यासे वातथें
आदियोंदोषहै सोयथार्थ अपनेकार्यविषेरहितेहैं और
तेजवीर्यबल अरुगतिवेग सदरना देहमासइनाको
वधानाहै अरुदेहकोंशरीरको दृढकरताहै अरुभार
कों चुकणकों सहारणावाला करताहै अरुदेहकोहा
लकरताहै अरुमार्गवहनकरणविषे समर्थहोताहै
अरुसंदरचालचलनेमेंवी समर्थहोताहै अग्निको
प्रकाशकरहै अरुसीलस्वभावकरहै यहेइतनेगुण

व्यायामेन हयानां दोषावाताद्ययोनलोप्य
ते तेजोबलजवशोभाशरीरमांसानिवा
र्द्धन्ते ८ स्थिरगात्राभारसहालघुगात्रपवि
क्रमाः स्वस्मचाराः दीप्ताग्नयः सुशीलव्या
यामेनोपजायन्ते ९ अभ्यंगोमार्दवकृद्ध
लौवातापहस्तथाबलकृत् विशुतभा
नेष्ववस्थित्वगशस्ताः स्नेभेषुसर्वेषु १० उन्म
र्दनंवतीत्वगाकडुसमानेलापहंकफ
वेव दहुकंडूपमानिहन्तिसर्वाणि
कुष्ठानि ११ उपनाहस्तुरगाणांसु
खः कफवातयोःप्रशमनः ॥

व्यायामकरवाणेतेंहैन ९ मालसनोहै सोदेहको
कोमलरगको बलको करतीहै अरुस्थानतेखिसा
की अरुभजीहोई हडीकों जोडहै अरुसभनिमल
प्रकारेहैन जोअंगहै तिन्हाकोगुणकरैहै १० तोता
कोउ गर्मद्रव्यपायकर उटनेकीतरां मलनेकरके
वानकफदह्री खेकोंकंड अरुसभतरांकेकोढइना
कोनासकरैहै ११ अरुजोवंधनहै सोघोडेके अंडके
कफवानको हरताहै अरुतारहीयाहूआ ।

शा॰
हो॰
६४
64

कोइंथी आदिलेजोरोगहै औरमुंमेसीथां इनोंकाना
शकरताहै १२ जोद्योडेकोपशांडुआणा सोकफ
वातकोहरकरताहै अरुलिंदकाजो रुकजाणा
तिसको खोलदेताहै अरुपीडाकानाशकरदाहै
अरुदेहकों कोमलकरैहै सोजेयाको समनकरा
ताहै १३ मुखकोंधोनेतें मुखसुगंधिवाला अरु
अपद्रवदोषरहितहोताहै औरभोजनविषे इछाहो
तीहै इसकारणकरके मुखकों विछायकरके

कष्ठादीमुंर्णोसिवहम्यान्नारः प्रयुक्ता।
त्र १२ स्वेदःकफवातहरोविष्टद्धविमो
न्तणोरुजाघ्नश्च कायःसमार्दवकरःश्च
पथ्लेपावमस्त्रैव १३ मुखधावनेनव
दंनंसुगंधिनिरुपद्रवंभवेत्त्रिरुजे आ
सेनथाभिलाषस्तस्मात्प्रक्षालयेद्वदन
१४ रोगान्मुखकंठगतान्गलग्रहना।
स्तकर्मनिर्हरति सिहूणाकंचनाशयति
मस्तकं चैवतर्पयति १५ हृतिकंठगतः।
कफंलोहोलालांविशोषयोचैव कायाग्र
सेजननंप्रतिपानेसर्वदोषहरम् १६ नेशा
मयासमस्तैवहत्यगिवाशाजनेनमुहयति

धोवे १४ नस्यकर्मजोहै सर्वोरदेणोते मुखरोग
अरुगलकेरोग औरगलग्रह मिलइ इनोंकोहरती
है अरुसीइकोंनाशकरतीहै औरमाथेकोप्रस
न्नकरैहै नरखताहै १५ चटणीजोहै सोगल
विषैजोहैकफ तिसकोंनाशकरताहै अरु मु
खमैवगतियां जोलाला तिनोंकोसुकादेती
है निश्चयतें प्रतियानरमविशेष तिस्ये॰ ।

© Dharmartha Trust J&K. Digitized by eGangotri

देहकी अग्निकों जगाता है अरु सब दोषहरै है १६
अरु सलाई अंजनी में पाएं करकें बहुत प्रकार के ने
त्ररोग सब हरे होते है अरु अंजनी निर्मल होजाती या
है अरु वैसे तेल सिद्ध कीये होये कानों में पायदे
कनों के रोगानूं नाश करदेहैं न १७ स्नेहपान घी
उ तेल मिझ चर्वी इनोंदे पिलाने से मिझ मास को व
धाता है अरु वूडेपा अरु व्याधि इनको नहि होने देता
अरु प्राणको वधाता है १८ जो निरूह वस्ति रुक्षदया।

कर्णेन्निमः स्नेहोअपोहन्तिकर्णरोगांश्च १७
मेदोमांसविवर्द्धनमायुष्यं स्नेहपानं सुख
वर्ल भोजनवन्हिकरं रसायनं प्राणसंज
ननम् १८ वस्तेन मे रोगध्वंसोदनश्चकेरि
दोषसंशमनं पश्चाईनाविकारानृशमय
तिवस्तिर्वलैवेकरूते १९ नीत्लोगास्मः पित्त
करोलघुर्वातकफापहो निरूहस्नेहशी
नःपित्तज्ञावलः पित्तकफहरोलघुस्निग्धः
पयोवास्ति: २० प्रथमनस्मापीताः कटुती
क्ष्णाः श्लेष्मसंशमनाः हृतमन्तुलोम्यपक्व
विरेचनेकोष्ठशुद्धिकरं २१ रक्तस्थिनास्त
दोषास्त्वरगाणांसंतिसर्वेदायसान ।

कीपक्वकारी है सोतीक्ष्णगर्म पित्तकर होती है अरु
वायकफका नाश करता है अरु जो घृततैलउभयकी जो
पक्कारी है सो कोमल ठंडी होती है अरु पित्तकफहरै है
२० अरु जो नाडी साथ धूमपान है सो कोउतीक्ष्ण है
पायन कीया दा श्लेष्मको समन करै है अरु जो वीउ सिद्ध
कीता वा है पकाया दा सो दोषों को यथार्थ यथार्थ र
खदा है अरु मलहरा है अरु मलस्थान को शुद्ध करै है २१
जिस कारण करके दोषों के रुधिर विषे सदा ही वात दि

© Dharmartha Trust J&K. Digitized by eGangotri

मा॰
हो॰
६५

65

विकारोंसेयुक्तरहितेहैंन तिसकारण बुद्धिवानोंने स
भनोरोगोंमें लङ्घनिकालनचाहिये ११ वायुलेप स्वेदन
रसोंका आरण्य मालस रुधिर छुटना वमन लंघन प
छकारी कहणी इनोंकेकेनाहिंसमहोवे तव अग्निकेसे
कबुद्धिमानदेवे १२ जलपानकागुण जलकेपीनेकर
केपित्तहरहोताहै औरमांसकोबधाताहै आयुकोब
लकोबधावताहै अरुछोडेयोंकोस्नानजोहै तुहाल
ना सोलघा मूर्छा थकेमा इनोंकानासकरैहै और

तस्मात्सर्वविकारेषु पोतणं मोहयेत्सा।
त: ११ लेप:स्वेदाभ्यंगौ विस्रावैर्वमिलांघ
निरुहै: सिद्धयन्तियदानवायुस्तदाग्निम
वतारयेत्सात: १२ जलपानेपित्तघ्नं हृद्यं ह्रा।
णमायु:प्रवर्द्धनंबल्य स्नानंतन्द्रामूर्छाश्र
मापहं पित्तसंशमनम् १४ वक्रामणम
निलघ्नंकफरोगस्तंभशूलशोफहरं उप
वर्तनंश्रमघ्नंस्तंभहरंहर्षसंजननम् १५
लघुगात्रकरंविघर्षणंरोमपाकादिभि:स
मम् केशापहरंचपरमंप्रासादनंवैवथा
ननाम १६ मुकोग्निस्यानगतोहाह
र:खलचक्रवियः पक्व: ॥

पित्तकोसामकरताहै १४ अरुपांवोछोडेयोंकों फेरा
नाहै सोवातको अरुकफकेरोग अगकाहक ना।
ण स्थूल सोजन इनकोहरताहै योविलणाहै सोथकेमा
अंगोंका पाकरनाण इनोंकोहरताहै औरचित्तविषैकों
पैदकर्ताहै खोखो इनोंदिनकयोहै सोउयोंको चोरी
करनेकके देहतिनोंका हौलहोजाताहै औरखुरकको
हरताहै अरुबालसाफकरताहै औरयातनुरसादितिन
कोपुष्टकरताहै १६ वारप्रकारकाजोभोजनहै ।

© Dharmartha Trust J&K. Digitized by eGangotri

भक्ष्यभोज्य लेह्य पेय सो आहार अग्निस्थानमें जायकर ह
छौ प्रकारकर पाकहोयाहूआ सारेदेहको तृप्तकरताहै
अरु प्राणोंकोवधाताहै २७ जैसे सूर्यभगवान आकाशवि
षै स्थितहोयाहूआ सारेभूमंडलको अपणेतेजककै तपा
ताहै तैसेहि अग्निभगवान अपनेसुंदरपराक्रमकरके
मेरगुणोंकोंके तोडताहै २८ इसीप्रकार कायाविषै
स्थितजोअग्निहै सोअपणेतेजककै सारेदेहकेविषै प्र

प्रीणयति सर्वदेहं सम्यक्प्राणांश्च वर्द्धय
ति २७ गगनस्थितो यथार्कः स्वतेजसा
धरणीमंडलं कृत्स्नं तापयति तथासौ
सौवीर्येण गुणौघं यो जयति २८ एवं का
यानस्थो वह्निः स्वेनैव तेजसा सर्वं व्याप्नो
ति वै शरीरं तस्माद्यस्य प्रतापेन कायाग्नि
स्तुस्मै दैव हि बलं वर्द्धतेऽस्य २९ सम्यग्
वै पचति तरां ततो नश्याहारमेवाग्निव २९
सम्यग्वै पचति तरां ततो बलं वर्द्धतेऽस्य
सर्वैश्च लघुत्वं रोगमर्दिनमप्रातराशिना।
मदोषम् ३० पानीये वा पीते निरूहयेन्तो।
पकालेन अस्थापितस्य वाप्यस्नानपानेव
गास्यतेऽस्य ३१

सरजानीहै जिसनेदेह अग्निकेसताते सदाही आहार
वाग्निविषै हळीनतरा पचकरके पक्कपणैमें अस्थिको
बलवधाताहै २९ सभनीमनुष्याविषै थोडेयोंको म
र्दन भोजनकेएवं श्रेष्टकहीहै ३० निरूहवस्ति पा
छकारी पाणीके पीतेनाहोयावादेवे अरुजलकेपी
णेकेसमयमें स्थितकरके फेरस्नानकरावे अरुजल
पिलाना थोडेयांकोंगुणाकरकहाहै ३१

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ टी॰ ९९ अस्थापनबस्ति पश्चिकारीकाभेदहै स्निग्धबस्तिजिसके
पीछे बासअरुदानादेवे फेर अनुवासनबस्तिदेवै इकदिन
देवे अरु इकदिनछोडकरफेरदेवे एकदिनभोजनदेवे इस
प्रकारबस्तिकिविधिकहिहै यबस्नेहबस्ति घृततेल इना
नुवकी पश्चकारी देणीहोवे नदस्नेहबा अन्नखानेकोदेवे ११
नदस्नेहनिकसजावे गुदाद्वारेते नदस्नेहखानेकोदेवे य
बस्नेहबस्त अरुपीणेको एककालविषेदेवेतो जिसकरके
देहकी अग्निशमहोजातीहै अरुअग्निकेशांतहोएतें यो

66

अष्युखादनेप्रदेयंभोजनमनुवासनंचैव
एकांतरंवदद्याद्वाजनमेकांतरंतनोवा।
स्निग्धेहवस्तिर्यदादेयोरुक्षान्नंभोजयेत्त
दा ११ यदाविस्नावणंनस्यात्तदास्नेहंप्रदा
पयेत् उभयस्नेहनाशस्यकायेवह्निःप्र
संयाति १४ अग्नेशांतेमरणंप्राप्नोतिनरो
गमस्ततस्माद्धि सर्वेष्वेवनुकालेषुवर्जये
दुभयःस्नेहम् १५ सम्यग्विधापिशिरया
नवाजिनोननिर्होति नाग्निर्हरतिनिरू
हःसम्यक्संयोजितस्तहैः १६ पानी
यपीनमथनवाहयेत्रोपवर्नयेद्दीमा
न् अपवारणानेनतुवायुःसम्प्रदीय
तेकोष्ठे १७

उकों मरणप्राप्तहोताहै निश्चयकरके जिसकारणसें
इके सभकालविषे दोयप्रकारकरके स्नेहकिदाना
देवे खानेकोदेवेनाबस्तिनादे १५ जोउंयोकेनाडीयों
मे जो रोगप्राप्तहै सो यथार्थचिकित्साकरके भी जैसे
बाहर नहिनिकसदे जैसे बहिखानकरके निरुह ब
स्तिहलीनरो देहहोइबाहरनिकासदीहै १६ पानीपी
नेरोप होउको मनावीनाहोरे अरुचरुवीनाफिर इके
करनेकरके अपचार विकारते वायुकोष्ठस्थानविषे

© Dharmartha Trust J&K. Digitized by eGangotri

उलटा होजाता है १७ प्रातकालमें घोडियोंको भोज
न कदाचित नदीवीनादेवे सोदीयाहूआ नानाप्रकार
केश्लेष्मकर उत्पन्न रोगोंको प्रगट करता है १८ जलअ
रु और जो पेयवस्तु काथादिकसो प्रातकाल विषे दे
वे अरु स्नानादि इत्यादि औषधी डरेरी देवे अरु भो
जन घासादिक अरु पच्छकारी फल नि अरु घेउ तेल
आदि वोह्य पहरगुणकर है १९ जिस घोडेको मदिरापि
लाया होवे उसको परसानाउ आवे अरु जिसको परसा

पूर्वाह्णेतुरगाणांनभोजनंदीयतेकदा
चिदपि जनयतिनानाकारान्तत्श्लेष्म
सम्भवात्रोगान् १८ पेयानिनपूर्वाह्णेम
ध्याह्ने स्नानानिदेयानि भोजनवल्लिदे
हाहितादिनुपादशेषेण १९ नहिपीत
मद्यमश्वस्निद्येत्स्विन्नंनपाययेन्मद्य
मद्याभ्यासात्पानंहिरुणध्यतिरक्तंचपि
त्तंच ५० आयामनस्थलेहंव्यायामं
वैवदन्तलेह्यस्य मारुतकोपभयात्
चास्यवर्जयेद्बुद्धिमान्वैद्यः ५१ प्रा
तस्यभोजनंचैवव्यायामंभोजितस्य
वाप्यस्य शूलमरुत्कृदभयाद्विवर्जये
बुद्धिमान्वैद्यः ५२

पआयाहोवे तिसकोमदनादेवे जिसकारणतें
मद्यअरअग्निकेपाकतें रक्त अरु पित्तको पकतें हैं
५० जिसघोडेको थकनी दितीहोवे तिसकोफेर
नहि अरु जिसको फेरा होवे उसको देवे नहि इस
ने श्वासक्रियामें चतुर वैद्यवाइसकेभयतें सदात्यागे ५१
चतुर वैद्य मार्गकर फेरने तें थके होए घोडेको दाना
घास नादेवे अरु भोजन करा के सताबी भ्रमना करे
तिसतें शूलरोग और गतिरुकजाने परोगहोते हैं
इसतें त्यागे ५२

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
६२

पूर्वे दो प्रकारकी वाह्यवाह्यरकी और आभ्यंतर वाह्यरकी
या बहुतन्तरकी या क्रियाचिकित्सा कहियाहैन इना
को रोगकारप्रकजो है प्रहनिरोगपजो घोडे हैं तिनाको
वनवैद्य सदापथ्यापिक्कारकरावे ४१ इतिक्रियास
माध्याय: श्रावणभाद्रोंविषे ये घोडे वाहररहतेहैन
तिसकालविषे जलकरके सिंचनते घोडेव्याकुलचि
नवालेहोजातेहैं १ तिसकारणते परोकेरोग प्रक
वाड़ीके रोग औरचमड़ेकेरोग ... इट३.ण वात

पद्यानानाकारवाह्याभ्यंतरक्रिया
कथिता: स्वस्थास्वस्थेषेनाप्रयोज
येद्बुद्धिमान्वैद्य: ४१ इतिक्रियासम
ध्याय: सिंहस्थकर्कटस्थे: केवहित्ति
ष्ठतियेहया: तस्मिंस्तेवारिसिक्तावा
जिनोहन्तचेतस: १ पादरोगै: शिरोरो
गै: ग्रीवारोगैस्त्वगामयै: उत्सूकपादै:
कैश्चैवस्त्वगतीसारकेभ्युता: २ भवत्प
न्नपरिश्रमा: इद्राशनिहन्ताययथा अत:
शालांप्रवसामिहयानांहितकाम्यया १
रूपवेश्मवामभागेषुभेदिनकारयेद्धया
गारं सहस्रामिश्रयत्नाडुत्तै: प्रवसंप्रति
ष्ठाप्य ४

रोगविशेष कोउत्तोरदस्त इत्यादिकरोगोंकरके
युक्तहोजातेहैं १ औरखानेपीनेतेरहितहोतेहैं
तैसेइद्राशनिवज्रकरकेहतहोवे तैसेहोजातेहैं इस
कारणसे घोड़ेयोंके स्वरेको इच्छाकरके घोड़ेयों
केघोरपलावधनस्थाननतवेला तिसकेबननेकी
विधिकरतेहै १ घोड़ेयोंकीशालाश्रेष्ठशुद्धहैतेदि
नमें राजाकेघरते खेवेपासबनावे लक्ष्मीकोए
नके औरउत्तैश्रवयाहै इद्रकाघोड़ा तिसकोतिसमें
स्थापनकरकेबनावे ४

© Dharmartha Trust J&K. Digitized by eGangotri

मंगलकर जैसे राजनकी रक्षाकरै यथायोग्यपदश
हाथ ऊंची ग्रहपकी हफबनावे ग्रहद्वाराकी जागा
तिसविषै द्वो २ हाथऊंची ग्रह मोटी बनावे ५ ग्रहनि
सशालाम ग्रहनिसशालामें वैलोकेसहित गोग्रा
सनदिनरखनीयां ग्रहनिसनेउपरंत ग्रग्निहोत्र
तिसविषैककैं योउयोंकों तिसशालामें प्रवेशक
रावे ६ हृतमंगग्रग्रस्थस्नानभूषणोंकरिसृंगारके
राकेप्रदक्षिणानेपरस्परसन्मुखवैठायावे नातोव

अथशालासंवेष्टं दंष्ट्रशहस्तसमुच्छ्रितां दृढां।
कारयेत् खोरकोष्टकमस्यां द्विहस्तस्त
श्रृलोच्छ्रितं चैव ५ स्थाप्याः सवृषागावः
सस्माहृवैववानिशालायां नतस्तोह्नवा
ग्निप्रवेशयेद्दाक्षिनेनतेत्र ६ हृतमंगल।
संस्कारावहृयास्नेप्रदक्षिणाभिमुखाः
नामायनानशिथिलास्थाने वाष्टनरा
भिमुखाः ७ शानसूत्रदामभिर्भिस्नेशफ
सवहास्मकीलवद्धास्त्र नानादारुकृता
गतिसंशालासकृवीत ८ पिटकाक्रे
शनितथा ख्रोण्यकटाहिकास्तृषदा।
स्म कृशालास्नकृणादत्तास्रतुकूलाः।
स्थानपालाःस्युः ९ हृतखलानातोवहृत।

दिलावाना नोवहृनतिलेस्थानमें उत्तरमुखकर्कें
वंद्रे ७ सणकेरसे सूत्रकेरस्सेसाथ पठ्ठयाउं ग्र
गेत्र्याउंकिहलेसाथवंधे औरयोउयोंविषै वहृतप्र
कारकेदाउीयाकृहाउीया सदाहीशालाविषै करा
वैरावे ८ औरवखोरकुंडखरलीयां वाउलीयां क
हाहा ```` इत्यादपदार्थपहेशालामेरखणे और
गोउकीशालामेंमनुष्यबुद्धिमान नग्रान ग्रहगो
उयोंकेकार्यमें चतुरहोरग्रान्नस्रनुसार एसेउस
शालाकेरक्षावालेहोवे ९

© Dharmartha Trust J&K. Digitized by eGangotri

तित्तर मोर लेडे चकोर सुफेदभिडें वांदर तोता सुफेद कुक्कुड पहपत्ति सुफेद बीणा बजंतर के बजानेवाले पहे इतने योंकी शाला विषे रखे सदा १० और शाला में दीपक सारी रात जगाया रखे तिसके प्रकाश करके यत्न देव ग्रह सर्प चोर नाश होते हैं तिसका रणते यो भजन विषे प्राप्त होवे यो सर्प सुपेद सभ देख जाते हैन और यो रोग है सो बील भते हैं ये डे विकार देखके जानी दैहेन और पक्षाव सुफेद हाट नहो रखो

तित्तिरमयूरलावकचकोरसितमेषवान
रश्वकाश्च सितककुद्रवीणावादकांश्च शा
लासु कुर्वीत १० दीपान्हयशालायां प्रय
त्नतः सर्वरात्रिकान्कुर्यात् ११ प्रभया प्र
तिहन्यंते यत्नोरगमस्तकायस्मात् वर
माणे परिसर्पः प्रदृष्यते लह्य विकार
श्च मूत्रं तथा पुरीषं शालासु नयत्र पर्वं
सुहुत्वाग्नौ निर्हरेद्रात्रौ गंधैर्माल्यैर्धूपैः
स्थानानि विभूषयेदलंकारैः १२ सविशे
षं तथा पर्वसु हुत्वाग्नौ एजेयद्विजान् कां
चनमयीन्मालामणिरत्नविभूषिताः
चबध्नीयात् १३

कौं पर्व दिनों विषे अग्नि विषे हवन करके दम्पकर के रात्रि विषे बाहर सुदट देव सूर्यशाला के यो स्थान है तवेलेको गंध पुष्प धूपादि फलो किया माला रूप भूषण गहने इनो करके सुंदर करो सुफेद घो॰ शुहतेम पर्व दिन संक्रांति आदिक मे विधिवत हवन करके उपरंत ब्राह्मणों को एजे और सुनेकी माला मणी करके यो है यो शाला में प्रधान घोडे हैं तिसके गल रत्ना करणवाले यो में उहै तिन्होंकी विधिकरके बनावे १४

© Dharmartha Trust J&K. Digitized by eGangotri

मन्त्रेणा विधि सूत्रका बणावे जिसकार के मखीयां
नादुःखदेन जिसके घरकरणे के चनेनाकरे जिसते
घोडेकी दृष्टी खुली रहे असा बनावे १५ रोगवालेयां
घोडेहै तिनकी जागा गसमारे अवश्य बनाने लिखी है
वीं येकोउ खेके राजयक्ष्म इनावाले आपसमें मिल
होए परस्पर दूसरेको वी रोगीकरदेनाहै १६ एहे
वस्त्रे घोडेकी शालाविषे सदा सीत पार रखे लहु घोरे
नेल मिक चरवी धूप धुखोनेवाले हरणे मलाईया न

सूर्यांशुमन्त्रकैः रक्षा मन्त्रेण विधिना च कार्या
जितेन सूत्रेण मृत्तिकाणां निवारणार्थं च अ
यीत नो दिसमालाना तिघ नोपरापतियथाश्व १५
स्यानेवधूप्यकं प्राकं गुम तरं रोगिणां प्रयत्ने
न अश्वीद्रुणी वयक्ष्मी परस्परं दूषयेयेते १६
लेहानतैल इस्पानदुणीजनन नरावाल्प
दिह्याश्च धान्यानि गुडं लवणं केशान् रोमा
णिन खेश्च १७ इमाणि वस्त्राणि च वि।
विधान्यपस्करांश्चेव वैद्यास्तुरगागारकु
यात्रिसं सदैव सन्निहितान् १८ तोरति
थिनक्षत्रा केशांस्तु न खोश्च कर्तयेद्दीवी
ने स्नानामतः प्रलिंपेद्धरिद्रया पिष्टा।
यान्तरगान् १९

सवाराम अरिष्ट अर्क मदिरादि अरुअन्न गुड लूण
सिरके वाल और रोम देहके वाले नही और नोहोडके
हिनवाले इसमें हैन और सूत्र और सब मग्री खरखरे मखे
रोण इत्यादि वैद्य पहसदा पास ही सावधान रहिए १८
योवाल उतारनेवाले तिथि नक्षत्र वार तिनों विषे के।
श अरु नखोंको कतरे ये ब पग ये हाप है न फेर ति
सने उपरंत नहायकर हरदल पीसके घोडेयों
कोलेपकरे सो हरदलप वित्र है १९

© Dharmartha Trust J&K. Digitized by eGangotri

शा० हो० ५८

69

और इनासें कोलवाके रोगोंको नाशकरदी है और भू
षनशोभाकरती है मंगलकारी है तिसकारणकर्के हर
दलकर्केलेपकरे स्नानकरायके फेरधूपभ्रलावे १
गौ अरु भेड बकरी इनकेबाल और मृगहरणके खु
रचमडा सींग और बिलेकीनखा शल्लकीदेत अरुये
हेकेटोटे इनौका धूप बनायके धूपदेवे २ अरुवो
डोयोंकीशाला नवेला राजाकेघरकेपीछेबंधिवा
नवनावे अरुपूर्वोक्तइन्होंसेशांतकरे अवपाप।

रक्षोघ्नीरूपविज्ञानदोषघ्नीविभूषयन्त्य
धान् मंगल्याव हरिद्रातस्मात् स्नानानया
प्रदिहेत् १ गोजावीनां रोमाणि मृगखुरे
नकन्तश्चैव शृंगंच मार्जारनखकच्छपेवल्लुल
किसकलेश्वधूपोयम् २ रक्षोघ्नः शांति
क्रो मेध्यः पापप्रणाशनः श्रेष्ठः बडवागा
रेप्यवेयमष्टक्षेत्रः कारयेत्सुशान्तः ३ शाल
विधिः ॥ शिशिरोवसन्तकालोग्रीष्मोव
र्षाशरच्चहेमन्तः षडमीऋतवोज्ञेयामा
घमासफाल्गुनौशिशिरः १ मधुमाधौ
वोवसंतोज्येष्ठाषाढौनिदाघकालस्तु प्रा
वृट्नभोनभस्यौतथाश्वयुग्कार्तिक
श्चशरत् मार्गशीर्षस्तथापौषौहेमन्तःकी
र्तितस्ततस्ते २

केरक्षकरनेवालीपवित्र है
शालाकीविधिकहिहे अबऋतुओंकाविभागकरकह
तेहैं शिशिर वसंत ग्रीष्म वर्षा शरद हेमंत येहैंछऋ
तुजाने माघ अरु फाल्गुण शिशिर अरु चैत्र वैसाख व
संत ऋतुकहिहे और जेठ आषाढ ग्रीष्मऋतुकहिहे
अरु श्रावण भाद्रो प्रावृट ऋतुहै अरुनैसेही आश्विन
कार्तिक शारद ऋतुकहिहे मघर अरु पौष हेमंत क
हिहे ये ऋतुकहीयोहैन ॥

© Dharmartha Trust J&K. Digitized by eGangotri

तिन्हों ऋतुओं में दोष वात पित्त कफ किठे होते हैं अरु को
पकरते हैं अरु सम होजाते हैं सो शिशिर में जोडे यों को श्ले
ष्म किठा होकर वसंत में कोप करता है १ अरु जेठ हाड
विषें वायु किठा होता है अरु प्रावृट् श्रावण भाद्रों विषे को
पको प्राप्त होता है और वर्षाकाल विषे पित्त एकत्र होक
र शरद ऋतु में कोप को करता है ४ अरु छे हि ऋतु ए
क दिन विषें ही जान लेवे सो कहते हैं प्रातःकाल विषे
वसंत ऋतु का गुण होता है अरु मध्यान विषे ग्रीष्म ऋ

निचितः शिशिरे श्लेष्मा नराणां कुप्यति व
संते १ ग्रीष्मे निचितो वायुः प्रावृट्काले प्रको
पमुपयाति वर्षाकाले निचितं कुप्यति पित्तं
शरत्समये ४ एवं ह्येतद्वसंतग्रीष्ममध्या
दिने विजानीयात् प्रावृषमपराह्ने वि
द्यात् शिशिरं प्रदोषेतु ५ शारद्दै रात्रसंज्ञा
प्रत्यूषः कीर्तितस्तु हेमंतः एतेषु कफपि
त्तवातं कुपितं भिषक् शमयेत् ६ वर्षास्व
स्वायोज्यायैः श्लेष्मा शमयेत् रोगाणाम्
शान्तेनानेन मनने कायाग्निर्वर्द्धते स्य ७
कायाग्निना प्रदह्नेनाम कृतन्तिष्ठति स्वक।
स्थाने स्थान स्थिते न स्थाने तिष्ठति वै दोषाः ८
स्व स्थानस्थे दोषे वल मारोग्यं भवेत् नराणां

तेजाणे अरु सायंकाल सांज विषें प्रावृट् ऋतु बीतती है २
अर्द्ध रात्रि विषे शरद ऋतु वर्तती है अरु रात्रि के अंत विषे हेम
न्त ऋतु कथन करी हैं १ तो ऋतुओं विषे कफ पित्त श्लेष्म
कुपित होए होया को वैद्य समन करे ६ वर्षा ऋतु विषें
थोडे यों को पसेरस देणे वा रप यिनाकर के कफ सम होजा
वे सो कषायरस है श्लेष्म के शांत होणे कर के थोडे के देह
की अग्नि वधती है ७ अरु काया देह की अग्नि के प्रकाश हो
ए दे वायु अपणे स्थान रहने कर के दोष मलादि वातादिक
अपने २ ठिकाने स्थित रहते है ८ अरु अपने २ ठिका
णे स्थित रहणे दोषादि तत्वों का वल अरु आरोग

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा॰
लो॰
८०
70

नाड़ुंदी है १ सकारणते गुग्गुल त्रिफले हरीड़ बहेड़े आ
मलेके काथसाथ देनेकहियाहै ९ अष्टघोड़ेकों वैद्य
गुग्गुल प्रमाण मात्रादेवे सो कहते हैं पहलेदिन अधपा
लका दो तोले देवे फेर दिन २ प्रति दोदो तोले वधाता जा
वे जितनाचिर पंजपल नहि होइ उतनाचिर १० और घोड़े
कों गुग्गुल त्रिफलेके साथदे हरीड़ बहेड़े आमले साथ
दो साते चौदांदिन देवे अरु फेर दोपलका पाउकाथ्या
वे अरु देवे अठतालीदिन ४८ उत्तममात्रा कहि है अरु

तस्माद्गुग्गुलयुक्तस्त्रिफलाक्वाथः समुद्दि-
ष्टः ९ प्रथमे दिवसे द्वे पले पलार्द्धे द्वे चाप
लानि वै पंच अनन्तरगाय भिषग्गुग्गुलमा-
त्राः प्रयुंजीत १० त्रिफलासहितं गुग्गुलम-
थायन सप्तकं द्व्यं दद्यात् ह्रेनपुनम्पला
नां त अष्टौ चत्वारिंश द्वात्रिंशन्मध्यमाधम
योः ११ एवं न्यूनकाले वमथपायरीनतं भो-
जये द्वापि दिनावशेषे पुष्कं प्रदेयं यवमंड
येभ्यः पानायकोष्णसलिलं प्रशस्तम् १२
त्रिदोषसंदुष्टशुन्नरणाणां विधीयते प्र
संधिप्रगुल्मेषु नष्यानाडीव्रणेषु च १४
प्रस्कंदरोगेषु नरंगमाणां स्तंभे प्रशोफेषु
गुदामयेषु शीर्षामयेष्वव शफामयेषु
दद्यात्समस्तेषु वलामयेषु १५

वतीस ३२ मध्यमकहि है आठदिन प्रथमकहि है ११ ति
सकों पहलेपहर पिलावे फेर मंजावेलू थाउ दिन रैदे
सकादा घासखाणकोदेवे अरु पानी शीतलगर्मकरके
घोड़ेयांको देने कहिआहै १२ त्रिदोष वात पित्त कफ ति
नके विकृत होयदे या घोड़ेयांको देणा योग्य कहा है गुग्गु
ल अरु जिसके याउ सत न होन गोल्ला रोग नष्टर प्रस्कंद रोग
नके इ नाना हलेमानानावे सोजा और गुदास्थानके रोग
और सिरके रोग और ड़े वके रोग का ड़ीके रोग और ये सभ वी
मारीयांके ना विषे वरिमान वधरवे १५

© Dharmartha Trust J&K. Digitized by eGangotri

और जिनां छोड़ेयोंकी शफा ... कोष्ठमें हृदयविषें ल
गगयाहै और जेमन्दाग्निवालेहैं और जेडोंविषें पीड़ अरु
लिंगमैं शूल इनां रोगांवाले याको देणेयोग्य है १९ जि
सछोड़ीकागर्भ नारहै और जेसडहोके और जेगर्भ नहिं ग्र
हणकरे अरु जिसकेवच्चे सदा मरजादे होन अरु वायुरो
गकर युक्त है तिनां छोड़ीयांके ताईं पहे गुग्गुल अरु अ
नेरोगका वला अवल सात्म्य योसेवकीया सुखकरहोवे
तिसकों देवे एसके सेवनते शोभा सुंदरता वलपराक्रम

येषां शफः कोष्ठगतो हृद्यानां मंदाग्नयो ये विष
माग्नयश्च शिश्ने च शूलो हृष्णोव येषां तेभ्यः प्र
देयस्तु तु रोगिभ्यः १९ गर्भच्युता याच हृद्या
नपत्या गर्भं न गृह्णाति च या तु रोगी नपत्या।
पत्या नि सदैव यस्या वातामयैर्या च निपीडि
तास्यात् २० ताभ्यः प्रदेयस्तु तु रोगमीभ्यो ता
तास्त्रत दोष वलं च सात्म्यम् शोभा वलं वी।
र्यमतीव दर्पस्तेजो जवो भार सहिस्तताव १ ८
नास्येन केनापि रसायनेन भवेद्यथा गुग्गुल
नाहृयानां २१ इति गुग्गुलविधिः गाहते।
यश्च वर्षासु पिवेदाभिनवं जलं सवाह्याभ्य
तरान्त्रोगान्लभते ष्वानं संशयः १ दृष्टे प्रति
वर्मांते स्वेदो ष्ठिद ज्ञानि भूतानि प्रादुर्भवंति
मलानि नानि तोयस्तु नात्मेव २

गर्वनेज औजथान्तसार अरु वहुत भारकों मारना पहे और
किसी रसायन औषधी बूटेया आधि हरकरणेवाली केसे
वाते नहिं होते जैसे छोड़ेयोंको इस गुग्गुलकरके होता है १
पहे गुग्गुल की विधि कहि है यो वोउ वर्षाविषें जलविषें
भिजना है अथवा नुहालते है अथवा नवीन जल को पीना है
सो बाहरके अरु अंदर के रोगांको लभता है इसमें कछु सं
शय नहीं १ ग्रीष्म ऋतु के उपरंत जव वर्षाविषें स्वेदन उ
ष्टिद वहे और मीण कहना दिजीव होते है सो मन तहां ए
जलोंविषें पाने हैं तन २

© Dharmartha Trust J&K. Digitized by eGangotri

पा॰ हो॰ ७८

71

सोनीचपाणीमेंविषकोंत्यागनेहै तिसकारणकरकेवर्षा
काजलविषवालाहै सोपानीपीनेमेंत्यागकियाहै ३ औ
रवर्षाविषे होउंकीशालातेवलासका अरुविस्तारवा
लापुला औरसबकीरेतकारसकायादा ऐसीसालाकोंक
हतेहैं तिसहीइसीतंरारवे अरुजलछोडेयेकोंखूपेका
पिलावे अरुवडीभुपनालगाणदेवे अरुघेउवनायादाप
कादेवे जवहुतकरस्निग्धहोवे तिसकेउपरंत छाय
सांकीका औरखवल डुंवादेवे जिसद्यासकों इसलोकवि

मूषकमंडूकाद्याःकीटास्तोयेविषंप्रसुंचंति न
स्माद्वार्षिकमुदकंसविषंनपेयमुद्दिष्टम् ३
शालाशुष्कांविपुलांनिसंशमेनिपांशुभिःकी
र्णां कौपंतोयंपानायवजेयद्वातपलीढं ४
पंकेचूतंप्रदेयंस्निग्धेभ्योदापयेनतःसस्य रण
माकाद्यनीलयत्वैन्द्रं प्रोक्तंतेलोके ५ अथवा
प्राक्स्निग्धेभ्योरुक्षेभ्योवापिदापयेत्सस्य ६
वारकेवरनोष्णस्पर्शेघोरेजवस्तथोत्साहः
गात्राणांचलघुत्वंनेत्रेंद्रियाणांविशुद्धिश्च
दीप्ताग्निर्वमेवदधत्समतामनस्वितारो
गपम् पविवर्त्तेनेवक्रमशोविपुलत्वंतेगमस्क
न्धिनः ८ सेव्याहारविहारैःस्वेच्छासम्पन्ना
शनैस्ततोवलिनः।

पेंइनेप्रगटकियाकरतेहैं ५ अथवाएवंहुतकेचाय।
देवे वाफूलकोंवीदेवेचाय ॥ वारवृमागकरवेयोहो
उविवरनाहै सोकहाहै अपणीइछाकरकेभोजनकरना
औरफिरना औरसोणा खाणा अरुवलकरयुक्त पहेचाय।
कोकहाहै मनमेंहर्ष अरुवीरता प्रतापवेगगति उदम
औरअंगोंविषेलघुना औरइंद्रियोंकीशुद्धि अरुहृदयकी
अग्निप्रकाशहोतीहै औरमार्गकेखेदकोंसहारणा अरुम
नप्रसन्नता औरनिर्गाप्पनाहोतीहै अरुग्रीवकुवारविलकर
अंगकोंकंपानाहै सारीहोतेहैं ८ अपणीइछाकाभोजन

© Dharmartha Trust J&K. Digitized by eGangotri

अरु विहार क्रीडा फिरना निद्रा और आसन बैठना यथायोग्य
और बल पुरुष इनां गुणां करके सहित यो घोडा है सो बारह काव
रहोता है ९ घोडेयां को नहि फेरने करके चमडे के रोग और
कफ के दोष सोजा निद्रा अरु सवीं के रोग होते हैं अरु वया
होते हैन १० तिस कारण ते घोडेयां को सूर्य के चडे देसभा
भूमि विषे अरु पवित्र और जिसमें कोई नहि ऐसे स्थान में फेरे
अरु यो बंधन के साथ बधे होए हैन तिनां को ११ वर्षा ऋतु वि
षे पहले घोडेयां को सस खेती के घास देवे गोमूत्रिका ते

परिभ्रमैर्लोहपेनाश्चारक्षावर्णभं वंतसश्चाः ९ तथा
दोषाः कफरोगाः श्वपथुस्तन्द्रा च पादरोगाश्च अ
श्वायामो चैषां दोषात्ते प्रवर्द्धने १० तस्माद्भा
नोरुदये समे प्रदेशे शुचौ निरावाधे वृक्षामये
नरेगान्स्तनिष्ठितान्पाशं वयेश्च ११ आदौ वर्षा
स्वहयांश्च सस्यं वै चारयेद्रोगानां गोमूत्रिका
करीरं तथान्नं जीर्णपादं तु १२ नावनमेका
तरितं कटु पिंड प्रथमना निरस्मांश्च कटुचूर्ण
कल्कोक्रमेनानितयापयेत्सातः १३ कारणः ऋ
श्ची वरुको च्चमौटी मृजन वल्लना वर्णा जनय
त्येने श्वानां वातातीसारल्हद्रोगान् १४ सहि
तलवणेन घृतषष्टिक भक्तं तु भोजने वल्प
पाने तु ठमरीछं शीघ्र कषायम पघ्रतःशस्त ॥

वेणा गंयन्नरण जीर्णपाद चाम १२ अरु तन सवार एक दिन छो
ड करके देवे अरु कोगी पिनी देवे और तन सवार का भेद तीन त्रण
न साद के और स्मद देवे और योकल्प स्थान में कटु चूर्ण कहे याद
मार देवे पहे समभवके उदिमान वेघ देवे १३ और कारणत्राय
दम वरी चमौटी मूंज वल्लन छपडी में जमे अरादा इतने यो
यन्त्रा गे पहेना पघोडेयां को वातकरा सुक अतिसार और हृ
दे के रोग उत्पन्न करने हैं १४ भोजन विषे सठी का भत्त चेड
अरु लूण के साथ बलकारक कहा है अरु पान में यो हलाव
ण या दा अकें मदिरा काथ इनो साथ वेगा है १५

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ टी॰ ७२

72

अरुनेलयोहै सोवनकेपत्तेयोंयोकेमासकेरससाथ सभा
योगोंविषेदेवे अरुपश्चाकारीफलावे पहेवर्षाऋतविषे वि
धिकहिहै १९ वर्षाविधिः ॥ वर्षाऋतुविषे सभऔषधीयों
मेरसवधनेहैन अरुतिनोऔषधीयोंमेहीस्थिरतेहैन सो
रसकौगहोताहै सर्वौरेतेनवीन होनेकरके १ तिसकोउर
सतेरक्तकिदाहोताहै फेरसोलहुपित्तकेसाथमिलके
वधेयाहुवा चोडेयांको योपहलेकहेहैन कोउ रक्तादि
रोग उनांकोपैदेकरताहै २ तिसकारणते तिन्हांचोडेयां

नांगलरसेनयुक्तैतैलंसर्वोपयोगतोदेयं आ
स्थापनेवदद्याद्दयंविधिर्वार्षिकप्रोक्ताः १९ वा
र्षिकविधिः ॥ वर्षास्वपिवर्द्धनेरसास्तसर्वौ
षधीस्थितास्तास्तु संजायतेकटुत्वंरसस्याव
ल्वभिनवत्वाच्च १ संवीयनेनतनोस्तक्तंतस्मिन
विमूर्छितंनरगाणां जनयतिशरदिविकारा
न्सर्वोदिष्टांश्चकुष्ठादीन् २ तस्मात्तेषांरुधिरंस
म्यग्भोगस्रावयेत्क्षुरकाले विस्तृतरक्तस्यभवेत
स्त्रानंप्रतिपानमसंगाः ३ दद्यात्क्षुंकंयवसा
धरूतरहुंवादनंदेयं सम्राहचानीतेच
नेनसंहृहयेदद्रुशः ४ विमलंतडागसलिलं
दिःकालस्नानपानयोःशस्तम् स्यान्निक्षिप्त
वासंज्ञमंस्पवनेनेनित्यं ५ मधुरकषायतिक्ता
नप्रतिकर्मस्यान्नयेद्दासानसततम् ।

कोकाडीकीयांजोनाडीयोंहैं तिनांतेलहूनिकाले शरदऋ
तविषे रुधिरनिकासकरके फेरस्नानअरुपीनेकोदेवे अ
रुमालसकरे ३ औरयामसकाराविदिनदेवे फेरत्रैदिन
केउपरंत दाणालानेकोदेवे यवमतदिनवीतनावे नव
येउकेसाथवलकरेवहुत ४ निर्मलतलावकाजल उ
हालने अरुपीणेको दोयकालवरतनचाहै अरुगात्रवि
षे चौडेयोंकाध्यानधाररकराना अरुधूपनिताहित्यागीहै २
अरुसमभकार्योंको मिला कोला तिस पहरमहियाउ

© Dharmartha Trust J&K. Digitized by eGangotri

अरु उगयकीपछकारी वहुतगुणकारकहिहै अरुखोले
वास्ते मुंगी अरु यवोंकेसाथ गुणकारकहिहै ६ अरुअ
भजवयोहै ...... सोहूंडेकहेहैं सोदेवे अरुस्निग्धमा
लसा बुद्धिमानवैद्यकरावे अरुशिशिरविषे निश्चयकरा
के चोउयोंकोस्नानकरावे पहेशरदऋतुकीविधिकहिहै १
शरदऋतुविषे विधिकहिहै सोलिखतेहो अवहेमंत
ऋतुविषे योविधिहै सोकहतेहो हेमंतऋतुविषेचोउयों
कोगर्म अरु विंदे योद्रव्यहै सोश्रेष्टहै औरसुखभुआणा

२९

शस्तश्रुपायोवस्तिः सयवाश्चहिताम्तथा शुक्रा
शीताः क्रमयवाः स्युरेयास्निग्धाश्चमर्दयेत्मति
मान् कार्यः शिशिरेविशेषेभिषेकोविधिरुत्तमा
रस्मैषा १ शारदविधिः। हेमंतेनरगाणामु
स्निग्धंचमस्तेसर्वे सुखपावनश्माबपि
यथागमंवैप्रयुंजीत १ भूयिष्टेमांसरसैर्भो
जनम्उपकल्पयेत् हुतेचवहुस्नानेस्वात्मप्रा
हेकोयंतोयंचपानाय २ शीतनिरुद्धस्तका
याग्निःस्याद्विमागमेवलवान् तस्माद्राहा
धारवोवराः प्रदेयास्युः ३ जठरेशीतसं
स्पर्शादेकपिंडीकृतोनलः रसंसशोषयत्या
शुतेनस्नेहोहितःसदा ४ जरणीयवारिष्ट
तेरंगप्रतिपाययेद्यथाशास्त्र।

अमपीणा वा अणीयां जेसेआयुर्वेदविषेकहेहैं तैसेयोउके
२ १ मांसरसवहुतप्रकारकेखानेवास्ते उआवे अरुहुतवीव
ऋतखानेकोदेवे अरुदुपहेरीवेलस्नानकरावे अरुलूप
कापाणीपीणकेवास्तेदेवे २ हेमंतविषेशीतकररोकी
होईशरीरकीअग्नि वहुतवलवालीहोतीहै तिसकारके
भोजन वीर्यकेवधानेवालीहोतीहै अरुभारे औरवनके
वासमांस इत्यादिदेणेयोग्यकहेहैन ३ उदयविषेशी
तकेस्पर्शकरके पिंडाकारहोईहोईअग्नि सोरसको स
ताबीसुकायदेतीहै तिसकारणकर्के स्नेहसदाहिहितकर
कहाहै ४ योस्नेहकोपचानेवाला अरिष्टकांजीभेद।

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰
टी॰
७३

73

सोपिलावे जैसेशास्त्रमेंकहाहै यहिशिशिरऋतुकीसारी।
विधिहै योहेमंतविषेंकहिहै ५ वसंतऋतुविषें श्लेष्मऔरक
फकेहरकरनेवालेरस औरनिरूहवस्ति एकएकदिनछोड
करदेवे औरकोईपढ्योप्रथमनस्यवारहितकारकहै १
औरस्नानादाचासश्रमकराणा फेरणाकोउभोजन रूक्षद्रव्य
श्रेष्ठकहेहै अरुत्वपकाजलसोयवेलेपिलावे अरुपकवे
लेन्हावे औरमिठारसनादेवे औरकाडीकीयानाडीते अ
रुसिरतेरुधिरनिकासे यहविधिज्ञानीयोंने छोडयोंकी

५ अथमेवविधिः शिशिरेकार्योहेमंतिकःकृत्स्नः
हेमंतशिशिरपोषणविधिः श्लेष्मोद्रिक्तोवसं।
तेरसाश्चकफनाशनानिरूहाश्च एकांतरेवद
द्यात्कदृष्टिपिंडप्रथमंनस्यम् १ रुक्षोयवसः
स्नानोव्यायामकटुभोजनंरूक्षं द्विःकालम
वकोपपानायहितंमहत्स्नानं २ मधुरस्न
रसोवर्ज्योवैहृद्यमन्नयोस्त्रपिरे एतद्वैतोव
संतेवातिहितंकीर्तितंमुनिभिः ३ वसंत
विधिः ग्रीष्मेस्यान्नशीतपयसःपानंवणी
तलंशाल्लं अन्नमधुरस्निग्धंघृतनिपानंवारुणी
मद्यं १ त्रिःस्नानपानयुक्तंसशर्करैः सक्तु
भिर्गौरयुक्तैर्वा नीरंद्वैतेस्वन्नीरीप्रदापयेत्
स्नानपोनाय २ त्वरसाश्रमतद्येवस्वेदंत्वन्
मत्रयातमस्य मद्यः शमयत्येषावलवस
र्वंयत्येव ३ व्यायामवलल्लंतरगःमहसायः
संनिश्रमेतेसावुधैः।

वसंतमेंकहिहै ३ ग्रीष्मऋतुविषें ठंडापान औरठंडाजल
अन्नमिठा घिरत अरु पानवास्तेवारुणीमदिरा गुडसाथ श्रे
ष्ठगणकरकहेहै १ त्रयकालस्नान अरुजलपानकरायके
नाई रेतसाथ सतेकरके अथवा गुडसाथ औरद्रव्यचत
करके नीरवस्तिदेवे वानीरणादेवे २ सोत्वघाश्यकेसा प
रसीनाछिकमत्रयान छोडकेसनाकी समनकरहे अरुव
लकोहलकीनतांवधातीहै ३ सनाकीकस्तीनाकरावे
फेरनहि योमत्रस्वसनाकीफेर तवसवोविषेरोगहोतेहै

© Dharmartha Trust J&K. Digitized by eGangotri

वाप्रसक्तनिकसयांदेहैन कार्यरहितहोतेहैं ४ तिस
कारणातेंबुद्धिमान घोडेनूंक्रमकर्कै फेरनेविषेयोरे गैर
पयोवस्तिदुग्धकीपछकारिदेवे पहिविधिग्रीष्मकीक
होईहै ५ घोडेयांकोवमननहिकरहैहैन अरुरेचनदस्तप
कवारदेलोकरहैहैन तिनांकेरोगांकेहरकरणेवास्ते वैद्य
नेनाडीवेधकरणाचाहिए १ घोडेयांके सभविकारांविषें
सदाहीलहूडुराणाश्रेष्टकहाहै एवंजलपियायकरके
तिसउपरंतनाडीवेधकरावे जैसेशास्त्रविषेंकहाहोवे २

तस्मात्पादविकारः प्रसक्तो वा भवेदेव ४ त
स्मात्क्रमेण मतिमान्व्यायामेषु नियोजयेद्दृष्ट्व १
दृष्ट्वा च पयो वस्तिदोषविधिग्रीष्मकः श्लोकः
ग्रीष्मविधिः वमनं नहि वाहानां विरेचनं वा
पित्तं स्वस्थहिष्ट तेभ्यः खलदोषेभ्यः सनतं ।
वेध्या शिरा भिषजा १ सर्वविकारेषु सदा ।
वाहानां रक्तमोक्षणं शस्तं पीते सलिले वा
हातस्मादेव व्यातशिरायुनाशास्तु २ यद्वा
पिस्कृतरक्तस्य वाजिनः किं विशेषवक्रियते
अविशुद्धशरीरत्वादपथ्यमेतद्विजानीया
न १ तस्मात्सर्वास्ववस्थासु शोणितं मोक्षये
त्पातः इति षडृतुकाध्यायः प्रवृत्तोदकवृद्ध
तोयो निर्वीनोद्वेलातपः अनूपस्तु सविज्ञे
यो हयानामशुभः सदा १ अल्पोदककटुमोपस्त
प्रवातः प्रचुरातपः ।
यदलाहूनिकासेहोए अस्तु
कौवीफेरदोषकीमात्रहोवे तो शुद्धशरीरनहिहोनेतें सोति
सकोंकुपथ्यहिजाणे १ तिसकारणातेंसभनांअवस्थाविषें
वेधरुधिरकोंकढावे इतिषड्ऋतुध्यायः जिसदेशविषें
जलअरुदरखतवहुतहोन अरुवायुनाहोवे भ्रपथोडीहोवे
सोअनूपदेशजाणे सोघोडेयांकोंहलाभनहिहै सदा
ही १ जिसदेशविषें जलथोडाहै अरुदरखतवीथोडे।
हैन गैरवायु ओर भ्रप वहुतहोए सोदेशजांगल।

शा॰
टी॰
७४

74

कहिआहै घोडेयांकोसुखदायकहैं १ जिसदेशविषे अ
नूप अरुजांगलदेशकेलक्षण रलेमिलेहोवें सोसाधार
णदेशकहाहै येहैत्रयप्रकारकेदेशकहेहैंन अरुजिस।
जिसदेशविषेयोहोवें तिसकोसात्म्यकहाहै अरुजि
सकोजोइछाहोवे सोविचारलेवे १ जिसदेशकाजलसभ
वडेगुणवालाहोवे तिसजलदेगुणकीवाहुलताते औष
धीयांवडेगुणवालीयांहोतीयांहैंन ५ औषधकेगुणकी
सेपानीकागुणसंपूर्णहोनेकरके देहकोवडतगुणहो

सेयःसुजांगलोदेशोहयानांचशुभःसदा १
अनूपजांगलोमिश्रोदेशःसाधारणःस्मृतः
एवंत्रिविधमेवेनदेशसात्म्यंविभावयेत् १
यस्यदेशस्यबाहुल्याज्जलेनोयगुणोमहान् तो
यस्यगुणबाहुल्यादोषधानांगुणोमहान् ४
औषधीगुणसंपन्नोशरीरस्यगुणोमहान् न
स्माद्देशप्रधानेनहयानांदेहधारणे १ देश
सात्म्यम् अतःपरंप्रवक्ष्यामिलवणस्यवि
धिंशुभ लवणस्यगुणायेचतन्मेनिगदितः
शृणु १ लवणंवाजिनांपथ्यंवातश्लेष्मनि
वारणं नभवेनहृद्रोगीनाजीर्णमुदारा।
मयः १ अरोगीचभवेद्वाजीवर्द्धनेचशिरोरु
हा नातिसारोभवेद्वास्यनवास्यग्रहणीभवे
त् १

नोहै तिसकारणतेघोडेयांकोदेहधारविषे देशहि
प्रधानहै देशसात्म्यकहेयाहै योरसवादेम सेवनकी।
कुवा सरवबाक्तहोवे सोसात्म्यकहाहै १ अवलूणकी
विधिसंदरकहताहां येडेलूणकेगुणकहेहैंन सो।
मेरवारकेकहेहोपसण १ लूणघोडेयांकोपथ्यगु
णकरहै वायुश्लेष्मदूरकरताहै अरुहृद्रोग अजीर्ण उ
दररोग नहिंहुंदे १ घोडेयांकारोगनहिंहुंदा औरबा
लाकोंवधजोरहैन तिसको अतिसार संग्रहणी रोग
नहिंहोते १

© Dharmartha Trust J&K. Digitized by eGangotri

अरु जो खायेहे सो सिताबीपचताहे सुखकरकेपरिणाम
परिपाक रसहोता है लूणखाणेकरके मलमूत्रसुखा
करहोता है ४ योंइयाको लूण आद्रक हेआहे जैसेम
त्रघाको हरीडकहिहे पहेसारनादेवे मत्तीरऊण गु
डरनोंकेसाथ औरतृषावालेको मधुगुनाको सूहोरे
वोडीको गर्भवालीकोंनादेवे और जिसकोंनवीनअति
सारहोवे वेगवालाउसकोंनादेवे कदाचित ६ एवम्
प्रातकालविषेंलूणदेना बहुतहितकरवाहाहे अरु

भुक्तंतुजीर्यतेक्षिप्रंसुखेनपरिणाम्यते सु
खंमूत्रपुरीषंतुलवणेनोपजायते ४ आद्रले
वणमध्वानानराणांचहरीतकी सर्वथान
प्रयोक्तव्यादोहृत्तीरगुडःसह ५ तृष्णामध्य
विषकानोप्रसूतायावगर्भिणी नवातिसा
रवितेनदातव्यंकदाचन ६ प्रातःकाले
वाष्यानेप्रायशोलवणंहितं प्रातर्हेलवण
दद्याद्धेमंतेशिशिरेभिषक् ७ अपराह्णेवसंते
वप्रावृट्ग्रीष्मशरत्सुच दीपनंवातशमनंहृ
द्यंस्रोतोविशोधनात् ८ शूलानाहविबंधघ्नं
लवणंसैंधवंवरम् ९ चातिनाविषमाग्नीना
मशाग्निक्रिमिकोष्ठिनां प्रशस्तंसैंधवंदद्या
त्परमारोग्यवर्द्धने १०

हेमंतशिशिरऋतुविषेंवेद्यलूणको प्रातकालमेंदेवे ७
वसंतऋतप्राहृटग्रीष्मशरद इनोंविषेंलूणसांझसमेंदे
वे सेंधवलूणहृदेकी अग्निकोंप्रकाशकरताहे औरवायु
कोंसमकरहे हृदेकोंहितकारहे नाडीद्वारकोंशुद्धकरनेतें
शूल अनाह बंदहोणा सबद्वारोंका मलकाबंधहोणा
इनोंकोहरताहे ९ पीडावाले विषमअग्निवालेकों मंदा
ग्निवालेको अरुकोष्ठस्थानमें कृमीयोंवालेको सेंधालू
णदेना बहुतगुणकरकहाहे रोगकोंहरताहे अरुनिरोग
नोंकोबधाताहे १०

© Dharmartha Trust J&K. Digitized by eGangotri

धा॰
ह्री॰
७५

75

वर्षाऋतुमें लूणकटूरीके पत्रोंसाथ देवै अरु हेमंतमें व
णके साथ देवै ११ पटोलके पत्र साथ शिशिर विषे लूण गु
णकेरेहु अरु वसंतऋतुके विषे कटूचूर्णके साथ देवै
सो चूर्ण आगे लिखा है १२ शरद अरु ग्रीष्मऋतु विषे लू
ण थोड़ा जैसा घेउके साथ देवै तिसकारणतें जिसजिस
ऋतु विषे योयो विधि कहि है तिसकर दीया हुआ लूण
रसायन वा जरा दूरेपा और रोग इनोंको शमकर कहा है १३
अरु तिसकी मात्रा प्रमाण पंचपल श्रेष्ठ कहि है अरु चार

वर्षासु लवणं देयं बिल्वपत्रेण संयुतं निर्गुं
डीसमायुक्तं हेमंते संप्रदापयेत् ११ पटो
लपत्रसहितं शिशिरे लवणं हितं कटुचूर्ण
समायुक्तं वसंते संप्रदापयेत् १२ शरद्ग्रीष्मे
षु लवणं स्वल्पं दद्यात् घृतान्वितं तस्मा
त्तु लवणं दत्तं विधात् रसायने १३ उत्तमस्य भवे
न्मात्रा पलं पंच प्रमाणतः चत्वारि मध्यमा स्व
ल्प त्रीणि दद्यात् कनीयसि १४ इति लवणवि
धिः प्रातरुत्थितस्य बाहुस्य मार्गे व्यायामशताय
ते चंक्रमणं लभ शूलं पित्तश्लेष्मानिलापहं
वैशम्यालस्यशोथघ्नं मारुतस्यानुलोमनं रो
गभ्यक्तिकरं वापि कायाग्नेरपि वर्द्धनम् २
श्रमापहं हर्षकरं तद्वद्देवोपवर्तनम् ।

पलमध्यम कहि है प्रातकाल विषे उठे हाथ पग्यो इंद्रीयोंको
सत व्यायाम लेमे मार्गमें फेरे दोय भुजा पसार करके योम
पहोता है सो व्यायाम कहा है १ सो अंग पुरुना पित्त शूल श्लेष्म
वायु इनोंको इनोंको नाश करता है १ अरु वैशम्य आलस
सोज रहता है अरु वायुको यथा मार्ग कर चलाता है
और रोगांको प्रगट कर देता है देह अग्निको वधाता है २
अरु तैसे हि यो उपवर्तन चक्र फेरना थकेमेको हरता है
अरु मनको हर्ष करे है चक्र फिरकरके उपरंत स्थित हो
कर यो अंगका कंपाणा है सो धातु रसादिक है ।

© Dharmartha Trust J&K. Digitized by eGangotri

तिनोंकोंसाफकरैहै ३ शोषफरमादिनामकोंरोगकाभेद
वालोंकेयोवणोहूयतिनोंकेसाथयोघर्षणखुर्कणा सो
वाल ५४ कोड़ इनोंकों शांतनहूकरनेहैं और को उकाना
शकरैहै अरुखुरककेहरणोंकों वहुतश्रेष्ठकहाहै और
जोयानलोहादि इनोंकावणयाहूआखोगा सुंदरपवित्र
सोवमउवर्णप्रकाशशोभा इनकेकरनेवालाकहाहै और
यातेदेहकीदफतासुखकरकरैहै अरुसंज्ञ महिष वकरी
भेड इनोंकेमूत्र अरुमलकरकेघोड़ेयोंकेगल वैणीके व

उपहूतोत्थितेचापिपूतं यातप्रसादनं ३ लो
महर्णकंकोटनाशनंकुष्ठनाशनं कहा
पंद्दपरेप्रोक्तंगोशफादिविघर्षणं ४ नवाव
णेप्रभाकारि प्रदिष्टंकुष्ठनाशनं प्रसादनंचधा
तूनांदेहदार्ढ्यकरंपरं ५ सखसायातभूते
वपवित्रश्रीमद्देववत् महिषाजाविकोमूत्रैम
लैडहतेनसरंत ६ कंडकर्णानरेश्यानोपर।
नच्छुसर्वेमहत् कंडूयनंपरंवाभिनेषांप्रोक्तं
मनीषिभिः ७ सत्यामादिभुकालेष्ठतत्समंर
तिदयाहतः नस्माकार्यंप्रयत्नेनतस्यकंडूय
नंनृपैः ८ रक्तपित्तश्रमश्वाससंतत्रसाग्ला।
निनाशनं यातप्रसादवलंचपुष्टितेजोविव
र्द्धनं ९ अश्वामर्दनपरंह्यंघेक्लेदनंभवतितस्यच

चकारउटणामलना वहुतसुखकरकहाहै औरतिनों
कोंयोखुरकना सोमुनियोनेश्रेष्ठकहाहै ७ घोड़ेयोंकेय
त्नकरकै खरखरा वाहथ्थफेरनावाइये वुद्धवानोंनेकों ये
गुहसमयमें औरथानोंमे सोजादरखदेहैन औररक्तपित्त
थकेमा दमस्वास भुखरेहै ग्लानता अरुतमा इनोंकाना
शकरताहै औरयातप्रोंकोंप्रकाशवलावधातीहै अरुवल
लकरैहै औरमसलकमैतेजकोंवधाताहै ९ औरघोड़ेयों
कों योष्णारदेणासंदरउलाना यहहृदयकोंप्रसन्न।
करनाहै अरुयोनलगानेखोयाहै तिसकोंनरमकर•

© Dharmartha Trust J&K. Digitized by eGangotri

76

पचादेताहै अरुश्रमकोयथार्थचलाताहै पानीपीनेका प
हैगुणकहाहै औरपरमाथ्थेकेमा रक्तपित्तपीडा इनकानाश
करताहै अरुबलकरहै औरमूत्रविष्टाविकार इनकोंहरक
रताहै औरयोवालफटेहैहैन तिनांकोउतारदेताहै और रंग
अरुथानबल प्रभा शोभा कांति लक्ष्मी पुष्टी देहकी इना॰
कोवधाताहै और मक्षीयांकीडे षटु इनांकोहरकरताहै १२
औरबलकरताहै और स्वरथानरसादि इनकों शुद्धकरता
है अहंकारबलकाअभिमानकरहै अरुदेहविषेलगुना

श्रमस्यानुलोमनंचापिनोयपानंप्रकीर्तितं १०
स्वेदश्रमापहंबल्यंरक्तपित्तातिनाशनं मूत्रवि
ट्पंकपांशुग्रंथ्युत्तलोमापकर्षणं ११ वर्ण्यमो
जस्करंचापिमक्षिकाकीटचूर्णनुत् छायाल॰
क्ष्मीप्रभाकांतिपुष्टीनांचप्रवर्द्धनं १२ आलस्य
शुद्धलकरंस्वरथानप्रसादनं दर्पसंजननंचा
पिलाघवोमादनं १३ जीवनीयंविशेषेण
ह्ययानांस्नानमुच्यते श्लेष्मातंकप्रशमनंमारु
तस्यानुलोमनं १४ ऊष्मप्रमेहशमनमश्वानां
पवखादनं सत्वाशनार्थयानांनांप्रयाने।
यवस्मृते १५ यवालाभेतवणाकंधान्यमस्य।
दनःपरम् स्यस्यहतेन्नरपणपरिवर्णानामध्या
यः। तयचननापहंबल्यंमाकृनस्यानुलोमनं

करताहै आलसकोहरकरहै १३ घोडेयांकोयोस्नानकराउ
ना सोजीवनकहाहै अरुकफकेरोगांकोंहरताहै वायुकों
यथामार्गचलाताहै १४ घोडेयांकोसखकरकेघोनेवासे
अंत्रांविषे नवहिप्रस्तकरहैहैन औरकोउप्रमेहमूत्रविकार
इनांकोहरतेहैं १५ अरुयवनामिलनोछोलेदेवे और
अन्नइनांनेपरेहैं कायोइगुणकरहैन यहस्नानवकायुक्त
घोडेकीविधिकरहैहै अध्यायः॥ सस्यखेनीकेनदण सा
कोमाघइत्यादिक घोडेयोंको मनीयोनेरसायणकहेहैं
अरुतोइकामवायुइनकोनाशकरतेहैं अरुवलप्रोरदेहकी
अग्निइनकोहलीनरावधानेहैं औरवायुकोंयथार्थकरके

© Dharmartha Trust J&K. Digitized by eGangotri

बढातेहैं और योविना मार्गलेदर्थिं थकेमा ग्ररुवानादिदो
षनिंनोंकोहरतेहैं औरछाया प्रभा वलगुवे थात्न वीर्यकोप
हीहर्दि ग्ररुवेगवाली गतिशोभा वर्णकोशोभा इनाकोवा
धातेहैं रसायणहहुतायाथि इनकोंहरतेहैं २ सस्यके
कालत्रयकहेहैं वर्षाहेमंतशिशिर आषाढ श्रावण वा
भाद्रों पेहप्रावृट ऋतुकहिहै मघेर पोष हेमंत माघ
फाल्गुण शिशिर ऋतुकहिहै पेहत्रयकहीहै ३ सांकीगे
र माघ इनोंथे नववीर्यके वधानेवालेकहेहैं सजरेग्ररुक

कायाग्नेर्वृंहणंसम्यक्शमंदोषापकर्षणं १
छायारूपकरंधात्नवंदेयम्नतिष्ठिदं शौछा.
शननेचापिकांतिलावण्यदंपरं २ रसायन
नंरंगाणांसस्यशुकंमनीषिभिः प्रावृट्हेमंत
शिशिराःसस्यकालास्त्रयःस्मृताः ३ मघामाघ
माघयोःश्रीकाय्वस्यापिवीर्यदाः ग्रपर्यु
षितमक्लिन्नमकीटातपरूषितं ४ हरितंका
लनंपुष्टमितरूकःसस्यसंपदः विपरीतमशस्त
स्मात्तत्त्वार्यंगुहिहे ५ क्लिग्धेविशुतिसंशुद्धे
निरूढेवानुवासिते संस्वर्णावलारोग्यवीर्य
दंप्रतिपादितं ६ तिथिनक्षत्रशुभेन्हिहेकवार
तावियानतः दंयनवजलोद्भदीस्यलीए
शोद्भवस्यण ७

मलापनाहोन औरकीड़े धुप इनोंकरके दूषित विगडेना
होवें मैलेहुए औरअपनेसमयविषे नमेहोवें गुटेहोवें प
हरेवनीके श्यामश्रोकीसंपदाश्रेष्ठनाकहिहै औरइनोंनेविप
रीतउलटेहोवें तोनिषिद्धहोतेहैं सोनहिवारनेयोग्यहैं जि
नाचोउयांको रुधिरनिकालेयाहोवे ग्ररुस्निग्धछोतनेला
दि पञ्चकर्म वराइहोवे वा रुक्ष कायकी पञ्चकारीदेइहो
वे इनाकोंस्निग्धकीये उपरंत थाय सस्य वल रंगसुंदरतानि
रोग्यताबीर्यकराकहेहैं ६ श्रेष्ठतिथिनक्षत्रमुहूर्तेदिन वि
षेरत्ताविधिकरके श्यामयोमाकष्टिश्राटिले औरनवीन
वर्षाकेजलोंकरके भेटकोंप्राप्तहुएशुवीतिसके रूपर.

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ टी॰ ९८

जमेंहोपनोहैं सांकरमादिकसंदरनीलवर्णोके जिनों
करकेपृथ्वीसभायमानहोनीहै सोकीन्याईहैरंगके
याहेंद्यासमेरभपवसतिनोकरके पकीहोईहोवैजैसे ८
पहिले वालछोरी फेरसगभी होयि पाकीरी पहेकवी।
भेदोचाहै अरुपक्कीहथिरादियानेकोवखानेहै ९ जब
माषोंकासमयहोवै तोत्रोउयोंकोंमहाउआवे आदवि
षेफलेहूयेमाषदेवेवानेको १० अरु यजेहुइकरको
गवनाके सेरकैतिलमिलायकेदेवै अरुमहाफलेदे औ

श्यामाकाद्यैर्मलैर्नीलैर्येनश्च्र: समलंकृता:
कांतेव भाति वसुधा शामा सस्योपकाहृता ८
वाल: सगर्भ: सम: हीरंतेलपाक्कान् श्या
माक: शोणितादीनां हृदावालोभवेस्क: ९
माषकालेन संप्राप्ते माषोस्तेभ्य: प्रदापयेत्
आदौपुष्पितान्माषान्वासरणायप्रदापयेत् १०
यवांस्तु निस्तुषान्निस्त्रान्दापयेत्तिलमिश्रि।
तान्माषांस्तु संप्रदानत्त्वा: पुष्पिताफलितास्त
था ११ पुष्पितारसजननाः फलितामांसवर्द्धना
पक्वामेदस्तथास्थीनिमज्जस्नायुतथेद्रियं १२
वर्द्धयंतिक्रमेणापुष्पानांमाईवावितान्
अपुष्पितास्तु फलिता: सर्वदोषविवर्द्धना: १३
अपथ्यास्तु पुनस्तेषां वारिस्नानफलास्तुये जन
यंति रुजाकोष्टेगुरुत्वाच्छूलमेवच १४

रफलदेदेनेयोग्यकहीहै ११ फूलेहोदेमहांलहूवखानेहैं औ
रफलेदेमांसकोवखानेहैं पकेदेमिफुरहडीयामज्जानाडी
यांइंद्रियांकोमललाक्रमकरके वृद्धियाकोंवखानेहैं १२
अणफूले अरुफलेदे सभदोषांकोवखानेहैं १३ अरु
तिनोंकेवीच योकरलमायेहै औरफलकलमाश्रे बहुत
अपथ्यहै अरुपेटमेंपीडा औरशूलकरतेहैंन भोरहो
णेकरके १४ तिसकारणतेमृदितातृणसोच्यचैन
नैल वा गोमूत्रइनोंकरके तीसरे तीसरेदिनमेंपछेकार

© Dharmartha Trust J&K. Digitized by eGangotri

वढावे सो वस्तिदेहकी अग्निवलकोवधातीहै १५ औरफ
लेमाषाकेखादेहोंयाको मूलकेहटानेवाली मदिरा लूण
औरतेलकेसाथदेवे १६ पहेमाहांकेदेनेकी विधिकहीहै
यदयवोंकीवहारआवे तदयोडेयांकेनाई पगदेवे सो
यव छेप्रकारकेकहेहैन छोटे छोछा मटीवाले गर्भि दो
दिवाले उडेवाले पकेदे पहेछेकहेहैं कषाय तिक्त कटु
कटु मिठे खारे कोड अम्ले पहेहैं जेय षट्रसवाले होतेहैं
सगर्भिगर्भिवालेदेवे जोछोटेहैं सोरसअरुपाकविषेको

तस्मात्तु तं सलवणं स्नेहगोमूत्रसंयुतान् व
स्तिमेकान्तरं दद्यात्कायाग्निवलवर्द्धनम् १५ स
सलवणं चैव तैलेन सहसंयुता फलितेषु
च माषेषु दद्यात्कुलविनाशिनी १६ इतिमाष
विधिः यवकालेन संप्राप्ते यवालेभ्यः प्रदाप
येत् तरुणा गर्भिनश्चैव शुष्कानास्त्री रिनस्तथा
सतेद्रुलोथपक्कश्च यवास्तेयश्च षट्विधः कषा
यतिक्तमधुरः सक्षारः कटुकस्तथा २ अम्लभा
वान्विताश्चैव षट्रसो हरितो यवः प्रथमं तरुणं
स्तेषु सगर्भं नप्रदापयेत् ३ दोषप्राव्यावनकर
कटुके रसनस्तथा मूत्रलस्तरुणो भेदी क्लेदनो
वातलस्मृतः ४ नालिकापत्रवद्दाहक्षुष्णाशु
हिकराः स्मृताः गर्भिनाक्षारकटुकाश्च पाके
मधुरा यवाः ५ मांससञ्जननः प्रोक्ताः श्लेष्मला
मूत्रलाश्च ते।

उहोतेहैं अरुदोषकोवारनिकासदेतेहैन अरुपक्काव व
हनकरतेहैं औरदस्तलगातेहैन औरग्रंदरतमेंकरदेता
है वातलहै ४ अरुयोनाली औरनडवधाहोय सो यव
वीर्यदेहपुष्टिके करनेवाले कहेहैन येउगर्भिवालेहैन
सोखारेकोड औरपाकविषे मधुरकहेहैन ५ सो मास
कोउत्पन्नकरतेहैं औरश्लेष्ममूत्रकोंकरतेहैन येउनिसरे
हैन अरुरसकरणोहैन सोमज्जामेदकोवधातेहैं ६

© Dharmartha Trust J&K. Digitized by eGangotri

पा.
हो.
७८
78

पाकविषें मधुरकहेहैं पचनविषें दुःखकरकेपचवेहैंहेन
अरुवायुकोकोपकरानेहैं अरुयेदाढीवालेहैन सोमिठेवि
कनेहैन सेपमकारहे दुःखकरपचतेहैन पाकविषेंमिठेकहे
हैन अरुमिकअरुअस्थिकीगिरी इनकोंवधातेहैं अरुदूदे
षहैरसकरयुक्तहे सोविपाकविषेंमधुरहै ८ सोइहविषेंस्थि
तहोपदे अहहोकरपचतेहैन औरवलकारकहेहै पक्केद
यव षट्रसयुक्तहे सोविपाकमेंमिठेहैन मासकोंस्थिरक
रताहै औरमज्जामेदहड्डी वर्म इनाकोदृढकरातेहैं यवों

निःसृताः सरसोपेता मज्जमेदोविवर्द्धनाः ६
विपाके मधुराः प्रोक्ताः दुर्जराः वातकोपनाः स
नीताः मधुराः स्निग्धाः श्लेष्मला दुर्जरास्तथा ७
विपाके मधुराः प्रोक्ताः मज्जमेदोविवर्द्धनाः
इंगलावद्रसोपेता विपाके मधुरास्तथा ८ वि
दग्धेतेवकोष्ठस्याव स्थास्तथा निदर्शिताः पक्षा
तु षट्रसोपेता विपाके मधुरास्तथा ९ स्थिरी
कुर्वन्ति मांसं च मज्जमेदोस्थिचर्म च यवास्तथ वर
नामे धातुप्रवारविधिः स्मृतः १० सप्तरात्रं क्रियाः
सर्वाः पानीयं च निषेधयेत् अष्टमेह्नि निर्दो
षान्समीक्ष्य गुणलाघवं ॥ मस्तिरस्का स्थकेलो
सेन वारिणा परिषेचयेत् एवं भवन्ति निर्दोषा
छायावन्तः सुवाजिनः ११ कफप्रमेहकासाद्यादि
विविकस्थानि मातृनः पृथगेवं प्रदातव्यं लवण
नसमायुतम् १२

केवांदैदोयाघोडेयाकोयहविधिकहिहै सोअगोलिखिा
है सो सुणे १० सातदिनपर्यंत सभक्रियाविधिमागे अरु
जलनादेवपीणेको अरुअठमेदिनविषें दोषरहितअरुल
गुणदेखकें गर्मजलसेसिर सहितसुखवे यावे इसप्र
कारघोडेनिरोग अरुछायाप्रभावालेहोतेहैन ११ सुख
लेलाला अरुजलवहतनवां भिन्नभिन्न नवग्राहिकल
णसाथ देणेयोग्यकहाहै १२

© Dharmartha Trust J&K. Digitized by eGangotri

तीसरे दिनके उपरंत तिन्हूंको पाणी थो उनेसे पिलावे
तृषा जो है सो मूर्च्छा करती है अरु मूर्च्छा प्राणोंको हरकर
ती है १४ यो थोउ चालिसदिन यवों के तण खोरखे ति
सके रोग धातुके विकार अरु कोष्ठ उदरयके रोग शम हो
जाते हैं अरु यथा अन्न विषें सेवे हूये निरोगपताको करते
हैं सभ रोग हरते है न १५ हरेयउ थोउ येंको परम रसा
यण है रोग ढरे पारनको हरते हैं पहले सात दिन दस्त।
लगाते हैं दूसरे लहू वधाते हैं तीसरे मासे विषें मास जा
मता है मोटा होता है अरु चोथे में मिंक हठ होती है अरु

ग्रहाहृद्वैतस्तेषां वैनोयमसंतद्दापयेत् त्व १४
ग्लानिमूर्च्छां जनयेन्मूर्छां प्राणैर्विमोचयेत्
मासंसहस्रराात्रं तु यो यवान्त्रिसरणं चरेत् दो
षास्तस्य प्रशाम्यन्ति यान्तु जायेव कोष्ठगाः श्रा
रोग्यं जनन्तास्यैव यथा तं परिसेविना: १५ पर
रसायने प्रोक्तमस्यानाहरितोयवः श्राद्येवि
रेकः समाहद्वितीये रक्तवर्द्धनः तृतीये जा
यते मांसं चतुर्थे मेदसंचयं अस्थिनी मज्जशु
क्रं च वर्णः प्राणो जवस्तथा १६ पंचमे चैव षष्ठी
च सप्तमे चैव वाजिनां लभ्यन्मासाभवेत्सेवया स
र्वव्याधिवर्जिताः १७ अतऊर्ध्वं तु येवा ह्याश्च
ति हरितास्तवान् रूपवर्णवलोपेताप्रमाशु
रवायुषः १८ इतियवविधिः स्नेहः सस्यव
योगाश्च त्र्ययमेतत्त्रिदंडवत् ।

पंचमे छेमे सतमे विषें हडीयां मजा वीर्य वर्ण रंग प्राण
वेगगति पहर होते हैं १६ यव खोट प्राप्त होइ है तद रसथा
तमें योरोग है तिनोंते रहित होते हैन १७ अरु येउ थोउ
यों को हरेसे लयव वारते हैं सो रूपवल वर्ण इनों करके
युक्त होते हैन अरु संपूर्ण आयुषाको प्राप्त होते हैन १८
इतियवविधिः स्नेह घृत तेल मस्य पह आदा घास
खेती का अरु औषधका योग पहे त्रय त्रिदंडकी न्याई
वेगगति स्वरूप बल इत्यादि गुणोंको थियत है त्रे।
दृवगको और मस्य वाम इपको अरु योगवलको

© Dharmartha Trust J&K. Digitized by eGangotri

पा॰ हो॰ ७९ 79 वधानेवालेस्थितहैं १ छोलेहरेबुद्धिवानोंनेवारतरांके
कहेहैन एककेवलचूरीवाले दूसरेकछुकअन्नवाले
तीसरेचंगेदाणेवाले चौथेपकेदेएहेहेन २ येउकेवलवा
युकरभरीयाछुंरावालेछोलेहैं सोलूणकेअमलेतिक
मधुर औरभारेकहेहैन अरुदोषकोंवाहरनिकासतेहैं औ
रभेदिदस्तकरकहेहेन ३ येउ जिनोंविषेकछुकफलहो
एहेन सोतिक्तरसअरुपुष्टदेहकाहै औररक्तकोंवधातेहैं
येउसारवालेहै सोमधुररसहोतेहैं अरुहारिमासको

नवरूपबलादीनां गुणानां त्वमवर्धिनं १ च
नर्विधः समुद्दिष्टो हवितत्त्वणाकोदयेः वात
दूर्णोऽह्रसारश्च सारोऽनपक्वपव च २ लवा
णाल्प्रसतिकश्च गुरुर्मधुरएव च दोषापक
र्षणो भेदी वातपूर्णः प्रकीर्तितः ३ किंवि
ज्ञातफलस्निग्धः शोषनो रक्तवर्द्धनः सार
वाच्छकं तनतोमधुरो दृंहणो गुरुः ४ स्थिरो
विवर्धयेन्मेदो मज्जशुक्रवाजिनां अयोग
दन्तो मद्दसु वै योगदन्तो यथामतं ५ हिमवद्वि
न्ध्ययोर्मध्ये प्रशस्ते वाजिनो यवाः तथा दक्षि
णतो विन्ध्यान्मुनिमध्यः प्रशस्यते ६ गोरस्मा
रितोऽश्वानां मधुरश्शोषवर्द्धनः सत्नीरश्वा
सवीर्यश्च प्राणमांसविवर्द्धनः ७ केउा
गास्यरोगश्लेश्मावर्द्धनः शुक्रमेदसो ।

वधातेहैं भारेहैं ४ येउएकदेहेन सो चोडुयांको मेद म
ज्जा वीर्यको वधातेहैं अरुदेहकोयथार्थरखदेहैन सो
विधिकरदोषहुये अस्तगुणकारहै अरुयोगविधिसेंवि
नादोषहुये निश्चयकरअस्मकुरैहै ५ हिमालय अरुवि
न्ध्याचलकेमध्यवीचघोड़ेयांको यवगुणकारकहेहैं तेसे
हि विंध्याचलपर्वतके दक्षिणविषे छोलेश्रेष्ठ गुणकेकर
नेवाले कहेहेन ६ सेलीकनक घोड़ेयांके सूषकोंवधा
तीहै औरमधुरहै अरुयोसेदीवालीहै सो वीर्यविषे
गर्मकहिहै और मास प्राणको दृढकरैहै ७ और गल
रोग मुखकेरोगकोंनाशकरैहै औरवीर्य मिजकोंवधा

© Dharmartha Trust J&K. Digitized by eGangotri

तीहै और वीर्यकी वृद्धि करणेवाले यों विषै वहुत श्रेष्ठ है
और खेती के घासों में वी वहुत गुणकारहै यवपकणेवा।
ली होइहै ८ यदकनक अरुयवों के ऊपर मखीरखणावरकी
नणें विंद देवीये अरु मत्तीरवाले कीडे जिसके ऊपर वैठे।
नहिं देणे होवै ९ ऐसा घास जानने वालियां ने घोडेयां को नहिं देणे
योग्य सो विकीको प्राप्त होया रस वीर्य तिसतें पित्तरक्त
कौ विगाडदेताहै १० अरु रक्त पित्त के कोपतें वेग वडे उल
रहोते हैं न ड़लदेणेवाले तिसकारणतें मधुरमुगयोंवा
सहै सोकरदेवी नादेवे ११ उच्चैश्रवानामकरयोहै इंद्रका

हृद्याणां चोत्तमो हृष्टः सुस्थानां तं दुलान्वितः ८
गोधूमयववयोर्वापि हृष्टंपतेयदि विद्रवः मधु
फाणितसंकाशाः क्रिमयो यत्र माधुकाः ९ हृ
यानां नादृशो संस्थेन देयं संविज्ञानता आप
न्नस्य वीर्यं ता कोपयेत्पित्तशोणिते १०
प्रकोपाद्रक्तपित्तानां रोगाः सन्ति सुदारुणाः
तस्मान्मधुकसंसृष्टं यवसेन प्रदापयेत् ॥
उच्चैःश्रवसोस्य नत्तः पतिताः फेनविद्रवः
धरण्यां प्राप्य ते जाता हिपिन्य इति संज्ञिताः १२
श्रेष्ठः स्वदेशजः श्रेष्ठो मात्रया सर्वदा हितः
भूमौ नष्टो न रसौ च यवने शुचकामतः १३
रसायनानां प्रवरो रोगनाशन उत्तमः सा
त्म्यं च परमो ह्यानां आयुःसूत्रो विवर्द्धनं १४
हिपिन्य रूपमस्तन्तं हयानां परिकीर्तितं

वाहन समुद्रतें निकसा दारत्तरूप तिसके उछलने करके
प्रस्वेद कीयां विंदु पृथ्वी में पडने करके तिन्हां के हिपिन्य
नामकर के इस्म होता भया १२ अपने देसविषै पैदहोया दा
श्रेष्ठ गुणकार है पीसकर प्रमाणकादीया हूआ सदा ही
गुणकार है सो उत्तर दिशाकी पृथ्वी विषै यवनदेश में।
होता है तिन्हां को वोलतेहै १३ अरु यो रसायन इस्म है
जरा व्याधि नाशन तिनों विषै प्रधान श्रेष्ठ है अरु रोगोंना
शकरणे को चंगा है सो घोडेयां को सात्म्यहितकर है अ
रुआयुषा नेनको वधाना है १४ सो हिपिन्यघोडेयांको।

© Dharmartha Trust J&K. Digitized by eGangotri

अमृतरूपकहेयाहै सोरसविषैं मिठा अम्ल कषाय रसहै
तेसेहीहै १५ सो ऊसा अथवा योसाथदीयाहुआनिरंतरह
र्षकरैहै तिसकारणतें तिसको यवोंकेसाथ अथवा वासके
साथदेवे १६ अरुयोञोउजुरे अरुरोगकरउकरै नतिनोको
प्रमाणते केवलऊसाहिहितकारहै अरुयोञोउजवनदेस
कीउतरभूमिकाजनमेआहुआहै तिसकोसात्म्यहोणेतेंवल
कोंहडकरताहै १७ मंगीदादीवालीलहूकोवधातीहै अ
रुफलीदीमासकोंवधातीहै अरुयेडीपकेदेफलेवालीहै
सेकफ अरुपित्तकोंवारनिकासतीहै १८ योमुगीकोमल

स्मेनमधुरः साम्लः कषायानुरसस्तथा १५
केवलस्त्वभियोगेन हृद्यो हर्षकरः शुभः तस्मा
द्यवेन संमिश्रो देयात्तयवसेन वा १६ हय
माथितवाहानां मात्रया केवलो हितः यव
नोत्तरजातस्य सात्म्यत्वाद्बलवर्द्धनः १७ मसी
रारक्तजननी फलिना मांसवर्द्धनी कंठः प
कफला चैव कफपित्तापकर्षिणी १८ रक्ते
निम्नि हृता वसुद्रो मृदुफलः स्मृतः वात
लस्तु रूणो श्वेष्यः पुष्टिनः कफनाशनः १९ फ
लिना चैव यमुद्रा तेया स्तु मधुरा रसे विपाके
मधुरा त्वेता न च वातप्रकोपनाः २० काश
योणितपित्तानां हिताः श्लेष्मविशोषणाः
मकुष्ठाः फलिना ज्ञेयाः पक्वाश्चैव विशेषतः २१
फलिना मधुरा हृष्या रक्तमांसविवर्द्धनः

फलोंवालीहै सोरक्तपित्तकोहरतीहै अरुयोछोटी
अरुफुलीनहिहै सोवायुकारकहिहै येडीफुलीदीहै
सोकफकानाशकरतीहै १९ अरुयेडीमुगीफुलीदीहै सो
रसअरुविपाकविषैंमीठीहै अरुरूक्षेहै वायुकोंकुपित
नहिकरतीहै २० सोठफलेदे रंगरुधिरविकार अरु
पित्तकेरोगवालेघोडेकोंहितकरहै अरुकफकेसका।
नेवालकहेहैन अरुयोपकेदेहैन सोनिश्चयकरहैव।
नेहैन २१ फलेहोएमिठेहैन वीर्यरुधिरमासकोंव
धातेहैन पकेदेवडीदेहपुष्टीकर औरसमधातुके

© Dharmartha Trust J&K. Digitized by eGangotri

बधानेवाले हैं न २२ तदमदिरालूणासहित देवे और तेल
बी देवे कुलथ्य मसर में एक कषाय रस है अरु यउ मधुर हो
ते है २३ सो रक्त पित्त को हर करते है अरु वायु को कुपित कर
ते है सभ नाजों में विषे हरीं खेवल की यां बहुत पथ्य कही
या है २४ सो हरीं कसेली यां मिठी यां अरु हृदय को प्रय कर
और वीर्य विषे ठंडी यां होती है न और वल वीर्य रुचि कर है अ
रु सभ प्रकार के रोगों को नाश करती है २५ ग्रीष्म रुत्त वि
षे सो चोडे यां को विशेष कर के हमा वे ये जे चोडे खेवल
कीयां उवा खाने वाले है न तिन्हां को वायु कर पित्त क

पक्काम्रमखुष्टिकरा: सर्वधातुविवर्द्धना: २२
तदा मद्यांस लवणं तैलं चापि प्रदापयेत् निष्पा
वाश्च कुलत्थाश्च कषाय मधुरा यवा: २३ रक्त
पित्तहराश्चैव तथा वातप्रकोपना: यवेषु
वसर्वेषु हरीं पथ्या तमास्मृता २४ कषायम
धुरा हृद्या शीतवीर्य्या बलप्रदा: हृद्या रुचिक
री लघ्वी सर्वरोगविनाशिनी २५ ग्रीष्मकाले
तु रोगाणां विशेषेण प्रदापयेत् वातजा: पित्त
जाश्चैव श्लेष्मिकारक्तजास्तथा २६ तरोगा:।
पीडयिष्यंति सर्वांहरिं स्तान्गमान् अनूपप्रभ
वा मानां निद्राम्लं भंगलग्रह २७ कोष्मण्यास्त
था रोगान्ग्रांडमालार्बुदादिकान् विभर्जिका
नीलिपादं ताप्रहंता प्रशापिका २८ गिरिजू
णं वनीवारा: सामाकरूहविंदका: ।

फुकरक्त कर होए हु ये रोगन हिं क्लेश पीडा करदे सो हद
वी जल विषे जमी होए जिह्वा को जडकार है और गल को रो
क देती है २७ और रोग हजीरां रसोलि इत्यादिक रोग क
रहे है विभर्जिका और भगाले वीली मूलवाला और पले ग्रामा
नाश के रंग के हैं न यत्न का अशोपिका रूण विशेष वीण
पर्वत के रूणघास नीवार सांकी चोडे विषे होणे वाली
स्यामांक सांक भेद रूहविंदक मुसयां का घास पहे चा।
सतवर्षा के होणे वाले वर्षा रुत्त विषे हि तक रुहु शाल
के धणी सांक और वण के घास और यो कसेले मिठे।

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ हो॰ ८१ तृणहैन सो शरदऋतुविषैहितकरहैन १०. मुद्गपर्णी
और माषपर्णी वनके माषमूंगकहेहै और मेढासिंगी और
येनिर्दोषघासकहेहैन शिशिरऋतुविषै होनेवाले सोशि
शिरमें गुणकरहै ११ वसंतऋतुविषै पापडा विभडकाघास
यवनालतृण इनकाघासहोलाहै और येउकोउतिनकहैन सो
वसंतविषैदेनेयोग्यकहेहैन १२ विल्व पिपल पलास
कमल न्हाये कमलकीगंठी भपडवी शिवाल ज्वाला मु
म्यर १३ .... सिंचितकीये ऐसा घास ग्रीष्मकाकहाहै
वभेकाहि वेरी सहित जडांदे मुज और छपडीयोंके

वर्षास्वथवसन्तेतेचाप्यन्नेप्रभवामताः १०
शालःप्रियंगुःश्यामाकोजांगलंवापियत्तृण
हिताःशारदियेचामेकषायाःस्वादवोमताः २०
मुद्गपर्णीमाषपर्णीतथामेषविषाणिका
शैशिरेयवसंदद्यात्तथायच्चाप्यनिंदितं ११
शाल्मलिकुःपश्यटकमत्रुषायवनालिका
मयौदेयस्तुयवसोयच्चान्यत्कटुतिक्तकं १२
विल्वाश्वत्थपलाशानिकमलान्यमलानिच
मृणालविषहर्तीश्वशैवालानिकशेरुकाः १३
गुडोवदाकाचसिक्तंतुयवसंग्रीष्मकेमतं उ
शकाशावकटकाल्यौःसपादांश्चजवल्वजाः १४
अश्वत्थवेणुपत्राणितथाशुष्कतृणानिच मू
लानानातिसारांणांरुद्रोगस्यवहेतवः १५ य
वानांतुबुषाकृतंयच्चान्यनहितंभवेत् वि
बंधभेदनेकृतंतुषांगोऽपस्मसंभवं १६ तुषा
णिसर्वसस्यानांतथाशुष्कतृणानिच ।

घास १४ वडके अरु वंशकेपत्र अरुतेसेहिकेदेतृणघास
ए हे शूलअनाहरोगवंदहोलाा सभदरोंका अतिसार हृदो
गइनोकेकरनेवालेकहेहैन १५ और यवोंका भोरुलोहै अ
रुपेड और रसीतनेकेहैन सोवी रुखेहैन येडाकाणके
काभोहै सोकवजीको भेदनकरहै रुसेहैन १६ औ
र सभ सस्यहोनीके घासके भो अरु सके घास सो

कौडे हले कषा है और वीर्य रहित देखे १२ इति सप्तविधि:
बुद्धिमान् वैद्य यो है सो इनके आश्रय विषे रस गुण वीर्य
विपाक जाने मधुर अम्ला लूण कौडा तिक्त कषाय एहे छे
प्रकारके रस कहे हैं १ कैक वैद्य ऐसे कहते हैं अम्ला लू
णका एहे दोय रस एहले कहे हैं अरु मिठा तिक्त एमध्य
कहे हैं कौडा कसैला एहे दोय अन्त पीछेके कहे हैं आद
के दोरा लूणका वायके हरने वाले हैं अरु वछकारके मि
ठा तिक्त पित्तके नाश करै है अरु इहकी विधि करदोएहप

कटुरुत्तकषायाणि निर्वीर्याण्युपलक्षयेत् १२
इति सप्तविधि: इत्याश्रितो रसगुणै पाकवी
र्यं वलक्षयेन्मतिमान् अथ मधुराम्ललवण
कटुतिक्तकषाया: षडेव रसा: १ अम्ललव
णौ विमौ द्वावाद्यौ मध्यौ न मधुरतिक्तारव्यौ
कटुकषायावंत्यौ के चिन्मन्यंते वदंत्येव २ न
माद्यौ वातहरौ पित्तघ्नौ मध्यमौ विजानीया
न् मस्मकवदमृ प्रयुक्तावंत्यौ कफनाशनौ
तेयौ ३ एवं द्वौ द्वौ नरसौ नियच्छन्नत्र्योन्ह दो
षमेकैकं त्रय एव रसा दोषशमयंत्येकैक
मष्यस ४ अम्लो लवणो मधुरो रसास्त्रिमे
वातनाशना: प्रोक्ता: हेतिक्तकषायस्तिक्तो
मधुरश्चैषां रस: पित्ते ५ त्रयस्तिकषायस्ति
क्त: कटुकश्च रस: कफं समनुजून एवं दोषा
त्रितयं त्रिभिस्त्रिभिर्वा रसै: शमयेत् ६

अंतके कौडा कषाय कफके नाश करणेवाले या ए ३
एह दो दोरस इक इक दोषको रोकते हैं और त्रय त्रय
रस वी एक एक दोषको छोडके शमन करते हैं ४
अमला लूणा मिठा एहे रस वातके नाश करते हैं
कषाय तिक्त मधुर रस पित्तको नाश करै हैं ५
कषाय तिक्त कटु रस कफसे दोषरोगको जीतता
है इस प्रकार त्रिदोषान् त्रय त्रय रसो करके श
मकरै ६

© Dharmartha Trust J&K. Digitized by eGangotri

धा॰ और कोउ तिक्त तीक्ष्ण कसैला ए है त्रय रस वायु के बधाने
हो॰ वाले कहे है न और कोउ लूण अमला ए है रस पित्त को बधा
८२ नेवाले है ७ अमला लूण मिठा ए है त्रय रस चोउ ये यां के क
फ को वधाने है न ए है छे प्रकार के रस आमि रोग के उपदेश
82 वास्ते कहे है न ८ इनके ए हे अठन रां के गुण यथार्थ करके
कर दिखाए है न ठंड गर्म चिंदा रुखा निर्मल पिछल चिपा
नीवाला कोमल चिकण ९ भारा सूक्ष्म होला तीक्ष्ण स्थि
र हल्ला अवापि सारे देह विषे गुण को विस्तार करके पवन

अथ कटुतिक्तकषाया रसास्त्रयो वातवर्द्धनाः
प्रोक्ताः कटुलवणाम्लाख्यरसाः पित्तवर्द्धयं।
स्तेन ७ कफमम्ललवणमधुराख्यो रसावर्द्ध
यंति नृणां एषमाभुप्रदेशो रसाः षडे
वहि समाख्याताः ८ व्याख्याविलक्षणादशा
नेव निदर्शिता गुणास्तेते शीतोष्णः स्नि ९
ग्धो रूक्षो विषदः पिच्छिलो मृदुः श्लक्ष्णः
गुरुर्मंदलघुस्तीक्ष्णाः स्थिरो व्यवायि वि।
काशी च प्रीणनो ह्याशुकारी च कर्कशश्च
गुणाः स्मृताः ९ शमयंति विपर्यस्ता।
स्त्रयो निवर्द्धयंति च वीर्याणि चैवमेवे
षां विविधान्येव निर्दिशेत् १० सौम्याग्ने।
य शीतमुष्णमिति वीर्याणि निर्दिशेत् प
वनोष्मः वहारस्य विपरीत गुणाश्रयः १२

वाला स्वभाव विकाशी अन्य धातु सार को एवं शोषक र
मर्थी यां के जोडों के बंधनां को ढिले करणे का स्वभाव वा
ला त्वमिकर शीघ्रकारि शनावी गुण दोष करण वाला
स्वभाव और खोरा ए है गुण कहे है न १० उलटे दीपर्य्य
दोषां को शमन करे है यो शीत वीर्य है सो पित्त को शमन करे है
यो इत्य उष्ण वीर्य है सो वायु कफ दोष को शमन करता है अ
रु अपणी यो नि को बधाने है न जैसे मधुर स्नेष्म को अम्ल
पित्त को कटु वायु को और स्वभ है यां के वीर्य अनेक प्र
कार कहे है न ११ इत्यादी प्रकार के हैं सौम्य आग्नेय निसमें

© Dharmartha Trust J&K. Digitized by eGangotri

वेंहगुण अधिक हैं सो सौम्य है अरु जिस विषे अग्निगुण
बहुत है सो आग्नेय है पीने अरु खाने विषे वीर्य कहे हैं जो
जो पचता होआ आहार है सो रेसा रस होजाय जिसको पाक
कहते हैं सो पाक दोप्रकार का है एक मधुर दूसरा कोडा है
विष मिठी मधुर अरु तीक्ष्ण वीर्य अरु पाक विषे कडुए हैं
सो काहू विषे स्थित होइ रही सो रोग पकरती है जैसे सके
वासको अग्नि दग्ध करती है १३ जो पुरुष द्रव्य को रस पा
क गुण वीर्य ने जानता है सो वैद्य कहे आहे १४ जो द

सपाको हि द्विविधस्स मधुरः कटुकस्त्रयः म
धुरं तीक्ष्णवीर्यं च विपाके कटुकं विष १३
दहेत्कोष्टगतं तेन शुष्कात्तृणमिवानलः
रसतः पाकतश्चैव गुणतो वीर्यतस्तथा १४
यो द्रव्यमेव जानाति विज्ञेयः स चिकित्सकः
नाहरेणाग्निना योगाद्ध्रुवं छतिरसान्तरं १५
आहारः परिणामान्ते विपाक इति संस्मृतः
इति रसविनिश्चयः रसवीर्यविशेषांश्च र
सानां च गुणान्गुणान् निबोध मम सर्वे
षां प्रोच्यमानान्पृथक्पृथक् १ अम्लो रसः
पाचनं दीपनश्च स्निग्धोऽल्पवीर्यः कटुको
विपाके च गतोष्णक पित्तकरः प्रदिष्टो हृ
द्यः शरीराग्निविवर्द्धनश्च १

जठर की अग्नि के संयोग ते खोया हूआ दूसरे रस कों प्रा
प्त होता है पचन के उपरान्त सो विपाक कहा है १५ इति
रसविनिश्चयः । रस के वीर्य के भेद और गुणने और ग
ण सभनो के मेरे करके कहे दे बकोव वौसण १ अम्ल र
स पाचन है और अग्नि को प्रकाश करता है चिदा है वीर्य वि
षे गर्भ है पाक विषे कोडा है और त्वचा के रोग पित्त इनको क
रने वाला कहा है अरु हृदय को हित करे है शरीर की अग्नि
को वधाता है स्पर्श विषे शीतल है बल हरे है लहू को ।

© Dharmartha Trust J&K. Digitized by eGangotri

धा॰ ऊपित्तकौहै होतेहै वायुकानाशकरैहै ३ लवणरस मा
ह्रो॰ सकोवधाताहै औरद्यासकोपचाताहै औरगंधकोपाकक
८३ थिरकोवाहरनिकाशताहै छोडेयांकेस्रोतसकोवधाताहै
वीर्यविषेगर्मैहै पाकविषेसोकटुवहैयाहै ४ आयुषा वी
र्यवलइनकानाशकरताहै औरपित्तहृदयकीअग्निकोकर
ताहै ५ औरविरेचीहै व्रणकोपचाताहै थिदा हरवा लकू
केऊपित्तकरेहै वायुहरहै स्रोषमकोवधाताहै इसतरांका
लवणरसहै ५ मधुररसआयुकैर शीतलहै वीर्य वल

शीतोवृंहिश्चायुष्यवलोनकर्तारक्तप्रकोपील
घुवातहंता ३ सचुणःपाचयतिस्रुतंवसंक्ले
दनःश्लेष्मकरोहयानां उष्णोथवीर्येलवणा
रसोवैस्रुतोविपाकेकटुकःसएव ४ आ
युश्चशुक्रंचवलंवृहमानंपित्तंवऊर्ध्वंज
ठरानलंच ५ स्यादेदनीयाव्रणपावकस्य
स्त्रियोथरक्तोरुधिरप्रकोपी वातापहःश्ले
ष्मविवर्द्धनश्च एवंप्रकारोलवणोरसस्य ५
स्याज्जीवनीयामधुरोरसोवैशीतोथवृंष्य।
वलवर्द्धनश्च प्रल्हादनःप्रीणयतीद्रिया।
णिरक्तोपशांतिंकुरुतेहयानां ६ वातोप
हःपित्तविनाशनश्च शुक्रस्यवृद्धिंकुरुतेक
फंच चक्षुःप्रसादंतनरोपणंच कुर्योद्व
हानांमधुरोरसोसो ७ तिक्तोरसोमारुतको
पनस्तुशीतश्चरुक्षस्च कफनिहंति ।

कोदृढकरताहै हृदयकोहर्षकरहै इंद्रियांकोतृप्तकरहै
औरघोडियांकेरुधिरकीशांतीकरताहै ६ मधुररसघो
डेकेवातपित्तकानाशकरताहै औरवीर्यकफकोवृद्धि
करताहै नेत्रांकोनिर्मलकरताहै घावकोअंगूरवडाद
ताहै ७ तिक्तरसवायुकोऊपित्तकरहै ठंडरुखाहै
औरकफपित्तकोनाशकरहै प्रमेहमत्ररोगऔररक्तके।

विक्कद्दोषकोहितकरहै कोष्ठआमशयकोंशुद्धकरता
है ८ अरु ऊष्ण वीर्य मेदक्रिमिविष इनकोनाशकरताहै
व्रणद्यागैरउगयकोशुद्धकरहै लेखन मल पानकोसु
कायकरवाहर निकासदेताहै अग्निकोवधाताहै ९ कषाय
रसदेहकोस्थिरकरहै वहुतरुखा ठंडा शोषणकर शुद्धक
रहै अस्थिसंधिमज्जीकोयोडदेताहै वायुकोकुपितकरता
है पित्तकफकोनाशकरहै १० कटुरसयोहैसोतीक्ष्णउष्ण
वीर्यहैं रसविषेंकटुहै रुक्षविशोषीहवमलमूत्रश्लेष्मको

हितः प्रमेहे रुधिरे प्रदुष्टे पित्तापहः कोष्ठवि
शोधनश्च ८ ऊष्णा निहन्मात् व्रणशोधनीयः
स्याल्लेखनी योग्निविवर्द्धनश्च शुक्रं च मेदश्च
कृमिं विषं च हन्यात्तथा लम्य विशोधनश्च ९
स्थिरः कषायस्त्वयि कल्क रुक्षः शीतो विशो
षी विषदस्तथैव संधानहृन्मारुतकोपनश्च
श्लेष्मापहः पित्तविनाशनश्च १० तीक्ष्णोष्ण
वीर्यः कटुको रसस्तु रुक्षो विशोषी वलना
शनश्च मेदः कफश्चैव कृमिं निहन्यात् स्यादृ
क्पित्तानिलकोपनश्च ११ इति रसवीर्यवि
धिः आम्रमामलकं श्रेष्ठं कषायं मधुरान्वयं
शीतवीर्यं च रुक्षं च विपाके मधुरं स्मृतं १
रुक्षत्वाद्विशदत्वाच्च श्लेष्माणं सन्नियच्छति
शीतत्वान्मधुरत्वाच्च पित्तं संशमयत्यपि २
अथ अम्ल विशेषेण मारुतं कोष्ठसंश्रितम्

सुकाटेणा ओर वल मेद कफ कृमि इनकोनाशकरहै रक्त
पित्तवायुकोवधाताहै इतिरसवीर्यविधिः आम्रोंविषें
आमलेश्रेष्ठकरहैन कषाय मधुर वीर्यविषें शीतलहैं
रुक्ष पाकविषे मिठे करहैहैन १ रुक्षे कसैलेहोणेकर्कै
कफको रोकताहै ओर अम्लस्वभावते, ठंडे अरु मधुर
रसनैंपित्तको शामकरताहै २ ओर अम्लस्वभावने को
ष्ठगतवायुकोहरकरताहै ग्रहणीकेविषें अग्निको
प्रकाशकरणेतें थोडेयाको अमित्रकरहै ३ ।

© Dharmartha Trust J&K. Digitized by eGangotri

धा॰
हो॰
८४

84

नारदाणाअम्लहै पाकविषैमधुरहै वीर्यविषैगर्महै हो
ला थिंदा थोडेरसवालाहै अरुअम्लहोणेकरके विदाह
करकाअम्लहोकर नहिंपचता ४ तिसकारणते संपूर्ण
रसोंविषैरुषोंविषै औरनानाप्रकारकेस्वदोंमें भोजनवि
षैवानश्लेषकेविहंतहोदेयाथोडेयाकोदेवे ५ दधाम्ल
कांजी थिंदागर्महै अरुपाकविषैकटुककहाहै छेदहै
वायुकोशमकरहै श्लेष्मपित्तकोवधाताहै ६ सोवक्रु
तगर्महोनेकरकेसेवाते रक्तकोविगाडके पित्तसाथ

ग्रहणीदीपकत्वाच्चप्रसादयतिवाजिनं ३
अम्लंविपाकेमधुरमुस्णवीर्यंचदाडिमं ल
घुस्निग्धंतत्तुरसेनवाम्लत्वंविदह्यते ४ त
स्मादस्मैप्रयुञ्जीतदेशेविविधेश्रव वात
श्लेष्मणिवाहानांकुपितेसंप्रयुज्यते ५ दध्या
म्लंस्निग्धमुस्णंचविपाकेकटुकंस्मृतं प्रक्लेदि
वातशमनंश्लेष्मपित्तविवर्द्धनं ६ रक्तमस्तु
स्णवीर्यत्वात्संदूषयतिसेवितं प्रदुष्टंसहा
पित्तेनशिराःसमनुगच्छति ७ त्वग्दोषप्र
भृतीवेवत्तरोगांश्चपित्तजान् श्रोस्याकोपय
तेह्यातानातेनणपादग्निंविवर्द्धयेत् ८ तस्माद
क्तंनरयतिहीणानामपिवाजिनां लघूस्णंपि
त्तकृद्भेदिमत्स्यवातकफापहं ९ मूलानार
प्रशमनंकफघ्नंदीपनंस्मृतं आम्लंकाञ्जिक
मत्यस्त्रभेदनंपित्तवर्द्धनं १०

मिलकेनाडियांविषेंचलजाताहै सोत्वचाकेरोग सोजा
नेत्ररोग औरपित्तकरहोणेवालेरोग बहुतगर्महोनेते
करताहै घोडेयांको औरनीलास्वभावते अग्निकोवधाता
है ८ तिसकारणते थकीणघोडेहैंत तिन्हाकेभोजननुकों
सेवादेताहै मत्स्यघरविनामकहायाहै सोहोला गर्म पि
त्तकरभेदिमलहरहै औरवातकफकोनाशकरहै ९ मूल
आनरवेदहोनासभहारोंका कपरनांकानाशकरकेरि
आहै अग्निकोप्रकाशकरैहै कांजी अम्लहै औरवहुतगर्म
विरेचमलहर अरुपित्तकेवधानेवालेहै १०

© Dharmartha Trust J&K. Digitized by eGangotri

सुरा मदिरा वीर्यविषे गर्म कहते है पाकमें कडुक कहा है और
मदिरा भेद अम्ला ते सेही उष्णवीर्य होएते सुरा मधुर कहा
है पाक विषे को आतिक रुखपित्तरोगको बधानेवाला है
तीक्ष्ण होने कर के अन्न को पचादेती है और अग्निको प्र
काशकर कहि है ११ यो सुरा हणोते निर्मल निकासी होइ
तिसको प्रसन्ना वारुणि कहते है सो वातमूलवालेको व
हुत श्रेष्ट परे कहि है १३ और सुराका कलल दुष्ट होला
अग्नि प्रकाशकारक कहा है और प्रसन्ना को शास्त्र जाननेवा

उष्णवीर्यं वह्निकृत्तद्विपाके कटुकं स्मृतं अम्ला
सैवोष्णवीर्याच्च सुरा समधुरा स्मृता ११ तीक्ष्णा
विपाके कटुका पित्तदोषविवर्द्धनी तीक्ष्णाश्च
जरयत्यन्नं दीपनीया च सा मता १२ वातबलि
भ्यो हितं तस्माद्देषा प्रशस्यते प्रसन्नभावसं
प्राप्ता सुराभावाद्विनिःसृता १३ लघ्वी च दी
पनीया च सुराकललिका स्मृता अतः तीक्ष्णा
नरैः प्रोक्ता प्रसन्ना शास्त्रकोविदैः १४ उष्णवी
र्यात्तु रसा दीपनी परमा च सा वातश्लेष्महरा
सैव पित्तस्य च विवर्द्धनी शुभोजितानाम।
थानामन्नपाने प्रशस्यते १५ इति सुराकल्पम्
सैंधवं लवणं श्रेष्ठं कषायमधुरं स्मृतं सर्वे।
भ्यो लवणेभ्यस्तु विघातो ततरं नतनं १
दीपनं रोचनं चैव चक्षुष्यं ते सर्वथा तथा ।

ले बहुत तीक्ष्ण करते हैं १४ सो वीर्य में गर्म सूक्ष्म रस
सूक्ष्म द्वार विषे प्रवेश करे है अग्निको प्रकाश करणवाली
है और पित्तको बधावे है वातश्लेष्मको हरती है १५ चोडे
याने खाय रुआयो अन्न जल तिसके पचाने वास्ते पान करा
णा श्रेष्ट है १६ इति सुराकल्पम् सभ नोंलूणों विषे सैंधव
लूण श्रेष्ठ कहा है सो कषाय मधुर बहुत ठंडा अग्नि प्र
काशकर और रुचिकर हृदयको गुणकर और नाडी
द्वारको शुद्ध करे है सूक्ष्म सूक्ष्म छिद्रों विषे प्रवेश

© Dharmartha Trust J&K. Digitized by eGangotri

करणेवाला है सभयानविषेयोगीदा है १ लूनसभप्रका
रके अम्लपाक होकर नहि पचदे तैसेही सैंधालूण अवि
दाहि स्वाकर मधुर होकर पचणेवाला कहा है और नेत्रों
को हितहै ३ सैंधवलूण अविदाहि होनेते और ठंडे होणे
करके सभजीवोंके श्लेष्मपित्तको और घावोंके व्रणे
के विषे श्रेष्ठ कहा है ४ मिठे द्रव्योंमें घेउ बहुतगुणकर
है वायुपित्तहर्ता है स्निग्ध है वीर्य शीतल है पाकविषे मधु
र है और बलवर्ण अग्निका आप्यायन करता है और विधि सभा।

तथान्तरसं चैव युञ्ज्यात सर्वेषु पानेषु २ लव
णार्थं तथा नागरं विदाहि विधीयते वल्हश्च
सैंधवं न हृद्यं विदाहि विधीयते ३ श्लेष्मपि
त्तानिभूतानां तथा स्थानानां व्रणेषु च प्रशस्तम्
विदाहिनाश्च शीतलं ताम्रसैंधवं ४ मधुराणि
हृतं श्रेष्ठं वातपित्तनिवर्हणं स्निग्धं वषी
तवीर्यं च विपाके मधुरं च तत्र ५ बल्यं च वर्ण्य
मायुष्यं हृद्यं चैव विदाहि च सर्पिस्तस्मान्नृ।
यां तस्माद्रोगानाभिभवन्तिते ६ तत्तकल्प
विशेषेण स्नेहपानेन मयमपि सर्वरोग।
हरं तस्मात् घृतमाहुर्मनीषिणः ७ अनु
लोमयेदपि तेन तत्संस्कृतं दीयते यदा अधो
हरति वै दोषान् यथाशास्त्रप्रयोजना ८
अथवा अन्यानि रोगेषु शिरोरोगेषु वापुनः।

ण विनावीया घृतभी विदाहि होके मरणकरता है और अस्न्।
होकर पचता है ५ और घृतके करनेसे अपथ्योउ रोगोंतें नहि।
होवते ६ सो रकल्पविशेषतें औषधियोंकरके सिरकि
या हुआ स्नेहपानको भी समकरता है तिसकारनतें मुनीयों
ने घेउ सभरोगोंका हरणेवाला कहिआ है ७ पर घृतय
थार्थ योगोंकर सिद्ध किया हुवा यैसे शास्त्रमें कहा है तैसे यो
ड्यांको दीयादा अधोभाग दरके रोगोंको हरता है ८ अ
न्निरोगों विषे सिरके रोगों विषे सभकी रोगविषे इनां विषे

© Dharmartha Trust J&K. Digitized by eGangotri

घेउ खाणेवाले को गुणकारक हुन्ते हैं ९ और उन्माद गंडस्था
न विषे कृशनर्मी यां में हुत श्रेष्ठ पथ्य कह्या है और स्त्रिनावीश
स्त्रकरके कटे होए विषे अग्निदग्ध विषे और विषकर दग्ध
विषे त्वचाके रोगों विषे और वहुत गये दोषके हटाणे विषे
और सूतिका रोगवालीयां को अपस्मार मिर्गी रोगवालेयां
को हुत पथ्य है ॥ येडे निरोग्य हैन तिनां को भोजन विषे
विशेषकरके श्रेष्ठ गुणकार है जुवाने बल वीर्यवालेयां
के वीर्य के वधानेवाला कह्या है और बालकों के देह को

शुष्ककासे श्रमे शान्ते तस्मादुन्मवतां हितं ९
उन्मादे गंडपिटके हितं पथ्यतमं स्मृतं शस्त्र
छिन्ने विदग्धे च विषदग्धे तथैव च १० त्वग्दो
षिणां च भूयिष्ठदोषप्रच्यवने हितं सूतिका
नां हितं पथ्यं तथापस्मारिणामपि ॥ प्राय
शो भोजने नित्यमरोगाणां प्रशस्यते वृषा
णां शुक्रजननं शिशूनां देहवर्द्धनम् ११ प्री
णनार्थं प्रजानानां वल्पमस्य विशोधनं प
कागेषु पिवाहानां भोजनार्थं प्रदापयेत् १२
रसायनार्थं दातव्यं तनुः स्नेहो न महितं खौ
द्रेनीलोभ्रकायहितं देयस्त्वमात्रया १४ शा
नैर्माशमिहर्द्धिःस्यात्रणेस्थवकेवलं त्रिप
वस्त्रमात्रेणाद्दशमात्रेणवापुनः १५ देयम
पि रसेदेव प्रशस्तमेयवानिनम् ।

वधाता है १२ हुत योस्त्रदयां होश्यां चोशीयां है तिनां को
निरोगपनावास्ते देना योग्य है और वलकरा है इसको
सुद्धकरता है पक अगके रोगवाले घोड़ेयां को खाणेवास्ते
देवे ११ सभ प्रकार के स्नेहों में हुत वहुत हुव्या है सो रसा
यणवास्ते वढेया अरु व्याधि के नाश करणेवास्ते देणेयो
ग्य है सो हुत प्रातकाल में भोजन के पचे होए तें प्रमाण
का देवे १४ अरु होलि होलि मात्रा वधावे [illegible]
सदाणा देवे घेउ त्रै दिन पांच सत वा दश वा त्रिनि
रन्तर देवे अरु मैथ वल्गुण करके गुण करै है ॥

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा॰
हो॰
८९

८६

अरुजलकाउकरकेसलोणसंशीतलगर्मपीणेनूंदेवे १९
आउकप्रमाण अरुसेरतक वधाताजावे अवहोउकोंदस
नाआवे यदगुदाकेरस्तेसेहकों इतकों लिखिविना नि
कासे तदहोउकों १७ इस्तिनरोस्निग्धहोयेहोउकों यो
गोंकरके रुक्षविधिकरणेयोग्य है ३ पदिनयवागू अरु
कुलत्थ सागमदिरा लूणसाथदेवे १८ अरुभोजनछांई
केसाथ पहेरुक्षविधिकहिहे इतिमधुरविधिः तिक्त
द्रव्योंविषे कुलाकपटोल मुख्य है मधुररसभारी अरुवद्ध

स्नेहेनप्रतिपानंवसलोणेनांभसाभवेत् १९
आटकान्तपराद्धिःकार्यास्याद्विरेकिनः
पायुनामुञ्चतःस्नेहंनिःशरीषस्यवाजिनः १ १
सम्यक्स्निग्धस्यकर्तव्यंयोगतस्तन्निरूक्षणं
त्र्यहंयवागूःकुलत्थांत्रसुरावलवणाविना १८
भोजनेतक्रसंयुक्तंमेषस्याद्रूक्षकोविधिः
इतिमधुरविधिः तिक्तानांकुलकंश्रेष्ठंमधुरा
त्रेरसेगुरुः नातिरूक्षंचशीतंचमधुरंचविपा
कतः १ तस्मात्श्लेष्मणिपित्तेचमारुतेचेवशु
स्यते तत्सूक्ष्मतमंचेवतिक्तानामुत्तमंस्मृतं २
निंबस्तिक्तरसःश्लेष्मपित्तघ्नोग्रहरोलघुः कृ
मिकुष्ठविषघ्नश्चभेदनोदीपनस्तथा ३ वि
पाकेमधुरस्त्वापिवातलोव्रणशोधनः त्वग्
दोषशमनःश्रेष्ठोहृद्रोगघ्नःपरस्मृतः ४
शामयेदनापित्तंचतिक्तत्वाद्दाहशोषकः

तरुक्ष है पाकमधुरविषेंसीतलहै १ तिसकारणतें कफ
पित्तवातविषें योउत्तमहै सोसूक्ष्मतम वढ्ढनवीर्यकेवधा
नेवालीहै अरुतिक्तोंमें उत्तमहै २ निंब तिक्तरस हलका भे
दी अग्नि प्रकाशकर होताहै और पित्त श्लेष्म कृमि को
ढ विष रोगहरता है ३ पाकविषेंमधुर है वायुकारके
व्रणत्रासको शुद्धकरता है और त्वचाकेरोग हृदयरोग
इनकेनाशकरकहाहै ४ सो सो तिक्तरसहोणेतें रक्त
पित्तकोंशमकरेहे गलोतिक्तरसवालेयांविषेश्रेष्ठक

© Dharmartha Trust J&K. Digitized by eGangotri

हीहै सोपाकविषैंमधुरहै स्निग्ध अग्निप्रकाशकर बल
वीर्यकरहै गलकोहितहै अरुखंगदमको हरता है अरु
सभयातुयोंरसादिविषैंहोउ ६ कषाय मधुर स्वाउ है।
ला अविदाहि शीतल है पाकविषैंमधुरहै वीर्यविषैंरूख
है ७ मेध्यबुधिकर नेत्रकोंहितकर आयुकर योगंकेम
लनवालेश्लेष्मकाहाहै अरुपित्तके विशोधनहिकरताहै
अरुश्लेष्मकोकटैंवीनहिविकृतकरताहै ८ लघुकषाय
नैं सोवायुकों कुपितकरहै अरुविधिकरकेदीपक्रूप हृद्य

वल्योहृष्यस्तुकंठ्यश्चकासश्वासहरस्तथा ५
स्निग्धाचदीपनीयाचविपाकेमधुरातथा श्रे
ष्ठागुरूचीतिकानां सर्वधातुप्रवृद्धये ६ क
षायमधुरंस्वादुलघुचैवाविदाहि च शीतं
विपाकेमधुरंमधुरूक्षंचवीर्यतः ७ मेध्य
वहृष्यमायुष्यं सर्व्यानार्थे प्रशस्यते नविकृ
ष्यतिनपित्तंश्लेष्माणमेवकरोतिच ८ लघुवा
हिदशनाच्चतत्कोपयतेनिलं उपायेनश
श्चेकेनहृष्यश्चविनियुज्यते ९ अतीसारज्व
रेहिकासध्यानितताविच तस्मान्मधुक
षायेभ्यः सर्वेभ्योप्यधिकंगुणेः १० रसेकषा
यमधुरालघ्वीचैवहरीतकी लेखनीकोष
दोषघ्नीदीपनीयायदेदहिता ११ विभीतके
कषायंचरूक्षवीर्यंचशीतलं कफपित्तह
रंचैवलेखनंव्रणशोधनं १२

कर्मविषैंवीर्यवृद्धिविषैंदेणोंसे गुणकरहै ९ अरुअती
सार ज्वर हिडकी इनकोहरकरते हैं अरु तनवायको रु
धिरकोधारतेहैं तिसकारणतें मधुरकषायसभद्रमोंवि
षे गुणोंनेअधिकगुणवाला है १० हरीड रसमेंकषाय
अरुपाकविषैंमधुरहै औरधातुमलकोसकाकर बाहर
निकासतीहै औरदेहधारीयोंकोअग्निकोजगादेतीहै अरु
कोष्ठकेदोषरोगनाशकरतीहै ११ बहेडेरूक्षकषाय वी
र्यविषैंठंडेहैं मलधातुकोबाहरकरतेहैं औरवायकोपु
दकरतेहैं औरकफपित्तकोहरतेहैं १२

© Dharmartha Trust J&K. Digitized by eGangotri

त्रिफला हरीड़ बहेड़े आमले तीनोमिलेहे त्रिफलाकहाहै
तिसकारणते वलीवलीहे तोतें किठाकरदेणेकागुणविशे
षकहाहै १२ त्रिफला हरीड़ बहेड़े आमले तल्यहेमाकरके
बनायाहूआ सोअग्निकेप्रकाशकरहै मलदोषकोंसकाके
कटकरवाहरनिकसताहै वीर्यमेंशीतलरूक्षहै पाकविषे
मधुररसहै १४ सोकषायरूक्षहोनेकरकेश्लेष्मकोशोकता
है औरकोष्ठकीअग्निकाप्रकाशकरहै रुधिरकोशुद्धकर
ताहै पित्तकोहरताहै दुष्टविकृतदोषोंकोपचाताहै अ

पतान्यामलकेसार्द्धंफलानित्रिफलामत तस्मा
वघाष्ट्यमेलविशेषंगुणतःस्मृता १३ त्रिफला
दीपनीयाचलेखनीयाचकीर्तिता शीतवीर्या
चरूक्षाचविपाकेमधुराचसा १४ श्लेष्माणंवि
पादनाद्रूक्षत्वाच्चनियच्छति कोष्ठेचदीपय
त्यग्निंशोणितंप्रसादयेत् १५ तथापित्तहरीचै
षादुष्टानांचविपाचनी ह्यानांत्रिफलाख्या
र्थ्यंसात्वांतंप्रकोपयेत् १६ कषाय । क
टुकामधुरास्वादेस्निग्धानीलावपिप्पली
विपाकेमधुराशीतापिच्छिलाचविशेषतः १
श्लेष्मस्थानमतिक्रान्तामाधुर्यमुपतिष्ठते स्नि
ग्धत्वाच्छीतभावाच्चपिच्छिलत्वाद्विशेषतः २
ततोवातंचपित्तंचश्लेष्माणंचनियच्छति स
र्वेभ्यःकटुकेभ्यस्तुतस्मादेषप्रशस्यते ३ वृ
ष्याचवल्यानत्यायुष्यारुधिरसविरोधिनी ।

कषायोगगनवायुकोंरुपित्तकरहै विशेषकरके इतिकषा
यः । मघांकोजोयो स्वादविषे मधुर चिर्ही नीलापाकवि
षेमधुरहै ठंडा पिच्छललेशदारबहुतहै १ यहश्लेष्म
स्थानकोलंघकर हमरेआशयविषे मधुरभावकोप्रा
मरोतीहै औरस्निग्धशीतलपिच्छलहोणेते विशेष क
रके २ तिसते वात पित्त कफ इनकोंहरकरहै तिस
कारणते सभकटुकोंते यहश्रेष्ठहै ३ और वीर्य
वल आयुकरहै अरूलहूकोविगाड़तीहै मघांसभ

© Dharmartha Trust J&K. Digitized by eGangotri

दोषोंकोनाशकरतीयांहैं औरउष्णताकोपचातीहै ४ सं
उकोशीतवीर्यमेंगामुअरुविशेषतेरूक्षहै पाकविषेकोउ
रसतीव्रहै अग्निकोप्रकाशकर अरुसोजावायश्लेष्म ह
रहै अरुवद्धतमेवीर्यहोनेते सेवाकरनेकरके पित्तको
कोपितकरताहै ६ सोविधिविनादीयाहुवा स्वभावविषेस्थि
तधातुरसादितिनोंमें सारेदेहविषे प्रवेशकरहै तिसतेति
सकोविषभेषजकहतेहैं ७ मरिच रूक्ष गर्भहै अरुवृष्टि
करनहि औरमंदाग्नितदमगंधिवालेहैं अरुपाकमेरक्तहो

पिप्पली सर्वदोषघ्नी उष्णानां च यावनी ४
दीपनीयं च शोथघ्नं वातश्लेष्महरं च तत् पित्त
मम्लरसं वीर्यं त्वाम्लं हर्षयति सेवितं ५ कटु
कं चोष्णवीर्यं च रूक्षं चैव विशेषतः विपाके
कटुकं तीक्ष्णमग्नेर्वैरं निदर्शितं ६ उपायेन
विनायुक्तं प्रहन्ति स्थिरधातुश्च विषकपारी
रेचरति तन्नाहि विषभेषजम् ७ मरिचं रूक्षमु
ष्णं च वातपित्तप्रकोपनं अहृद्यं श्लेष्मशमनं
स्वल्पाउवमगंधि च ८ परिणामे च बहुस्तवाउ
स्वं चाप्यजायते एतानि तत्समायोगात्त्रिक
टुः परिवक्ष्यते ९ इति द्रव्यगुणदोषनिर्णयः ।
मधुरः शीतवीर्याश्च विपाके कटुकाश्च वाः
स्थिरा कषायाश्च विसदाः जेरा वातकोपनाः १
स्थिरीकुर्वन्ति मांसानि शोणितं च विशेषतः
अल्पमूत्रा स्थिरत्वाच्च परीषं च हुलाम्बते २

एतेगर्भभावकोंहोजातेहै अरुकफकोंशमकरहै इनो
नयनौकेयोगकरके मघा मर्च संठ समभागकरके त्रिकु
टाकहतेहैं ९ इतिद्रव्यगुणदोषनिर्णयः जो मधुर शी
तलवीर्यते विपाकविषेकटुहै अरुदेहकोस्थिरकरहै
रूक्षकषाय अरुउष्णकरपचतेहै वायुकोंकोपितकरहै
अरुविशेषतेमासअरुरुधिरकोंस्थिरकरहै औरपछावथोरा
करताहै स्थिरस्वभावते अरु मलशुद्धि बहुतघनकरतेहैं

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
ह्रौ॰
८८

88

सो कफकों छिलके निकासते हैं और बलकों बधाते हैं सो
रोगों के विषै गुणकारक हैं और बलकारक हैं ३ सो छोडे
याको दाणेवाले अरु भोजन त्यांसों विषै श्रेष्ठ कहे हैं और स्थि
र रहते होने ते कफकों शमकरते हैं ४ मोठ दाणे विषै सा
ठी लीये बहुत गुणकार है मिठ स्वभावतें बलकों बधाते हैं
अरु कछुक करुवे कषायरस तें रक्तपित्त कफकों नाशकरते हैं
और मास प्राणकों बधाते हैं और कफपित्तवायुकों नाशकरे हैं ५
छोले सदा खाणे विषै मधुर और वीर्य मे शीतल कोमल स्वादु

श्लेष्माणं बलिनं चैते बलं संवर्द्धयन्ति च ३ वि
नाल्लेन रोगाणां बलाढ्ये ते निदर्शिताः १ हु
यानां खादने शस्ता भोजने शुच कल्पिता स्थिर
त्वाच्चैव रोसा च श्लेष्माणं शमयन्ति च ४ मकु
ष्टाः खादने शस्ता मधुरा बलवर्द्धनाः किंचि
दुष्णाः कषायाश्च रक्तपित्तकफापहाः ५ वृंह
णाः प्राणजननाः कफपित्तानिलापहाः मधुराश्च
गुरुश्चैव खादने चणकः सदा ६ वीर्यः शीतो
मृदुः स्वादु त्रिदोषशमनो लघुः निर्दिष्टः खा
दने ह्येवं चणकः शुक्रवर्द्धनः ७ माषा बहुम
लाह्युष्णा महाभिष्यन्दिनो मताः बल्याश्चैव स
वीर्याश्च गुरवश्च निदर्शिताः ८ कफपित्तकर
स्वादुः कषायस्तु गुरुस्थिरः तेयश्चोसः कु
लत्थश्च पित्तकृद्वातनाशनः ९ माषान्मु
द्राश्च गोरसान्कुलत्थानपि शास्त्रवित् ।

मधुर है त्रिदोषको शमकर है छोले अरु भोजन विषै छोले
वीर्य के बधाने वाले कहे हैं ७ तदा बहुत मलकराते है वीर्य
बधाते है अरु बहुत अभिष्यंदि होते है नारी यां रस वा हीयां।
का हारके रोकने वाले कहे हैं और बलकर है वीर्य विषै गा।
भे अरु भारी दिखाए हैं ८ तिल मधुर कषाय भारे हैं और क
फपित्तकरे हैं कुलत्थ गर्म जाणो पित्तकरे है और वायुकानाश
करे है ९ शास्त्रके जानणेवाला माषा मूंगी कणक कुलत्थ

© Dharmartha Trust J&K. Digitized by eGangotri

रनोंकोखानेवास्ते सिद्धकरके महेलावनाकरकेदेवे कचेक
देवीनादेवे १ शाली धान अरुयव कंगुणी व्रीही अन्न रसत
रोके गैरत्रणधान्यपहेकछेहिखाणेवास्तेदेणे ॥ इतिखादन
विधिः विहि मिठा चिकना रूक्ष स्वभावहोणेते त्रिदोष वायुपित
कफकेनाशकरताहै अग्निमथ हुंडरण स्नेह स्निग्ध गर्मस्वभाव।
ते वातकफको नाशकरताहै १ शोनाक टटर कसेला तिक्त मधु
रस्वभावते रक्तपित्तके नाशकरहै कश्मी अरुपाटला यहदोष उ
रकेवरावर गुणवालीयांकहियांहैन २ शालपर्णी पृश्नपर्णी

खादनेशाप्ययेत्सिद्धान्नासिद्धानपिदापयेत् १
शालीव्रीहीन्यवानंगून्नन्यच्चापितथाविधं
तृणधान्यानिधान्यानिदद्यादामानिखादने ॥
खादनविधिः मधुरस्निग्धरूक्षत्वात्स्वल्पतोवि
ल्वत्रिदोषहृत् अग्निमंथोनिलकफौहंतिस्ने
होष्णगौरवात् १ कषायतिक्तमाधुर्यात्श्योण
नाकोरक्तपित्तहा काश्मीर्यपाटलेचैवविज्ञे
ताशोनाकवद्गुणाः २ शालिपर्णीतथालक्ष्मी
मधुराबृंहणीचतौ रक्तपित्तानिलकफान्हं
तीसज्वरशोषघ्नी ३ मधुरास्निग्धतिक्ताचबृ
हत्पर्णीतथानिले वृष्याकफहरेकल्पेबृंहणे
कोष्ठवर्धनः ४ श्लेष्मपित्तानिलहरेहृद्ये
मधुरेरसे पंचकेवातपित्तघ्नौगोक्षुरस्त्व।
त्रिदोषजित् ५ दशमूलानिवात्यर्थंश्लेष्माणि
कटुकानिच।
होली मिठी अग्निप्र कापाकरहै तेसेही।
कोष्ठकोपुष्टकरहै औररक्तपित्तवायुकफ इनोंकोनाशक
रतीहै ३ पृष्ठपर्णी हंथ्या मधुर चिकनी तिक्त रसहै औरवायु
कफके हरकरणविषे और वीर्य मास कोपुष्ट इनोंके वधाने
केविषे औरकल्पसेवाकरणविषे बहुतश्रेष्ठगुणकरहै ४
शोथेकरस्त्रारी कंडस्त्रार रसविषेमधुरहै औरकफपित्त
वायु इनकोहरतीयांहैन ५ धरण वातपित्तको ना
शकरताहै अरुमज्जाउर त्रिदोषहरहै यहदशमूल ग
र्मवरूतहैन कौड़ेहैन सोसेवनकीयाहुवा निश्चयकर
श्लेष्मकोनाशकरताहै ६

प्रा.
हो.
८९
89

रोगमे होनेतें वायुकोंरोककेदेतेहैं और थोडे याके श्लेष्मको
अरु गुदाविषे प्राप्तहोय पित्तकोंशामकरा है ७ वायुकरके प्रे
रतकीया श्लेष्मशिरविषे प्राप्तहोयादा तिसविषे वीणासूके
जाननेवाले दशमूलकोंदेतेहैन ८ विल्व अग्निमंथ टउ
एणा श्योनाक टाटर काश्मीरी कसीर पाटल सूरकणी दथ्यर
कडेआरा कडेआरी वर्द्धमानक परण इनाकीयाजडा दशमूल
कह्याहै ९ अरु पाटल विल्व कसीर अग्निमंथ टाटर पहेम
हत पंचमूलकह्याहै पंजीवस्तविषे सोवायुकफहरेहै अरु

भृशंश्लेष्मांश्च विद्ध्याणं सेव्यमानानि तानितु ६ ३
स्तब्धान्याहृतनालीसं नियच्छेत्तिवाजिना श्लेष्मा
णावगुदप्राप्तं पित्तं संशामयत्तिव ७ शिरोगत
श्चयः श्लेष्मावातेन सहमूर्छितः तस्मिन्नपि
प्रयुंजते दशमूलानि णास्त्रवित् ८ विल्वोग्नि
मंथः श्योनाकः काश्मीरी तथ्य पाटला शालिप
र्णीपृष्टपर्णी बृहतीकंटकारिका ९ वर्द्धमान
कमूलानि दशमूलं प्रकीर्तितं पाटलाविल्वका
श्मर्यः साग्निमंथाः सटुटुकाः १० पंचमूलंम
हत्प्रोक्तं मेतेस्तपंचभिः वातश्लेष्मश
नकिंचित्पित्तहरंवतत ११ शालिपर्णीपृष्ट
पर्णीबृहतीकंटकारिका परंडमूलमेकंत्रप
मूलंलघुसृतं १२ वातपित्तप्रशमनं किंचित्क
फविनाशनं नमाहयागविकेरतनतो निदा
घेवर्षास्वेवमसितानलदाग्धदेहः स्निका
लवैयवमस्वादनमविपाभिजीवंतिवैव
यदिनेपरमायुषोपि १३ कछुकपित्तकोवीहर

ताहै ११ सूरकनी दथ्यर कडेआरावडा कडेआरी परण इ
नाकीयाजडा लघुपंचमूलकह्याहै १२ सोवायुपित्तकोश
मनकरताहै अरु कछुक कफकोवीनाशकरताहै जो
उग्रीष्मऋतमें सूर्यकीया किरणकरके सतप्तहोतेहैं
अरुवर्षाऋतुविषे वदलोकियाविंदुवर्षाकरके सिं
चितहोयसांतहोतेहैं अरुनिकारमवालेद्याम अरुदाणा
इत्यादिक विधियोंकरकेवी यद्उनकी आयुर्णाहै सो
जीवतेहैन १३

© Dharmartha Trust J&K. Digitized by eGangotri

इतिदशमूलाधिकारंनामस्थानं अठप्रकारजलकहिआहै
खूहेका सरका सरका नलाका बाउड़का उरणीका खूटेका वा
उलीका नदीका एहेअठप्रकारकाप्रसिद्धहै १ खूहकापाणी
खाराअरुअग्निप्रकासकर अरुवातलबहुतनहि ओरपितक
रहै अरुसरकाजल स्वादअरुहोलाहै नलाकापाणीवात
लअरुभाराहै बाउडाजलपित्तस्वभाववालाहै उरणीकाज
लसभदोषहरहै अरुकोरजूपाणीस्वादुहै पित्तकोनाश
करताहै बाउलीकाजल स्वादुअरुहोलाहै २ नदीकाज।

विसंभरः कालभवेस्तुणाद्यैः स्थानेनथाप्रुलिर
तिप्रभूता प्रमाणस्वेदप्रादिनिवारणार्थंकक
नकैर्यान्कुणमस्यदेहे १४ दशमूलाधिकारं
नामस्थानम् कौपसारसनाडागंवाप्रेयप्रस्र
णोद्भिदं वापीजानादेयमेतत्प्रयानेपुनर
पुधा १ सत्रारंपित्तकृकौपंदीपननातिवा
तलं सारसंस्वादुलघुवनडागंगुरुवातलं १
वौऽ्यंवपित्तलंतेययप्रस्रवणंदोषहारकं औ
द्भिदंस्वादुपित्तघ्नंस्वादुवापिजलंलघु १ नादे
यंवानलकृतकटुकंवतथादिशेतन् कर्मदः
शीतलोरुक्षोविषघ्नोवेदनापकः ५ शोथदा
हप्रशमनोव्रणरोपणः सुंठीमरिच
पिप्पलोधान्यकाजाजिदाडिम ५ पिप्पली
मूलसंयुक्तोवेशाङ्गारइतिस्मृतः ८ रसव्याक
रणाध्यायः इतिदुर्लभसूनगणकृतेसिद्धयो
गसंग्रहे रसव्याकरणंनामद्वितीयस्थानम्

लवातल रुक्षा कोश कहियाहै कर्मदः शीतलरुक्षहै
अरुविषकोनाशकरहै ओरद्याससकोपुरुहकरअरुशरवडादेता
है संठमरिच मघां धनीयां जीरअनारदाणा ५ पिप्पला
मूल इनोकरकेषुक्तवेशाकर एहेकहिआहै ८ इतिरस
व्याकरणध्याय: इतिदुर्लभसूनगणकृतेसिद्धयोगसं
ग्रहेरसव्याकरणंनामद्वितीयंस्थानम् ॥

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰
टी॰
१०

यहयो स्नेह घृततैलादि विधि करके पीता होया सम्यक्पाकु
को प्राप्त होकर सो धोइके सारे देह नैं वायु करके नाडी द्वारमें
प्रवेश कर प्रसर जाता है १ सो सभ रोगां को जीत करके सा
रके कोष्ठ को और इन्द्रियां को शुद्ध करके फेर रसादि धातूआं
को क्रम पूर्वक करके वधाता है २ सो फेर तेज अरु बल के
र प्राण बल अरु वेग धातु सार करा है अरु छाय को और देह
को सफा करता है सो स्नेह नसवार मालस भोजन वस्ति
पछकारि इनां विषे बुद्धिमान् स्नेह कर्मे जानणे वाले दीया
हूआ तिनां का रोग करके नाश न है अरु मार्ग के खेद।

स्नेहोऽयं विधिपीतः पाकं सम्यगागतस्य शोध
स्य भावयति खलु शरीरं शिराभिरनिलैर्वि
तः कृत्स्नं १ रोगान्निर्जित्य सर्वान्विशोध्य को
ष्ठं तथेन्द्रियाण्येव संवर्द्धयति रसादीन्धा
तून्स्वैर्वानुपूर्व्येण २ तेजस्तेजो बलं च वर्णा
जो व्रणप्रसादनं चैव गात्राणां दीयते नन्ते
प्राप्रेवनावनादेवाभ्यंगे भोजने च वस्तौ च ३
तेषां न संति रोगाणां बाधपीडन भारपीडाव
प्राणास्तेयानतेषां गात्राणां सादनं चैव ४
सुखेनः प्रथमे स्नेहं बल्यवर्णप्रदं यथाः प्रशंसे
ति शास्त्रज्ञा रसनिकर्माणि मूलच्छसर्वरोगा।
णां ५ सुखेनः स्निग्धस्य स्वतनः कृपीतरग।
स्य वस्तिकर्माणि लमस्य वस्तिभिस्थापित त
स्य कर्माणि कुर्वीत ६ एवं स्निग्धाय पृष्ठा भव
तिकाये तमानि राने का।

करके और भार करके प्राणों का नाश न है है और देह विषे
कोमलता होती है अरु यो स्नेह सुखेसे पाने नैं बल वर्णक
रहै अरु शास्त्रज्ञान निकर्मों को विधिवाले वैद्य ने सलाहते
है और सभ रोगां के मूल को नाश करे है ५ सुखे कर स्ने
ह पानतैं स्निग्ध होए के जोडे को फेर वस्ति कर्म पछकारी
करनै अरु वस्ति करके लमहा होए को फेर आरोग्य कर्म नावे
रे ६ इस प्रकार करके स्निग्ध अरु पृष्ठ होए देजोडे सभ कार्य

© Dharmartha Trust J&K. Digitized by eGangotri

कर्णो विषें समर्थ अरु रोगते रहित होते हैं जितना पचना बो
उतने प्रमाण की मात्रा देवे बुद्धिमान् ८ रूक्षी नरो स्निग्ध होए
काए हेलक्षण होते हैं अग्नि प्रज्वलित देह होला अरु बलकी
वृद्धि लिद विषें थिंदे और अरु तेजबल अरु रसादि यथामार्गक
रबलते हैन ९ अरु बहुत स्निग्ध होए को पहेलक्षण कहेन लि
स्वबहुत थिंदी अरु पाणी और मंदाग्नि मन दुःखित सोजा मूत्र
बडे क्लेश कर होता है १० अरु रूक्ष चोडेके पहेलक्षण हैं पतली
रुक्षी बगनेवाली बहुत लिद करता है अरु रजन विषें न हिआ

नरणी घृयामात्रां तां मात्रां दापयेन्नतः ८
दीप्ताग्निर्बलपुष्टत्वं वलवृद्धिः स्निग्धताप्ररीष
स्य तेजोबलाङ्गलोम्न सम्यक् स्निग्धस्य रूपा
णि ९ सुस्निग्धस्य कुद्दल्यं मन्दाग्नित्वं वजमन
स्त्वच स्यपथुः कण्डात्मूत्रं रूपमति स्निग्धकाय
स्य १० कृते हृद्दंगुरीषं संवन्ति वहुशः प्रवाहमा
नोस्यः न हिस्नः पारुष्यं पात्येतानि हलक्षणं ११
स्निग्धशरीराय ततस्तु रंगमाय प्रदापयेत्तस्य
कार्या क्रियाय योकाविवर्जयेत्स्नेहकर्माणि १२
सस्येयवसंवरान्नायेषां स्नेहः प्रदापयेत् यानां रो
गाः कृष्यति भृशवातश्लेष्मान्तरात्तेषां १३ अ
तिशीतेवान्ह्सोदेववैवाभिवर्षति हृयेभ्यः
नस्नेहोदातव्योव्यायामे चैव वृक्षेभ्यः १४ अस्ने
हाम्परिगृष्णांति भृष्य्येत्क्रमस्य मति स्नेहान्
स्मान्मात्राकालं जानीयाद्बुद्धिमान्वैद्यः १५

उदा और देहके दोर ए हे रुक्षों के रूप हैं ११ स्निग्ध देह होएदे
चो रेताई यामडु आवे और यो विपिके हैं साकरे अरु स्नेह
कर्मी कोना करे १२ ते नी के अन्न वाले या सु अरु और यासको
खो देहे होए चोडे को स्नेह देतने लादिदेवे तब तिनां को वायु
अरु श्लेष्मावाले रोग निरंतर कोपने करते हैं ११ अतिशीतका
लमें अरु बहुत गर्मी विषें देववरलके वर्षदेहोया अरु व्याया
मकालि विषें चोडे यांताई स्नेह नहि देने योग्य है १४ स्नेह नहि
देने के कैं बहुत थान केषोषकरता है अरु बहुत स्नेह देने क्रम
होता है तिस कारण ने बुद्धिमान वैद्य काल अरु मात्रा को जान
लेवे १५

© Dharmartha Trust J&K. Digitized by eGangotri

षा॰
हो॰
९१

91

यात्त्वगांके प्रकोप प्रकृशमनापंतकरनेका स्नेहही मूलकहे
याहै तिसकारणते स्नेहसंयोगते विना बुद्धिवालानादेवे १९
प्रकुचेउतेल पकायेविना बुद्धिवाले याने थोडेयानाईनहिदेणे
योग्य तिसकारणते स्नेहके संस्कार पहेविधिनूंकहना हो १८
इति स्नेहपानविधिः दशमूल बिलण ग्रग्निमंथ टांटर पाटल
कसीर देवदार मूरवनी कडेग्रारी कुडेग्रारा भंतडे वा प्रसणदीजड
गलो पटोल वासा त्रिफला हरीड बेहेडे ग्रामले वावडिंग निंब इ
नांदा विधिकर क्वाथवनाके तिस्कोपुनलेवे ग्रकूउतने चारगुणा

स्नेहो मूलं विधानानां वैषम्यकोपसंशमने तस्मा
न्नायोगेन न देयः स्नेहोयमन्यथिया १९ नहि
मपिस्तैलं वा देयमपक्वं तं रोगमाप्नुयैः तस्मा
त्स्नेहस्य मसंस्कारविधिं प्रवक्ष्यामि १८ स्नेहपा
नविधिः दशमूलगुडूचिपटोलवृषैस्त्रिफला
कृमिमारकनिंबयुतैः कथितैः विधिनापरि
पूतरसो घृतमेषजकल्कयुतं च भवेत् १ प्रति
विषासुरदारुपाठाविडंगं कणा विश्वनाली
मनीलोत्पलं शारिवेन्द्रायमाणा हरिद्रा चंद
पिप्पलीमूलतेजोवतीचित्रकं मरिचं गजक।
णाकुलिंगानी तिक्ता तथा पर्पटं पद्मकं वंद।
नौषधीरम्भूनिंबयुक्तं सचूर्णैककल्कीकृतं क्वाथ
सर्पिष्प्रतं साधयेत् २ इदममितगुणं महाति
क्तकं नाम सर्पिः सुमस्तामयघ्नं परं वाजिना
कुष्ठदाहज्वरोत्कर्णकं का गमन्याग्रहोन्माद
निर्नाशनं सकलकृमिरजानिहंस्यामयान्

पावे और कल्कपावे सो औषधी कहते हों अतीस देवदार बठ
लवेल वावडिंग मघो संठ नलीमपत्र नीलकमल कानाथका
लिबलवाय बनकसा हरदल मुथर पिप्पलामूल तेजबल
चित्रा मरिच गजपिप्पल कोगड कोड पापडा पद्म चंदनचिटा
विज्ञामरिव गजपिप्पल कोगड कोड पापडा पद्म चंदनचिटा
लस विरायता इनाकों कूटके पुगदावाणकके क्वाथ और घेउ
विवपाइके सिद्धकरकाउ, एहे महातिक्तनाम घृतवहुतगु
णवाला है अरु थोडे याके सभरोगांकेनाश करहे और कोड
दाहज्वर उत्कर्णक वात व्याधि अपंग मन्याकेठ नाडिका।

© Dharmartha Trust J&K. Digitized by eGangotri

हकजाए उन्माद इनका नाश करता है और रुधिर के विकार वा
शुक्र पित्त के श्लेष्म के ये रोग हैं इन निन्हों को नाश करता है और ते
ज प्रकाश बल पराक्रम योजधातु सार वेगगति अरु बहुत स
रस्वरूप इनों को धाता वीकरना है महातिक्तघृत: कौड शती
स मूर्वा गलोट वा माडेयो मयार धातोना दालचीनी वटलवेल
निंब पटोल धवर वर्चे ब्राहा पापडा त्रिफला हरीड वहेडे आम
ले हरदल दाल हलदर त्रायमाण वनगसा रक्तचंदन मुहल
ठी किरायता मंजीशतावर पदमकाष्ट खस अड्रा वेनस अ

वातजान्पित्तजान्श्लेष्मजांश्चापिरोगाञ्जन
यन्माशुकुर्याच्चतेजोवलंसत्वमोयोजवरूप
मस्तुतं १ गणाङ्कतेमहातिक्तकेघृते कटु
कातिविषामूर्वामुस्तंसम्पाकदनच: पाठा
पिचुमर्दपटोलवचाङ्गलभापर्पटंचैव १
त्रिफलाहेमरजन्मौत्रायतिरक्तचंदनंमधुके
भूनिंबोमागधिकाशतावरीपद्मकोशीरं १
ब्राह्मारग्वधंगुडूचीदृष्योविशालाश्वशारिवे
हेतकटजैश्वषांभगान्सलोमितान्कारयेत्क
ल्कं १ निंबोद्भव:पटोलंच्छिन्नरुहाकंठकारि
कावेषांपचपलिकान्मात्राथात्रीप्रस्थेनम
शुक्ला ४ सलिलेकथितांविधिवयेघ्याणि
हेनाफकंवसंयोज्यं मरुद्धोपक्वमिंदंह्युतम
हातिक्तकंनाम ५ अस्मत्तोपमामिन्द्रकेगुण
कायाग्निविवृद्धेनपथ्यंतेजोजनवपुष्टिकारकं
ष्टंभेरक्तपित्तसंशमनं ६

ह्लनाम गलो धात्री आमली ईदूवा रुणी ब्रमा कालिवेल दो
य उन्नाल वोगरड पहेद्ध वारवार तोलेलेके कल्क नुगदा कर
लेवे और निंबवासा पटोल गलो करै आदि पहे पंच वारवार
तोले प्रमाण और आमले दोसेर मिलायकरके ४ मलविषेका
ढे विधिपूर्वक जितने विषे सिद्ध होजावे फेर कल्क अरु कथ
मिलायके अठसेर घृत पायकर मिठी आंच देकर के पकावे
जब सेर का थक लक के सिद्ध नहिं होवे तो कछुक जल पा
यपकावे का रोहे इसका नाम महातिक्तक है ५ इसका अगुणके
वरावर गुण करता है और वेदकी अग्निवधामा है पथ्य है ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ हो॰ ९२ और तेजवेगदेह पुष्टि बलवर्ण मांस इनांको वृद्धि करै है औ
र कोढ रक्तपित्त और सभ रोग इनांके नाश करणे कों श्रेष्ठ है २
द्वितीय महातिक्तकं घृतम् कडुआति करआत पटोल नि
ब काया कोठी पद्दे सम बराबर करे पाउपल साढे चारो सेर
इनांके मोटे करके कूटके मण २ जलविषे क्वाथ करे चौथा
हिसा रहे तो छाणकर अठ सेर घृत अतिविष पादेवे और मिरच स
उमचो हरीड पिप्पलामूल नेजबल गजूची अमलतास वट
लवेल किरायता वनगसा हरदल दालहरदल वायविडंग

बलवर्णमांसजननं सर्वामयनाशनं श्रेष्ठं ॥ २
द्वितीयमहातिक्तकं घृतं ॥ छत्रिणुगलप
टोलनिंबपुनाकाकमाची समांसानि सर्वा
णि वैकरंजकुर्यासलानुपानं खंडशाब्दे दिन
वारिणा क्वाथयेच्चतुर्थांशशेषं समं तेन घृत
स्याफंके निक्षिपेत् । प्रथमरिचमहौषधं ।
पिप्पलीरोहणी पिप्पलीमूलनेजोवतीन
त्रिकारजहृत्पाठाकिरातस्पतिक्तं तथा
त्रायमाणं निशेद्धे विडंगानि तिक्तापटोल
कलिंगानि चव्याववाचनप्रियस्त्रिः त्रिफला च
नेभेषजैरंशः पलिकैः २ मगुष्ठैः सुतनैः
क्वाथयुक्तं घृतं सर्वमेकीकृत्य पाचयेत्सा
पिरेतन्महातिक्तकनामदेयं ह्यभ्यः स
मस्तामयोन्मादनपवनकफविकारांस्त
था श्वासकासान्गलेगडुरोगान्समस्तिश्चाण
वान्नेत्ररोगांश्च कुष्ठानि शोफांश्च हन्या ।

कोढ पटोल इंद्रजव वचक वर्च मुथार पटकडु त्रिफला हरी
ड बहेड आमले यो औषध दो वार आई होवे सो भाग ते ह्नीपा २
लेणी पद्दे सम औषधीयां पल पल वार वार तोले सम पाले वे
हळीनां पीसके क्वाथ सायरलाके घृतडरलाके पकावे ए
हे महातिक्तकनाम घृत है पहे चौड्यांके नाई देने योग्य है
सभ रोगके हरकरणे वाला है वायु कफ के विकारां को ते
से ही दम खंग गलरोग गंडदोष और सीडके रसके विका
र अग्निरोग कुष्ठ सोजा और पित्तके वायुके रक्तके रोग

© Dharmartha Trust J&K. Digitized by eGangotri

रनोंकोंनाशकरताहैं औरघोडेयांकोवलवहुतसंबास्ख
रूपकोंकरताहै इतिमहातिक्तकंघृतं शरीहिहलतकेसि
कड नद पत्र सौपल साडेवारासेर षोडशसोलांगुणा ना।
लपायकरकाढे यवचौथाहेसावाकीरहे नवघृणलेवे
फेरघृतमिलाके मिठीअगलगायके रखावे २ मरित म
तीस कौड मद्यो चित्रा कडेआरि पिप्पलामूल गजपिप्पल
सड पापड़ा चिवक वायविडंग हरीड बहेडे आमले ३ हळी
नरोंसिद्धहोयाघृत पद्दैरोगहरहै औरकफपित्तनेहोर।

तथापित्तनात्वाततानात्रक्तजानामयान्
हंतिकुर्योद्दुहायानांवलेरूपमसघृते १ म
हातिक्तकंघृतम् त्वकमूलपत्राणिवृशरी
षद्धहृस्यपलशतंकथितंषोडशगुणेनवश
लिलेचतुर्थशेषपरिश्राव्य १ घृतसमिश्र।
कृत्वाम्लकगोपाचयेन्मतिमान् स्नेहचतुर्थी
संयुतैःपिष्टैरेभिःसमालोच्य २ मरिचानि
विषकटुकामसकणा शिखिथावनिपिप्पली
मूलयुताः गजपिप्पलिविडंगमपर्पटकोव
विकाकृमिशत्रुघनेत्रिफला ३ स्निपक
मिदंघृतमार्ति हरंकफपित्तसमुद्भवरुक्
समनं यवनामयशोथक्निाशकरंवृणकु
इहृद्गग्रहनुत्कथितं ४ अनुपमगुणमेत
न्वासकासापहारी अतुलवलजवोन्मत्तेज
सामाशुकारी नयतिपरमवृंहे सर्पिरेतच्छ
रीरे जयतिसकलरोगान्वाजिनांसप्रभुक्तं ५
इतिशिरीषाद्यंघृतम्

पीडाकोसमकरहै वायुकोविकार सोजा वाय रूप हनु
ग्रह इनोकेहरकरणेवाला कहेआहै ४ वहुतगुणवा।
लाहे पद्दैघृत अरुदम रोगकोंहरताहै वेरेवलवेग औ
रपात्तवलतेज इनोकोंमिलावी करताहै पद्देवोडेदेहवि
षेवहुतपुष्टिकरताहै अरुविधिकरकेदीयाहुआघोडे।
याकोसभरोगोंकों जीनताहै ५ इतिशिरीषाद्यंघृतम्।
॥

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰
टी॰
९३

शरीषके सिकडे पत्र जड वो सोपल प्रकजितने जलविषे
काथ होजावे उतने विषे काढकर छाणके रसग्रहणकरके.
फेर पहेले औषधियां पावे रास्ना पिप्पलामूल चित्रा वच भारं
गी शरीहि मधं सेंधालूण हरीड बहेडे आमले चन्द्रनक
लाचीयां दालचीनी तजपत्र नागकेसर गुगल छड गोंद हर
दल दालहरदल वासा खैरसार दिआर कांगडफल इंद्रजव
इनांको हलीनांसे कूटलेवे ९ इनांकाकिछाकारके औरबकरी
के हृयके साथ पैसे शास्त्रमेंकहाहै तेसे घृतको पकावे य

तकाथमूलानि शिरीषजानी तेषांशते द्वे वि
धिवज्जलेन संसाधयेत्तत्र संसृष्टहीनाढ्या।
णिचेमान्यथयोजयीत ९ रास्नापिप्पलीमू
लचित्रकवचाभार्गीशिरीषकणा सिंधूत्थवि
फलावचन्द्रसुतामांसीनिमेदेहृषं वर्षाभ्रम
रदारुवत्सकफलैसं चूर्णयेदेकतश्चैते राजप
योगुतैस्तविपचेत्सर्पिर्यथाशास्त्रतः सम्यक
पक्कमिदानमेघृतमिदं सर्वामयान्वादने म
न्यास्तमेकृत्रग्रहादितगदैस्मादेहितिनेनाकण
के एकांगेविधुरत्रहेहृषणयोःस्कंधेपद्ग।
आमिने उन्मादेवहितमहावलकरंदेयं
हृयेभ्यःसदा ८ गणाकृनेशरीषाद्यंघृतम
शिरीषपुत्रान्स्वसंस्तहृहीन्वाचवन्दंगुणान।
नघृतान्प्रदेयं छनत्रयंचैवसमेसभागैरेता
निसयोत्सपचेत्तनम्म ९

यव अर्थछीतरीसिह होजावे तोपहेवहतप्रेष्टकहाहे
सभरोगांकोंमन्यासंभ हनुटोडीकारकनाना लकवा
मुरखपिरकजाना स्पालिगित उत्तांकविषे पनशान
अपरंग विधुरकेरूकनेविषे अंडग्रहमें मगरोगविषे उन्मा
दविषे इनांकोहरकरताहै अरूपहेघृतघोड्यांकेनारं
दीयाहुवा सदाहितकरवलवर्धनकरताहै ८ पहेघृत
शरीषादिघृतहै शरीषकेपत्रोंसरसलेवे वारगुणा हु
लेनेपाके इनांकापत्यवाय हठ ....

© Dharmartha Trust J&K. Digitized by eGangotri

पहेसमतुल्यभागमेलकेफेरपकावे हकीमतथा पका
हाजानकरके वैद्योने थोड़ेयाकेतनाईदेणावास्तेयोगहे
श्रहवातयकरविकार श्लेष्मकेविकार पित्तकरहोपरोगा
कोहरकरताहै यहशिरीषादितेलकीसेवाकरणेकरके
तेजवलस्वरूपशोभाइनाकोहरताहै ॥ तोमसाशिरीषा
दितेलहै । निंवपटोलकेपत्रवासागलो कौड़ाश्री इन
केभाग ढाईढाईसेर साडेवारासेरडुसविषे पचमणकचे
जलपायकरकेकाढे जवचौथाहिस्सा वाकीसवामणर

विज्ञायसम्यक्कृतविपक्वमेतन्मानायदेयं
भिषजाहृदयेभ्यः वातोद्भवाश्लेष्मसमुद्भवा
श्चपित्तोद्भवाश्चापिहियेविकाराः १ ते
नैवलरूपमतीवशोभांकुर्याच्छिरीषाद्य
मिदंप्रयोगात् ॥ शिरीषाद्यंतैलंपूर्वोक्तम्
निंवपटोलपत्रंवासकमस्तानिदीप्यका
श्चैव भागान्विंशतिपलिकाःषोडशगुण
मत्रपानीयं २ क्वाथेतुपादशेषेसर्पिः
प्रस्थंसंयुक्तंपचेद्धीमान् पेष्याणितत्रद
द्यात्फलत्रयंत्रिकटुकंचैव ॥ सम्यक्प
क्वेनानेनान्तरगेभ्यःसंयुक्तंचगुग्गुलनाके
वलमथवादेयंनिहंतिसर्वाणिकुष्ठानि १४
शोणितपित्तंदद्रुंविसर्पकंचैवतथापा
मां पीतंजयतिस्तन्यानांजनयतिरूपंवल
वर्णं ॥ अमृतोपमस्तोत्रंदिष्टंसर्पिरिदंपंच
तिक्तकनाम

है तोसौपलसाडेवारांसेरहुतपायके
पकावे बुद्धिमान औरइसमें यहेवस्तुपीसकरप्रति
वापदेवे हरेतवहेपकहैसा फेरहकीमतासिद्धहोयाजान
करके थोड़ेयाकोगुलकेसाथदेवे अथवाअकेलाहीदेवे
सोसभप्रकारके कुष्ठकुरुक्तकेपित्त दद्रो विसर्प ओरक इ
नोकोनाशकरताहै औरथोड़ेयोंको स्वरूपवलवर्णइनोंके
उत्पन्नकरताहै २ यहेपंचतिक्तकनामहुतअमृतकेतुल्य
केहयाहै ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
१८

अरुरसकेपीणेकरकेघोडेकों सभकार्यसहारणेकी
समर्थवालाहोजाताहै १६ पंचतिक्तनामकहतहम् काको
लि क्षीरकाकोलि वीराखालि आंवली जीवक ऋषभ
ऋद्धि हंसपदी मनका कालीवेल इवारुणी तमा
विवदुवा १७ मेदा महामेदा सोप शतावर मुंडी मंजी
मलठ ब्राह्मी खालि खालपर्णी सण झीरी वंसलोचन
मोथा मुद्गपर्णी माषपर्णी इनोंको बुद्धिमान चूर्णकरे
यहयोजीवनीयगणहै तिसकरके जैसेघोस्त्राविषेक

पीतेनानेन भवेत्तुरंगमः सर्वकर्मसहः १६
पंचतिक्तकनामकहतम हेकाकोलीवी
राचामलकीह्रीवनीवकर्षभको ऋद्धिहं
सपदीमधिमद्वीकोषाविंवामेदा १७
मेदेद्वेशतपुष्पशतावरी श्रावणीकणा
मधुकं ब्राह्मीतथाविदारीखियुपयस्यत
गाक्षीरी १८ मधुकानिमुद्गपर्णीमाषप
र्णीवचूर्णायेद्धीमान् एतेस्तजीवनीयेः
शर्पिविपचेद्धृयाशास्त्रं १९ क्षीरेणसमा
युक्तैस्तनः प्रयुंजीतपतिकेघाथौ मारु
तपित्तेवतथाशोणितपित्तवाह्याना २०
क्षीणेंद्रियाचयेवाहाः इच्छाविशेषतोह
ह्याः वडवास्च प्रसूतास्तसर्पिस्तेनसदा
तथा २१ पानेवस्तोनस्यव भोजनेचेवदाप
येद्धीमान् एतच्छ्रेष्ठं सर्पिनिर्दिष्टजीवनी
याख्यं २

हाहै जैसे चूर्णकों वारगणा दुग्धपायके
पकावे पाकवास्ते कल्ककजलपाणकरहै पश्चिमा
घाविषे यहचूर्ण पित्तरोगमें वातपित्तमें रक्तपित्तवि
षेघोडेयोंकोदेणयोगहै २० औरयेदक्षीणइंद्रियवा
लेहें अरुवीर्यरहितयोहें इच्छाफे अरुसुरसहोरेघोडी
कायहेचूर्णदेनयोगहै २१ यहजीवनीयनामचूर्णपीने
वास्ते पछकाविषे नसवारमेंभोजनविषे बुद्धिवाला
डवावे २२

© Dharmartha Trust J&K. Digitized by eGangotri

अस्थानवस्ति मधुरगणाकरकेहि छोडेयोंको कहिहै अह
इसस्नेहकर्के वस्तिपछकारिदेवे और इसजीवनीयघृतके
समकोइवीस्नेहनहि वलंरगकरणेवाला कहेया जीवनी
यघृतः २१ मालती निंव पटोल इनोकेपत्र कोउ दालहट।
दल हरदल कालीवेल मजीठ हरीड सित्या नथ मुलठी
करंजवीज इनाहूयोंकाकरके सिद्धयोघृत तिसकर्के सूक्ष्म।
स्थानोंविषें मुख मर्मस्थान विषे घाय मुखवाले हूगे पीडा
स्थानोंविषें ... गंभीरघाय हैं तिन्हा
करकेशुद्ध यो व्रण अहनस्नरकेसहितयो घायहै

आस्थाप्य हृयं मधुरैः स्नेहेनानेन दापयेद्वस्तिं
नाम्यस्येतसमः समः स्नेवलवर्णकृत्कथि।
नः २१ जीवनीयघृतम् जातीनिंवपटोल
पत्रकटुकादार्वीनिशासारिवा मजिष्ठा।
मधुसिक्थ नक्तमधुकैस्तैलाहवीजाविं।
तो २२ सर्पिः सिद्धमनेन सूक्ष्मवदनाममं·
श्रिताषाविणो गंभीराः सरुजो व्रणाः सग
तिकाशुद्ध्यंति पेहंति च २४ जात्याद्यंघृत
म् नाकीनां कषायेण पचेत्स्नेहवत्स्थय
तस्मिन्द्याह्सांकोली नाम्नाभवतिताद
णी २५ मत्स्यानां जांगलादीनां मजनश्च·
एथाविधाः गोजावीणां वसपिंषितैला
निविवियानि च २६ दधिशुक्तसुरामंडसौ
वीरकतुषोदके अम्लकांजिकतक्रेच यानि
चाम्लानिकानि च २७

कोशुद्धकरताहै और अंकूरवढादेनाहै २४ जात्याद्यं।
घृतं। वला यमणीआदिकाथकरकेवरस्नेह घृत तेल
सिक वदी इनाकोकाढे तिसविषेसरकी सिकपावे इस।
केसमान और कोई नहि है २५ और वनके याजीवहै तिनकी म
जा भिन्नप्रकारकीया और घृत गौका वकरीका और तेलव
हुतप्रकारके २६ और दहि सिकी सुरामंड सौवीर कांजी
भेद नाहे काकांजी अम्ल कांजी छाछ और मध्य इत्या।

दि २२

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ और कुलत्थ इत्यादिक यो अन्न हैंन तिन्हांके रस तैसेही मांस
टी॰ रस पावे अनूपदेशके जीव जलके वनके जीवोंका २८ वैद्यक्का
९५ थकों सिद्ध करे उत्तरवातिक यो पदेद्रव्य हैं समग्रथवा यो मिल
यावे तिनांको भिन्नभिन्न तिनांसभनांके वत्तोवत्ती समभागसे
सोलांसेर पावे अरुसभनांस्नेहांको तत्पभाग अठसेर लेवे ३०
पदे सभद्रव्य किठे करके महास्नेह पकावे हल्वेपकेकडाहा विषे
वडे विस्तारवालेमें अथवा काठके लोहेके विषे ३१ चीड मा
सिट हाएणके वेल इनांवस्तुओंका प्रतिवायकल्कतुहि।

कुलत्थादीनि धान्यानि तेषामपि रसो भवेत्
तथा मांसरसं दद्यादानूपोदकजांगलं २८
कषायं साधयेत् सम्यग् भिषग् उत्तरवातिके द्र
व्याण्येतानि सर्वाणि यथालाभं पृथक् पृथ
क् २९ विभज्य समभागानि तेषां दद्यात् द्विरा
टकं स्नेहानां नाडकं चैव तत्पादेन च दाप
येत् ३० एतत्संहृत्य संभारं महास्नेहं विपा
चयेत् टंकटाहे विस्तीर्णे भाण्डे कांस्या
यसेऽपि वा ३१ तत्र दद्यात् प्रतिवापं सिद्धमा
ने विचक्षणः रास्ना व्याघ्रनखं विश्वं शता
सा देवदारु च ३२ सरलं स्वर्भीभार्गीवान
ना पिप्पली वचा विशती नी वनीयानी।
श्रेयसी मधुशिग्रुकं ३३ लवणानि च सा।
र्वाणि समाहृत्य पृथक् पृथक् पक्षामक्षप
लं तत्र भेषजानां प्रदापयेत् ३४

मान पावे रैसण नख सोप देवदियार ३२ चीड मा
लनी भंडीगी अगर जारा मधा वचै ढीश हरीडं
अरु मिठाशरीहि ३३ और सभप्रकारके लूण पदे स
भ किठे करके वत्तोवत्ती अठपल इनोंके चूर्ण तिस।
विषे पायकरके मिठीमिठी आंचके साथ पकावे
अरु इस विषे उगयन हि पावे और उगयकरके वी पकावे

© Dharmartha Trust J&K. Digitized by eGangotri

योग्य है मदिरेके साथ अम्लसाथ लूणोंकरकेवी पका
णोकेहेया है २५ स्नाउ ओषधीयोंकरकेहि पकावे अरुअ
म्लिन्नार स्नाउ थिविनासिद्धकरणेकहाहै पहेस्नेहवायुक
रके पीडितयोंचोउ तिनाकोदेवे २६ उपकेसाथमि
लाके केवलतेलपकावे तिसकारणतें घृतअरुतेलप
कावे तोतिसकोमिश्रककहतेहैं ३० ओरभिंकयेउतेल
इनकोंसिद्धकर तोसोमध्यमहै ओरगलोंकातेल इसीत
रां अरुणास्नातेल इसीतरांपकावे ३८ सेहचारप्रकारक

सद्भिनापहिपवेत्सीरंतत्रविवर्जयेत् ११
त्सीरेणवापिपक्वंमद्याम्लालवणानिव
पत्तद्धानाभिभूतानांमहास्नेहंप्रदापयेत्
पतैरेवौषधैःसर्वैरम्लक्षारविवर्जितैः २९
पयसासहसंयुक्तंतैलमेकंविपाचयेत् त
स्मात्सर्पिश्चतैलंचपक्वंमिश्रकसंज्ञिते ३०
वसामपिश्चतैलंचमध्यमंतत्रकल्पयेत्
गुडूचीतैलमध्येवेरास्नातैलंविपाचयेत्
स्नेहःचतुर्विधःप्रोक्तःपंचधासंप्रयोजितः ५
वायुपचविंयहेतुःस्यानवगतंजयेत् १
नत्रपित्तात्मकेदोषश्लेष्मिकेवापिवर्जये
त् अग्निरल्परसोह्येषवायोश्चपरमौषधं
४० इतिगणकृतेसिद्धयोगसंग्रहेमहास्ने
हः। तैलेनवापिवत्साभिस्नेहपाकेनिवापय

हेयाहै सोपंचप्रकारकरकेदीयाहुवा पंचतरांकेवा
यु विहतहोयदे अरुकोटेस्थानविषैंप्राप्तहोयपयांको
जीतताहै ११ पहेमहास्नेह पित्तकेरोगांको अरुकफके
रविकारोंविषैंनादेवे पहेअग्निकेसमकहाहै सोवा
युविकारकोश्रेष्ठओषधहै ४० इतिगणकृतेसिद्धयो
गसंग्रहेमहास्नेहः॥ अवतैलबहुतकीविधिकह
तेहैं सोसरण वसा ओरघृत तेल पहेतिसेहे।

© Dharmartha Trust J&K. Digitized by eGangotri

शा० स्नेहतंजाएा ४१ तिसको बुद्धिवाला वैद्य लूएा अरु अ
द्वि० म्लविंविनापकावे और ऊपुकरकेपकावे तिसको अथ
१६ वा दशमूल विलएा अग्नि मथ टांटर पाटल कंभीर शा
लपर्णी पृष्ठपर्णी कंडेआरि कंडेयारी भबडे इनकेरस
96 करके सिद्धकरे ४२ योएवैनियमकुहेहैन तिनोकरके
अन्नरसोंकरके तैसेहीमांसरसकरके सिद्धकरके अग्नि
तेजनारके ठंडेहोएदेविषें अठसेर स्नेहमें अठपला
खेडपायकेहोत वैद्यसंदरागुमस्थानविषेंरखदेवे ४४

वसाघृतं च तैलं वा त्रिस्नेहं स्नेहतं विदुः ४३
पचेन्नह्युहिमाम्भैर्घोल लवणाम्लविवर्जये
न् ह्रीरेणाव पचेन्नह्वदशमूलरसेन वा ४ २
नियामैश्चतनो दृष्टैर्यार्मासरसेन च था
सिद्धावतारितेशीते शार्करांचप्रदापयेत्
स्नेहपाढके शार्करायाश्चूर्णस्याष्टपलं हूतं ४४
ततः संयोजयेद्वैद्यः सुनिगुप्तनिधापयेत्
स्नेहकार्येषु सर्वेषु प्रधानं त्रिहूतं मतं ४४
प्रवृद्धदोषाश्च वातादीन्संनियच्छति ४५
वलवर्णोपजननमुत्तमं च रसायनं पाती
भ्यजनवस्ति भ्यौनावनेवयथागमे ४६ रो
गिणां सप्रयुक्तमन्नं ऊर्ध्वहारोगपथ्यमे
आरोगाणांचकल्पितः स्नेहोयमस्तोपा
मः ४७ इति वैघृत ह्रूतम् ।

सभस्नेहकार्योंविषें त्रैहूनप्रधानकहेयाहै परेस्नेहहा
वधेहोएयोदोषहैं वातादिक तिनोकोहरकरताहै ४५
अरुवलवर्ण गेजयातवसा इनकेवधानेकोंवहूनहै।
पुष्ट अरुवृद्धवस्था रोगकेनाशकरताहै अरु पान मा
लस पदूकादि नसवारइनाविषें असेशास्त्रविषेंकहाहै
तैसेजोरे ४६ रोगीयोंको अरुविधिकरदीयाहोया संदर
निरोगताकर्ताहै अरुरोगरहितोंकोपरेस्नेहअमृतहै ४७ इ
तित्रैहूतनेहूत ॥

© Dharmartha Trust J&K. Digitized by eGangotri

तैलस्वादविषें मधुर है ग्ररु विपाकविषें कटु कहिया है
ग्ररु कषायरस है चिकना है ग्ररु पित्तको वधाता है ४८ सो
तेल वायुको समन करता है बलकारु है ग्ररु यो वकृतमोटे हैं
तिनकी स्थूलताकौ लेखन करता है हौली करदेता है ग्ररु
योनि सिर इन तिनांके मासको वधाता है ग्ररु श्लेष्मरोगवा
लेकौं देने योग्य हैं ४९ ग्ररु ज्ञानथके होएकौं कोमल।
करता है ग्ररु रोमांमूलांकौ ग्ररु खहानाउीयांकौ नमस्कर
ता है ५० योनवाविषें ग्रामहोय प्रयोग है तिनांसपणांको

आस्वादे मधुरं तैलं विपाके कटुकं स्मृतं कषा
यानुरसं स्निग्धमुष्णं पित्तविवर्द्धनं ४४ वा
तप्रशमनं बल्यं स्थूलानां लेखनं परं कृशा
नां बृंहणं चैव श्लेष्मिके च प्रयुज्यते ४९ ज्ञा
नेशुत्र विशेषेण नद्यंगे प्रशस्यते मस्तुक
रोति श्रोतांसि सिरोम कृपांसि रोमस्थया ५० न
गानां श्वापि येभूतास्तान्सर्वान्पकर्षति भ
ग्नव प्रतिसंधत्ते गात्रं यत्रापि विश्रुते ५१ औ
ष्णात्कल्पविशेषेण श्लेष्माणं संनियच्छति
उष्णत्वादेव पित्तं च प्रकोपयति सेवितं ५२
श्लेष्मिके च पिरोगेषु नद्यंगे प्रशस्यते ति
लतैलं विशेषेण वातिके च प्रशस्यते ५३
तैलमेवविधं प्रोक्तं सर्वेहान्ते प्रयुक्तितः सा
रत्नीरास्न त्रिफला वारुण्यो गुडसम्युताम् ५४

खैंचकर बाहर निकासता है योअंग भजे दे हैं न ग्ररु
खिसके दे हैं न तिनांको जोड देता है ५१ गर्म होने तें कल्प
समर्थ विशेषकरके कफको रोकता है ग्ररु गर्मस्वभाव तें
सेवनेकरके पित्तको उपित्त करता है ५२ ग्ररु श्लेष्मकेरो
गांविषें सो मासस्सवा सत्तश्रेष्ट है ग्ररु तिलांका तैलविशे
षकरके वातरोगांविषें श्रेष्टक होता है ५३ तैलयो है सो सभ
रत्न ग्रोविषें युक्तिकरके वर्तमान कहेया है लारउग्य स्र
स्त्र त्रिफला वारुणी मदिरा गुड इनांककें युक्त देवे ५४

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰
टी॰
८७

97

होउ इयांको तेल गुणकारी है छे रुतों विषे वर्षा ऋतु ने थें ले
कर सो वर्षा ऋतु विषे यव क्षार साथ देवे शरद में उपर के
साथ करे या है ५५ हेमंत विषे जल साथ देवे शिशिर में
त्रिफल के साथ वसंत विषे मदिरा करके देवे ग्रीष्म में गुड
के सहित हित है ५६ अरु पोष महीने विषे सण के साथ हि
त है इस तरां तेल के देने ते बल गल उदर पेट वृद्धि होजाते
है ५७ तिसकरके निद्रा नेत्र कृमि इनों को हर करके रण में अ
रु मार्ग विषे बडे पराक्रम वाला होता है अरु अंग छुटे रहिते

तैलं शस्तं तु रोगाणां षट्स्वृतुकं तु दोगमात
यवक्षारेण वर्षासु पयसा शरदीष्यते ५५
हेमंते तु समायुक्तं शिशिरे त्रिफलायुतं व
संते सुरया सार्द्धं ग्रीष्मे गुडसमायुतं ५६ पौ
षमासि युतं तैलं सुरया संयुतं हितं पवै तै
लप्रदानेन हृद्दलगलोदरा: ५७ निद्रा ने
त्रक्रिमिहीना वृद्धा धस्म महाबला: भवंति
वाजिनो नित्यं स्वहतागाः स्थिरविक्रमाः तैलवि
धि: अमृता या रस्नाद्रोणपचेत्तैलाढकं भिषा
क् दद्याच्चार्टकं दद्यात् दने: प्रोक्तै: समन्वितः
मूषणं पिप्पलीमूलं चित्रकं हस्तिपिप्पली
पाठा च कटुका कुष्ठं विडंग दारु सैंधवं ६० व
लाप्रसारणी रास्नामधुकं गोक्षुरं सचं सिद्ध
म् हृद्यग्निना तैलं वन्तैः योजयेन्नरः ६१

रहितें हैं और पराक्रम स्थित होता है ५८ तैलविधि: गलों
को रस भाग विषे तेल अढक सेर वैद्य पकावे अरु मदा अढ
सेर पावे और पहेव लापा करके सो कहते हो ५९ मयो मरि
च सुंठ पिप्पलीमूल चित्रा गजपिपल वटल कौड कुठ वा
वडिंग दालहारदल सेंधालूण ६० पमणी कालिवेल रै
सण मूलठ भकरे दालचीनी इनों का चूर्ण पाय करके मि
ठी मिठी अग्नि लगाय के तेल सिद्ध करे तिसके चार प्रकार के
कार्य विषे पान मालस नसवार पचकारि इनों में ६१

© Dharmartha Trust J&K. Digitized by eGangotri

अरु उत्कर्णी हनुस्तंभ गात्रका हकनेमें हनुग्रह मन्यास्तंभ
महावात वातवलासक विषें देवे ९१ अमृतादि यह तेल
पालिहोत्रणे कह्या है इति अमृतादितैल अश्वगंध साढे
बारासेर मिहीन करके मण जल विषे पकावे चौउ तेल अ
ठसेर अरु दूधवत्तीसेर पाक करके पकावे अरु इनका प्रतिवाप
पायके सो कहते हैं शतावरी मघ नगर चंदन श्वेत मनका
रसमिट रक्त श्वेत दोनो दालचीनी तेजपत्र खस पद्मकाष्ठ ना
गकेसर वायुनेरा ..... कडेआगर गोभि होलिहोलिसि।
हकरे फेरदेवलिसो अरु वायुकरके नष्टचित्तवाले कृशां

उत्कर्णके हनुस्तंभे गात्रस्तंभे हनुग्रहे मन्यास्ते
भे महावाते दद्याद्धानवलासके ९२ अमृता।
द्यमिदं तैलं शालिहोत्रेण भाषितं अमृताद्य
तैलं वाजिगंधाशतं श्लक्ष्णं तैलद्रोणं विपाव ९४
येत् सर्पिस्तैलाढकं तत्र पचेत्क्षीरचतुर्गुणं
वरी मरणाल नगर हिमद्राक्षा पुनर्नवे तवक
त्रकोशीरपद्मपुष्पकेशपकर्षिभिः ९३ ना
गपुष्पाप्लवहूतीगोजिह्वाभिः शनैः शनैः
द्दितं कृशानाम् अश्वानां वातेनोपहतचेतसां ९४
क्षीणानां हततेजानामपि मांसजननेपरं अश्व
गंधाद्यतैलं देतद्दूत्यो विस्रोव देवदारुमधु
शिग्रुः अमृतानि विषाणपाठा वृषाणां काथयच्छा
णासु ९८ एतानि वेवराभेमागधिकास्सुतानि
कार्षाणि तैलं तनस्वविपचेत्स्त्पुन्कैकाथ।
कल्काभ्यां ९९

वालेकौं हितकार है अरु मांसके बधा
नेविषें बहुतश्रेष्ठ है इति अश्वगंधादितैलम् कडेआरि
कडेआगर संठ मुन्यार नागर मोथा दियार मिठा सहो।
जण गलो पतीस वटलवेल इनका काथ चारगुण
जलविषे काढे यवसिद्ध होवे तो पुणलेवे गौरमथो अ
मणकी यो पायके इनोंकरके काथ कल्क यो कल्यकोया
वस्तहेन तिनांको पायके सिद्ध करे यह तेल अश्वको रो
गविषे अनवासनबस्तिविषे चौडे यांको श्रेष्ठ है अरु
पानमें पक्कारि नसवार इनो विषे हित है ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ हो॰ ९८ ग्रहन्येष्टुशमकेनाशकरक्कहाहै ७० इतिहस्मादितैलम्
कालीवलकेपत्रजडलेके कूटके साडेबारांसेरलेके मण
पाणीविषे काथकरे जबचौथाहैसाबाकीरहे तोपुणले
वे गेरकाथ्यनेहूणाकांजीलेवे गेरग्रद्धाबी इतना हीपा
वे मठाग्रठसेर ग्रहनेलग्रठसेर गेरइनाहंग्रोंका पलप
९८ लपायकेसिद्धकरे भलाबे पुठ कालीवेल पिप्पलामूल
चित्रा रास्ना सैंधालूण दशमूल विलूण अग्निमंथ टांट
र कपूर पाटल भूरकरणी देवदार कडेग्रारि कडेग्रार प
रणकीजड वंच यमणी कालिवासा मद्या ११ समवरा

पनलकफजोग्राधौप्रशस्तमनुवासनेनरों।
गाणां पानेवस्तौनस्येभ्यंगेतैलमुद्दिष्ट १०
इतिहस्मादितैलम् पंचमूलेत्युपुनाप्रसारि
णीकहितशतेनतस्याः क्काथसलिलद्रोणे
चतुर्थभागावशेषित ११ क्काथाद्विगुणंद
धोकांजिकमम्लंतथाठकेदभाः तैलस्याढ
कमेकंपलिकाभागानिवेमानि १२ महान
कानिमेदिप्रसारणीमूत्रचित्रकंरास्ना सिंधु
स्यदशमूलवचावलासहवरीकुसा १३
समभागैर्मदहंग्रा सिद्धनाम्ना प्रसारिणी तैल
पानेवस्तौचतथानस्येचाभ्यंगे वैवपुजीत
हन्याद्वातविकारान्विसृग्वातंशुगुल्मम ३
रुणाकामैकाग्रमन्यास्तंभनरगाणा १४
प्रसारिणीतैलम् रसपलशतानावेयागो।
हरसप्रसस्थमसपुंको प्रस्थमस्तारससघप्र
स्थैकप्रसारणया १५

वरभागलेके मिठीग्रां
वसेसिद्धकरे यहेप्रसारणीनामतैलहै इसको पान
मालिस नसवार पद्धकारी इनाविषे योडे १६ यहेवाय
केरोगोंको सर्ववातको शुगुल्मको उरुणीको ग्रामवि
कार पदवान मन्या गलनाडी कारुकना योडयोंके परे
रोगनाशकरताहै १७ प्रसारणीतैलम् शतावरीकारस
साडेवारासेर ग्रहमलेरकाटोसेर गेरगलोकारसेर का
लीवेलकारसदोसेर मठाग्रठसेर ग्रन्नकांजीसालासेर

© Dharmartha Trust J&K. Digitized by eGangotri

तेल अठसेर औरइनांकाचूर्णकरके तेलकोपकावे ११
मेद्या मिरच सुंड वचे हरदल कौड हौवेर शतावर रास्ना रा
ञफल सोए ८टांक सैरियां केईआरी ७८ मेदा महामेदा
मुलठ पमणी सैंधालूण वायविडंग पिप्पलामूल वजीय
मणी निंव कालिवेल ऊग्राण पहसभ वारवारतोलपायके
कोम अग्निलगायके सिद्धकरे ७९ इनारोगों विषेंदेवे
सरणी वातरोगों विषेसभस्तंभों विषें वातवला सविषें
एकस्तंभमें ऊरुकंणक विष्वकवात लकवे महास्तंभवि

षभाश्वाफकमेकं हितगुणं चैवाखकांजिकेन
तैलस्याढकमेकं पेष्येस्तुतैःपचेदभिः १
मेषंववाहरिद्राकटुकहपुषाशतावरीरा।
स्ना मदनफलेशतपुष्पापुनर्नवासर्षपाद्दर
नी ७८ मेदेद्वेयष्टीमधुनागवलीसैंधवविडंगा
नि पिप्पलीमूलंबलानिंवहेशारिवेपालिकं
स ७९ तन्निहंत्यरहयोदेयंवातामयेषुसर्वे
षु स्तंभेषुचवदानंतथावातबलासेवबाह्यानां ८०
एकस्तंभोरुकणकविष्वग्वातादितेमहास्तं
भे पानाभ्यंजनवस्तिषुनस्येषुवदापयेन्म
तिमान् ८१ शतावरीतैल काकोलिद्वयऊ
र्ज्जिनिगिलितकमोवालमगुमानरेवं देमृद्वेन
लिकालेवेगशारलाप्पामाशतालाद्भतैः ८
मंजिष्ठागुरुजीवकषभकणायष्टाह्वसिं
धुरवैः संगृभीरूमराह्वपत्रकवचावर्षा
भककोलकैः ८२ माषाकाथसमास्तुतैःवि
पिवनकैःपयोन्मिश्रितैः। इ देखो योग्य है और
पान अभ्यंग पक्का रि नसवार इनों विषें वंदिवाला देवे ८१
इति शतावरीतैलम् काकोलि क्षीरकाकोलि ऊड मोदनी के
वलहरनका गूंद कौंचवीज मजूली नख मेदा महामेदा
नडीशाक लौंग चीड प्रियंगू सौंफ मजीठ अगर जीवक रि
षभ मचा मुलठी सैंधालूण त्राण शतावर देवदार त
पत्र वच ४टांक मासा इनांकेकल्ककरके माषांकेका
थसमान औरदुग्ध कल्कपायकरके तेलसिद्धकरे ।

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
टी॰
९९

९१

येमें तेलकी सिद्धिकहि है सो तेल सभप्रकारके वायु अर्द्धंग
गठीया आमवात अपबाहुक लकवा हनुस्तंभ कुबड़ी इनों
को नाश करता है और नसवार मालस पानवास्ते पछकारी कुरा
नेवास्ते सदाही वैद्योंने देने योग्य कहा है ९२ इति माषतैल।
महायपयाज्ञनकेवर्णत्रोप सातेवांसेर अरुमणजलवि
षेकाढे यवचौथाहिस्साबाकीरहे तोछुणकर हलुवेयाजा
णके तेलसेरचारपावे और इनोवस्तुओंकाकल्क दोदोपलपा
वे ९५ असगंध मजीठ मैंथाल्लूण मुलठी निंबकीजड सौंफ

सैंधपक्वमशेषवातशमनेपूर्णाभिघातापहे
अपस्मारबाहुकर्दितहनुस्तंभेष्वथातःपके
नस्याभ्यंजनपानवस्तिषुहितंजोयंसदापैडि
तैः ९३ माषतैलम् माषाणांकालजानानांप
लानांशतमाहरेत् पाचयेज्जलद्रोणेचतुर्भा
गावशेषितं ९४ तेनकषायविहितानतैलास्या
ढाकेपचेत् कल्केयमाणिचैमानिहिपला
निप्रयोजयेत् ९५ अश्वगंधासमंजिष्ठासैंधवं
मधुयष्टिका निंबमूलंशताह्वाचरास्नामपि
समाहरेत् ९६ एतत्सिद्धंग्निनासिद्धंसर्ववातवि
कारेण सर्वरोगप्रशमनंसर्वस्तंभनिवारणं
अशीतिवातजानरोगान्सोदत्तयोजितं
शालिहोत्रेणमस्यानेमाषतैलमिदंस्मृतं ९७
माषतैलम् अथायुर्वेदगणोक्तंतेसिद्धयोग
संग्रहस्तेहकल्पाःसमाप्तः। क्रियाक्रिमीघ्नी
दोषघ्नीमारोगप्रपक्षरीहितो

ऐसन एरंपायक
र मिठी ग्रांथके साथ सिद्धकरे विधिसे सो तेल सभप्रकार
के वातरोगांवालेके सभरोगनाशकरता है और सभप्रकार
के स्तंभकारक जाना अंगोंका तिनोंको हराटेता है ९७ और
असी प्रकारके वायुरोग हैं तिनोंको दीयाहवानाशकरता
है ऐसे माषादितेल शालिहोत्रणे अश्वमस्यानविषेकहेया
है ९८ माषादितैलम् गणाद्धतेआयुर्वेदसंग्रहस्नेहह
नतैलादिकल्पासमाप्तः। अवघोड्योंकीचिकित्सा क
हिये उनेआदलेकर करनाहे। वैसीकीक्रियाहै क्रिमीया

© Dharmartha Trust J&K. Digitized by eGangotri

कों नाश करणेवाली और रोगकों हरणेवाली और निरोग्यता आरोग्य करणेवाली हितकारी है अरु मुखवेप्रहृकारनी है अरु मास बलको वधानेवाली क्रमकरके कहते है काढापिंडी कोडियोगी वधावाली अरु सभ रतन विषे गुणकारी है २ मरिच लूणपंच सें धा सोंचल बिड समुद्र साभर चित्रा सरेयो हिंग वटलवेल कि रायता मचा पिप्पलामूल अमलतास हरदल दाल हरदल वा वडिंग निंब पटोल गलोय सभाल रेंड महानना कोले माईकेवीज १ रेशण गजपिप्पल न्वाण हरीड विलकथ म

मुखमंसेशोधनीचैव हृहणीबलवर्द्धनी १ आरु एवंप्रवक्ष्यामि वाजिनां कटु पिंडिका कटुकी षधसंयुक्तां सर्वेनेविधिहितां तमा २ मरिचं लव णंपंचकं चित्रकं शषेषा हिंगुपाठा किरातसप्तिकेकणा पिप्पलीमूलमारग्वधं हेहरिद्रेच विडंगानि निंबपटोल गडूचीतथा रेणका शिग्रु गंडीर मारध्नश्च मेव हवीजेर्युतं १ सरसगज। कणाजमोदा अभया विल्वमध्यं करंजफलस बीजा निनकाकूयजाणि नीजोवनी पील्काष्टतथा वत्सकं नवबीजेचकिराव वाजीरकेद्वे कणे ४
न्यार्जकं अस्तर नीकनिर्गुंडिया अरुकर भीयुतं शनिविषकटुमत्स्याडिकाराजिकानागरं देवदा र्वेन वचा रसोन हंसधावनीभार्गीमूर्वा च सर्वा णिचैमानि संहूणा गोमूत्रयुक्तानि निरूपयेत् ततः पिंडिका मात्रया ख्याय एवं ह्रकाले समसला मयो नष्टाद नीदापयेत् ५

इलायची केलाफल करंजकेपत्र तेजवल पीलुछलकाकाष्ट कोगड़ केसिकरे इद्रजव छल कालाजीरा चिट्टाजीरा म ह्मा वणतुलसी मथार एनी करंजुआ वणा आमले वहेडे पारल प्रनीण कौड़ मिशरी राई सुंड दाल हलदी वच क थोम वासा कडु आरी मडिंगी मोडेयां गलोटवा एह सभ वस्तुका चूर्णकरके गोमूत्र साथ मिलायके प्रमाण किया पिनी यावनायके होरेनाईप्रातकालमें देवे सोसभरोगों के हरकरणेवालीहै और सभप्रकारकी रोग अरुनाशमें

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ सीउ दम हृद्रोग सूल अमवात उपजिह्वा और जिह्वाके रो
हो॰ ग वालक नासाके रोग इनाको नाश करती है ये चोउ दाण
१०० नहिं खावे अरु जिनाका वर्ण विकृत होवे अरु ये निर्वल क्षी
ण है यात अग्नि जिनाकी तिन्हांको मदरे के अरु आसव मा
ध्वीक इनौके साथ मिलाके तिसु देवे कटु पिंडीको इनाको
मेल सदा करणी मदिरा करके चोउ करके और गोके मूत्र करके मि
लाय चोउ याको योस दाप्रत विषे जितनी समर्थ होवे और
ये प्रातकाल विषे भोजन करणेवाले को वारतोल देवे उर

नयति सकलकासं सिंहाणकश्वासहृद्रोगशू
लाम्बवातहृज्जिह्वमय्यावालकानास्यनास्यम्।
यान् हन्ति मधासवालोडिता खादने येन खाद
ति वाह्वविवर्णास्तथा दुर्बलाः क्षीणवह्निय
यो वाजिनो नित्यशः ८ तेषां प्रयोगं कुर्वीत स
दा कटुकपिण्डिका सुरवा सर्पिषा वा पिग वा मू
त्रेण वा पुनः ७ संसृष्टा वाजिना देया कल्पमग्र
नशालिनो दापये त्वसृता हुंतनि पायड रहंतनं
क्रिमिकोष्ठे तिलैः पिष्टैः सुरया मद्य खादने स
रयामर्दिन वैवदुर्वलस्योपकारयेत् ९ सन्न
हरणमेन हीनीणनाग्रष्ट सुख्यते शतीवका
लमयस्य ग्रहणी वाप्यदीप्यते १० सयं श्ले
ष्मः स्मनाहं यते चाग्र एवेशः नष्टेव श्ले
लवर्णाः सेयवाघसपंचभिः ॥ इष्टगाष्टगु
णो कृता देया लवणपिंडिका प्रशस्ता चूतपी
नानां वर्षाकाले विशेषतः १२

हेतन पाउ विशेष विषे पायके ८ जिसके कोष्ट विषे क्रिमी
होवे तिसको तिलो करके अथवा आटे साथ देवे जिसने भो
जन थोडा खाया जावे तिसको मदिरे साथ देवे अरु निर्बल
के ताई मरामदरा साथ मल करके खुलावे ९ क्षीण निर्बल
होउ याको अष्टवल करके याहे और चिरकाल चोउ की ग्रह
णी जठराग्नि को प्रकाश करे है १० और इसकरके आपत्थ्यमुक्त
प्रसन्न मन होया दा कमकरके वधता है और ते सेहि स्वेदमेय
वाधिक लवणपंच नलोचली अष्टगुणा कर्के लवणसाथ पिंडी
देवे।

© Dharmartha Trust J&K. Digitized by eGangotri

जिनांकों चूर्न पिलाया होवे तिनांको गुणकार है अरु वर्षा।
कालमें बहुत गुणकार है १२ अरु शीत वायु करके उत्पित
भै मंदाग्नि वाले घोड़ेयांको बहुत गुणकार कही है इति हर
कटु पिंडिका है। मघां मरिच सुंठ जीरा सैंधा लूण हंदण
दाणे दोनउ सौंचल लूण चित्रा हरड़ल हाल हलदी कानूआ
भंगी गी सहांजणा वनतलसी इनांको हणीकार गोमूत्र सा
थ पिंडी बनाकर के प्रातकाल मै घोड़ेयांको देवे अथवा मदि
साथ देवल पार करदी है अरु को हृदय हृदय के क्रिमीयां

शीतवातार्दितानां च मंदाग्नीनां च वाजिनां १२
हरेत्कटुपिंडिका: ओषजीरक सिंधूत्थ दंति
सौवर्चलानिलैः हरिद्राद्वय पूतीक भार्गी पि
गुरु कंठरकैः १४ गोमूत्र पिष्ट पिंड च प्रातर्वाजि
षु दापयेत् अथवा सुरया सार्द्धं हृदिपलं च वि
वर्जनः १५ कायाग्निदीपयमाशु क्रिमिकोष्ठ
विनाशनं गलग्रहे श्लेष्मकासे तु रंगस्य प्रदाप
येत् १६ ओषाद्यपिंडः। ओषानिंबहरिद्रा च
गुडूची कटुका वचा गोमूत्रेण समायुक्तं श्लेष्म
घ्न पिंड उत्तमे कटुपिंड कटुकत्रय कुष्ठ त्रि
फलागजपिप्पली पिप्पलीमूल सुना
वनं ते वृत्यान्नयवा सवचा कुष्ठ टंकण सफला।
नितंब्याति विषा १८ चित्रमे दमजाम्स पर्पट
के कुष्ठं तत्तगुणे च निशे द्वे अजमोद समदन्ता।
धानेन वनी सुरदारु पटोल यमानि शटी १९

कौं नाश करे है गला का रुकणा श्लेष्म खंग इनां रोगां विषे घो
ड़े को दुआवे ओषाद्य पिंडी। मघां मरिच सुंठ निंब कड़ेआरी
करे आरा गलो कौर बचे इनांको गोमूत्र साथ पिंडी बना के देवे
सो श्लेष्म के नाश करणे को बहुत गुणकार है इति कटुपिंडी।
त्रिगुटा मघां मरिच सुंठ कुठ त्रिफली हरीड़ बहेड़े आमले ग
न पिप्पल पिप्पलामूल मुस्थर तिमरु वीण नउआहा वर्व
हेद्य जो अनीस निंब जीरा पापड़ा को गड़ के छिल्ह मेव के
हरड़ल हाल हरदल चित्रा त्वाण ह्दण दाणे को मेड़ मेनव
ल देवदार प्रवर पत्र वलन्वाण कचूर।

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा० गायमाण वनगसा वायवडिंग मोरयां पलाजडी सहांज
ह्लो० ना मोठेया हिंग मेढाश्रृंगी कौड भडिंगी सैंधा लूण इनां
१०१ का पहेचूर्णमखीर वा आसव मदिराभेद तिनांकोसाथ।
मलकरकेदेवे तो वायु कफको नाशकरताहै अरुरुचिकर
है अरुवातरक्तकेरोग कउ सोजा इनकोहरताहै अरु दे
हकी अग्निकोप्रकाशकरता है अरुचूनकेसाथदीयाहूआ
अर्शकेरोगकोनाशकरता है अरुबुद्धिमानवैद्य घोडेको
एवं रुधिरनिकासके पीछेदेवे अरुपहेचूर्णसेंधालून
हिंग वारुणि मदिराकेके सहित शूलकीपीडाकानाश।

101

त्रायंतीचविडंगमर्षपत्रुनापाठावशोभांजना
म्बुवारामठहस्तिकालिकुडकाभार्गीतथासै
धवं पतद्धानकफापहेरुचिकरंमधासवालो
डितं चूर्णमारुतशोणितामयहरंकायाग्नि
संदीपनं २० कटुशोथहरं चूर्णेनसहितंअर्श
र्शनिनाशनं वाजिभ्यःखलुदापयेन्नमतिमा
न्वक्तवाशिरामोक्षणं पतत्सैंधवहिंगुवारु
णियुतंशूलार्तिनिर्नाशनं: अथानाकटुचूर्ण
मित्यभिहितं सर्वामयघ्नंपरं २१ कटुचूर्णम
तीसारमरयासैंधवेनच अर्शकेदेचूतसंयुक्तं
शूलवारुणिसंयुतं २२ कफप्रायेषु रोगेषु
खरोगेषु वानिनां सिंहणकेषुसर्वेषुक्रिमि
कोष्ठगलग्रहे गोमूत्रेण समायुक्तं कटुचूर्णप्र
दापयेत् निंबकाथसमायुक्तं मंदाग्नीनाप्रश
स्यते २४ द्विचत्वारिंशत्कटुचूर्णम्

करताहै पहेकटुचूर्ण घोडेयांकोबहुतहितकरताहै अरु
सभरोगांकेनाशकरणेकोसमर्थहै २१ यहकटुचूर्ण अती
सारविषे मदिरा अरुसेंधालूणसाथदेवे अर्शकेरोगामें घृ
तसाथ शूलरोगविषे वारुणीमदकरकेदेवे २२ कफके
रोगोंविषे मुखरोगोंमें नासाकेसीड पीनस इत्यादिरोगों
विषे कोष्ठकेविषे कृमीरोगमें गलकेरोग विषे पहेचूर्ण
गोमूत्रसाथदेवे अरुमंदाग्निवालेयाको निंबकेकाथसाथ
अच्छागुणकरकेदेयाहै २४ इतिद्वाचत्वारिंशत्कटुचूर्णम्।

© Dharmartha Trust J&K. Digitized by eGangotri

इसहि चूर्णके कै लवणपिंडी करे कटुचूर्णका इक
हेसा दोहेससैंधवलूणके २५ असन्नामहिराकाभेद
तिसकेसाथ मिलायके कराही विचपायके अग्निऊ
परचढायदेवे यवपकणलगे तबघोउतेलमठाइमा
दि इवपायदेवे २६ जबचणाहोनेलगे पिंडीवटनेवा
लानाहिवे तोउतारलेवे केरसनेओंका इकहेसापा
यकरके लवणपिंडीकरे २७ यहेपिंडीघोडेयोंको
अन्नवा घासमधकरके त्रयदिनपिछेवा चौथेदिन

पतैनैवतुचूर्णेनकुर्याल्लवणपिंडिकां
भागंकटुकचूर्णस्य द्वौभागौसैंधवस्यच २५
असन्नयाभिसंयोज्यकटाहेसमधिश्रयेत्
पच्यमानेहुतेतैलंदध्यादीनिचदापयेत्
श्रपिंडिकरणासिद्धमथैनमवतारयेत् स
कृन्तोयचभागेनकुर्याल्लवणपिंडिका २७
इदन्तुदद्यादश्वानांमहावनरहादपि अश्वे
ह्वराद्भिःपानेमधासवविवर्जितैः २८
उदराणिचसर्वाणिगुल्मंमंदाग्निनाशकं
मारुतंकफसंसृष्टंग्रहणीरोगमेवच २९
वाजिनांशमयत्येषाश्रेष्ठालवणपिंडिका १०
लवणपिंडिका। सिंहस्यपञ्चमूलस्यभा
निमुंजेदेयंहयानांसरयाचपिंड प्रयो
तमेनतत्वलपिंडइदन्त्वासवानसकलेसपि
ड ११ मिश्रपिंड। अपानाकसंतवमूलप
शाणिचसमुद्धरेत् ।

विधिदेवे अरुयोमधा
सवहैइनोकोनादेवे २८ यहेपिंडीघोडेयांकोसभउ
दरविकार गोला मंदाग्नि औरवायुकफ मिलाहु
आ संग्रहणी इनाकोंशमकरतीहै यहेघोडेयोंको
बहुतश्रेष्ठगुणकरतीहै ३. इतिलवणपिंडिका।
सैंधालूण हरीड होयतुल्यभाग इनाकीपिंडी सराव
साथ घोडेयांकोदेणीयोगहै यहेप्रसिद्ध है घोडेयोंके
सभप्रकारकेवायुरोगोंकोनाशकरकहिहै ११ मिश्र
पिंड। तरकेमिकउ मूलपरलेवे अग्निमंथ।

© Dharmartha Trust J&K. Digitized by eGangotri

पा॰ टेंटारण पाटल ब्राह्मी वासा सालवृक्ष कैंथ करीर
ह्री॰ इनांकेपत्रलेवे पीलू भातुरा एलवालु इत्यादिइनो
१०२ को उखलविषें कूटकरके चूर्णवनाके अरुकटुक
चूर्णका अरु इसचूर्णकादोनोका एकएकसौसौ
102 पलसाढेवारासेर दोनो पंजी सेर अरुलूण तिसके
वरावर पायकरके गोमूत्रसाथ काढे १५ इतनाके
पात्रविषें अथवा तामेका कंसेकेपात्रमें पायकरके
मठेथे आदिलेकर एहद्रव्य इसविषें देणेयोग्यहै ट

अग्निमंथस्यपाटल्यायवासस्यतथैवच १ २
आटरूषस्यपत्राणितथाश्वत्थकपित्थयोः
करवीरस्यपत्राणिपीलुमर्कैलवालुका ११
कल्पयित्वेवमादीनिहरीणिकृत्वाघुलूख
ले ततःकटुकचूर्णस्यचूर्णस्यतस्यचोभयो :
एकैकस्यशतंकुर्याद्दद्यात्पलशतंद्वयं त
त्तुल्यंचलवणंगवांमूत्रेणपीवयेत् १५
स्रणमैयवापितामेवाभांडेकांस्यायसेपि
वा दध्यादीनत्रदेयानिदशमूलरसंतथा
तारांश्चोक्ताकषायाश्चवातिकोत्तरवाति।
काः स्नुहीतिलयवार्काणांलवणानिव
सानिच १७ नाल्युग्याहरीणितान्सर्वान्सम
कृत्वापरिस्रुतान् मूत्राणिवाप्यजीवीनां
स्थितमानेप्रदापयेत् १८ द्रव्याणांसम
भागानांतेषांदद्यात्तुलात्रयं भांडेतत्रैव।
निःक्षिप्यमसियानेपचेत्शनैः १५

शमूलकारस सोकरदेनेहां विलणा अग्निमेथ टांटर पा
टल कमीर स्याकरनी टेंथर केडयारी कडेयारा वखेड
इनाकारस १६ ओरतार ओरकहेयाकाथहै मेदाश्रृंगी
हसरी मेषश्रृंगी ओर थोर तिल यउ आक इनोका ना
रलूण ओर मिका १७ तिनोकोभस्मकरके महीनचूर्ण
सभनोको वनायेहोको सतवारीपूणके वकरीयाओ
रभेडोकामूत्र सिद्धहोनेकेविषे पायदेवे १८ तिनोस
मनाद्रव्योकेतुल्यभागके साडेसततीसेर एकभा

© Dharmartha Trust J&K. Digitized by eGangotri

उविषैधायके ऊपर सेंककके होलि होलि अग्निलाय
करकेपकावे जव औषधीयां हच्छीतरां मिलजावे फे
र अग्नि कों हच्छितराजगावे यव उसमें लारो ग्रहण मना
निकसे नोदृग्ध होयानिश्चय करे ४· सोछेतरंगका श्र
हमहीनचूर्णकरके संदरस्थानविषैं हच्छीतरांरखरके
रखे पहेवनेलवण मदिराकेसाथ अन्नकेसाथ अग्नि
करके अथवा जलसाथ उआवे ४। सो गोला कवजी
हकजाना मलका उदरदोष वधजाना पेटकाकोष्ठ।

औषधं पुनरिमं स्विन्नं तथा प्रज्वलितं भवेत् गता
विस्रावि स्मवह्नयमिमं धारयेत् ४· शीत
हरिंी कृते श्लक्ष्णं स्नि निग्धमेनि धारयेत् ४६।
वैवनेलवणं स्त्र यास मद्दापयेत् ४। अन्ने
नाम्लेन वासाह्ने मुदकेनाथवापुनः गुल्मवि
वधमुदरं हृम्मी न्कोष्ठसमास्त्रिनान् ४२ मंदा
ग्निवमथो हंतें श्लेष्म कोष्ठगलग्रहं सर्वकूट
गता त्रोगान्स्मात्सर्वां स्त्रवाजिनो ४३ वन्नै
लवणः। अजमोदामजाजश्चयानकेदीप्य
कानिच वचायुवानीनिर्गुडिनंत्रकणितथै।
वच ४४ उष्णवीर्याणि कृत्ताणि विपाकेकटु।
कानिच अग्निसंवर्द्धनान्याहुरेतानिरूशला
जना: ४५ उद्भभागानिभूयिष्ठसगंधिकटु
कानिच रुचिप्रदानिवाध्मानावातश्लेष्महरा
णिच ४८ इतिसगंधिकटुहरणः ।

विषैंक्रिम मंदाग्नि उदावर्त उलटीगतीहोनी मलमू
त्रादिकौंकी श्लेष्म अफरकजाना हृदयका औरगलका
औरसुरव अफगलकेरोगसमग्धोउयोंके तिनोंकानाश।
करता है इति वन्नैलवणः अजमोद जीराकाला धनीयां
विजा वचे वहान्नाण वनातिमरू पहेद्वयवीर्य विषैंग
में हैं रूक्षपाकविषैं कौरे अग्निकोवधानेवाले वतावे
धरनेकोंकहतेहैन ४२ अफजहैभागविषैंभारेहैं श्र
रूचेरगंधिवाले अरुकौरे हैं अफरोरेयांकोंरुचिवधानेहैं

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ वायुश्लेष्मको हरनेवाला है इति सुगंधिकट्वरणं । यको
हो॰ बेर कुलत्थ इन तीनोंके एकसेर ग्रह दशमूलके सेर उ
१०३ ईइनासबनाको अठसेर जलविषे पकावे यव चारसेर
103 बाकी रहे तो छाणकरके फेर अग्निके ऊपर चढादेवे
और सौ पल जलके समीप रहणेवाले जीवोंका मासको
काढ ४८ और जांगल मृगपक्षीयोंके मासको महीन
करके इतना ही काढ ग्रहतिसक्काथको दोसेर मठ साथ
मिलाकरके पकावे और मघा मरिच सोंठ अठतोले ग्रहरू

यवकोलकुलत्थानां त्रयस्य कुडवाद्वयेच मू
लस्य विंशतिपलं तत्द्विपचेद्विराढके वारिस
वे ४० अष्टौ विशेषमेतद्धि आमष्टनरथित्र
येदग्नौ तत्क्काथे विपचेत्पलशतं मांसस्या ध
जांगलमथ वारि पचेत्सा एव ततस्तन्ता कल्पि
तेतत्तत्तैव विपचेत्क्काथ्यद भाग्रश्थेन समुते
द्विपले त्रिकटु द्विपले पिप्पलं च चूर्णयेतेन त
त्रैव महास्नेहदद्यादयमिश्रिकेवापि ५० अव
चूर्णयेत्त्रयः कर्षस्त्रिभिः सुगंधिकट्वाना
पतेत वातिकान्वैय वोदनं भोजमेद्यान ५१
वातविकारविनाशनं भोजनमेतत्प्रशस्तम
स्थानां इहतेत्रैदशमूलानि वातिकानीनिकी
र्तितानि तथैः ५२ एतान्पुनर्वातिकसंज्ञानि
भिषग्विजानीयात् कारमर्यमुष्ककमूलाककं
पित्थवरुणानि बिल्वपत्राणि ५३

णसैंधा अठतोले चूर्णपायकरके फेर तिसमें महास्नेह सभ
सेर वृततेलमिक वर्षी मिलायके फेर मिश्रकरे ३यतोले
सुगंधिकटु स्नान जीरा बील चित्रा वर्च बलछ्राण वण
तिमरु पाइकरके मिश्रकरे इकसाथ वासकरणत् ओरे
है तिनाकीयवोके काटेका भत देवे ५१ यहभोजनमंडल
णवायुके विकारोंके नाश करनेवाला है बहुत श्रेष्ठ गण
करहे ओउयोके तत्रशास्त्रविषे दशमूलवातिकनामकरा
के होहै इहीवानोंकरके ५२ और एहेयोकहनेहेन सोउन्तर

© Dharmartha Trust J&K. Digitized by eGangotri

वातिकनामवैद्यजाने वासीर मूली सकी होई कैण वे
र विलणकेपत्र ५३ अग्निमंथ शणचेउ इटसिट दोनो
छेतरकलालभेद गलो विहु यंग कलत्था पान मसरा
वाउल कनक ५४ मिठासूंभोजनना मंहा छोले पहेसथि
योनेकहेहैन और येहमतंराकेयो होर अन्न हैन अथवा
तिनोंको बुद्धिमानैद्य उत्तरवातिक जाने सभनाको ५५
इसको आस्थानवस्तिपञ्चकारीविषे और स्नेहकल्पते
हविधिविषेयोर ५६ इसकारकेसभवायकेरोगगोउ

नक्तीरीशणवीजशुनर्नवेदेवदारुचीव वि
ल्वयवान्कुलत्थान्ब्रीहिमसूरांश्चशालीगो
धूमान् ५७ मधुशिग्रुमाषवणकान्अथि
णाश्रीकान्यथैतानि यद्वासकिमपिभवे
दीदृग्विधमेवयात्संवा ५८ तद्धीमान्जानी
याभिषगुत्तरवातिकंसर्वं आस्थापनेनु
नेवैद्यः स्नेहकल्पेषुयोजयेत् ५९ अनेनस
र्वेनसंपतिवातरोगाइयोस्थितः उत्तरवाति
कनाम त्रुन विडत्रिफलाविडंगानिसौवर्च
लनागरंसैंधवं हिंगुभार्गीकणामूलपा
ठाचित्रकच्छित्रकंसर्षपः ६० भल्लातकश्चव
च्यकर्णीलाजेकंमधुकमरिचयवानीयवा
त्तारुशोभाजनंरेणुकाविल्वपत्रीकंकिणवे
कलिंगानिवर्षाभूयुतानिसर्वाणि वैक
त्रचूर्णयेद्विपलन्तलितमात्रयादायगोमूत्र·

केसरहोतेहैन ५७ इतिउत्तरवातिकनाम । मुण्टर
विडलूण हरीड़ बहेड़े आमले वायविडंग सौंचल
लूण सउ सैंधवलूण हिंग भडिंगी पिप्पलामूल व
टलवेल चिवी विडा सरियां ५८ दियार अफल कको
इण मधो लाजीयां वृणतलसी मुलठी मरच ज्वाण
यउखार सहांजना रेउट विल्व करंज तिलखेल इंद
नव इटसिट इनोंको दोदोपल समभागकठेकरके
चूर्णकरके अरुगोमूत्रमात्थपिंनी दोपल अठनोले
देवे नोयहेपिनी मंदाग्नि कृमिरोग आमवात ।

© Dharmartha Trust J&K. Digitized by eGangotri

शा० हो० १०४ निद्राकेरोग बालकुविकार ५६ सभप्रकारकेमुख
रोग अरुमुखके सभरोग और गलके संपूर्णविकार सि
हाणा नासाकेरोग सिरकेरोग सोजा अतीसार गोला
अजीर्णशूल इनांको मरिचेकेसाथ सदाही इनारोगांको
नाशकरताहै इतिहाविशालकटुपिंडिका। अवचूर्णलि
खकहतेहैं सोचोडेयांकोसदाहीहितकरहै और सभव्या
धिके शामकरणेवाला है अरुवधनअग्निके प्रकाशकरा
है ६२ हरीड बहेडे आमले सुंठ जीरा मोटाजीरा जीरी

शकाविंयंपिंडिकाबाजिनोदीयमानानि
हंत्याशुमंदाग्निनांहमष्मवातंकनिद्राश
याबालकान् ५६ सकलान्मुखगतान्रु
गामयान्कठरोगानशेषांश्चसिंहाणका
कासशोथानतीसारगुल्मामजीर्णंच
शूलंचहन्यात्स्वरासगुनासवेदा ६० हावि
शालकटुपिंडिका। चूर्णलिख्यतेस्वामिन
रगाणांहितंसदा सर्वव्याधिप्रशमनंप
रंवाग्निप्रदीपनं ६१ त्रिफलाशृंगवेरंचजी
रकंचोपकंचिकां पिप्पलीपिप्पलीमूलंम
रिचंचाम्लवेतसं ६२ दाडिमंतिंतिडीकंचस
हितंकरणीरिणी अजमोदाश्वगंधाचयवानी
गौरसर्षपः ६३ पटोलपित्रमेदश्चत्रिवृन्मुस्त
सपर्पटं सैंधवंकृष्णलवणंसामुद्रंकृत्रिमंवि
डं ६४ पंचलवणसमभागश्च्चूर्णंतुकार
येत् ततःपातसमुत्थायवातरोगसमन्विते ९९

मद्यं पिप्पलामूल मरिच अम्लवेतस ६२ नारदा
ण तेतरी कौड न्याण असगंध वलज्ञाण सेतीस
रियं ६४ पवलपत्र भिंव त्रवी मुत्यर पापडा सेंधा
लूण कालालूण समुद्रलूण साभरलूण विडलूण
६५ एहसभद्रव्यकिडेकाके महीनचूर्णकरावे इस
कात्रिकूहनिकालके वायुरोगवाले और इसका
चूर्ण घृतकेसाथपीनेयोग्यहै अग्निकोप्रकाशकारै

© Dharmartha Trust J&K. Digitized by eGangotri

अरु देहको स्निग्ध चिकनाई करै है अरु पित्तके सभरोगां
विषे मवीर और खंडके साथ देवे और श्लेष्मके रोगां विषे
मदिराके साथ दुआवे ९७ कांजीकरके देणेसे सूल और
अनाह सभभागे वद्धहोजाने तिनको हरनेवाला कहा है
अरु मदिरा मासरसके देणेकरके घोडेयोंके वलको वधाता
है ९८ येह इना मिले तो गर्मपाणी साथ देणा अरु घोडे
के हित प्रीतिवालेने पहेनिसदिन सावधान होके करणा ९९
इति चूर्णाहिंगम् अथ मधो मिरच सोंठ दिग्मार प्रियंगू वा

हृतेन सहयातवेच्चूर्णं स्तेह्नेन दीपनं पेति
केश्व सर्वेश्च मश्वशाकेरयाश्रुने श्लेष्मिकेश्चपि
रोगेश्चमधेन सहदापयेत् ९७ कांजिकेन स
मायुके शूलानाहहरं स्मृतं मद्यमांसरसेश्चैके
हयानां वलवर्द्धने ९८ एतेषामथ भावेन द
द्यादुष्णोदकेन च नित्यं सन्निहितैःकार्यं हयानां
हितमिच्छता ९९ इति चूर्णाहिंगम् अथ अ
षणादेवदारुफलिनीरास्नाविडंगाग्निभिःसै
न्धवकृष्णाहबानरिधनैः पाम्पाकशक्रडु
मेः हिंगुश्रीफलमोचकद्रवशटीसिंधुत्थव
कान्वितैः स्रावःक्षयनरोःकफद्वयनिशापिंड
त्वगेलान्वितैः १० सर्वेल्तिमहरोपिशीति सम
ने सर्वामयघ्नं परं मन्यालभगंदादितेच सा
नं तं देयं मृगश्चामिते पकांगे हनुग्रीवा
हु शिरसि स्कंधे तथा कर्णे केशोपकेवानकपा
मयवमसकृज्जेपिनेचरकान्विते १(

मालकंगुणी रेणुका वायविडंग चित्रा पदली सुआर अ
मलतास कोगड हिंग विल्व मोचरस कचूर सैंधालूण हेर
मा क्षयनक्त काउंट मसूर फेन हरदल दालहरदल दाल
चीनी साबीयां इनको पिश्रीवनाणी १० सभनरोगांकालेप
करना नानाअंगोका तिसको हरता है शिरपीडा सभप्रका
रके रोगको हरकरे है और वाडीकीयां नाडीयाका रुक
जाना लकवा मरवेफिके जाना अरु सरोग भसितरोग
अथवा दोडीके रोगाविषे पिठ भना शिर मोंडे उकणीके

भा० टी० १०५ विषे सोजेमें वात कफ रोगमें पीड पित्त रक्त इनां रोगां वि
षे देने योग्य है ११ अरु यो घ्रीउ राजन्हे तिनांको वीसरूप परा
क्रमकारे है अरु बलवीर्यको बधाता है औरउन्मादरोगविषे
सदा ही हितकारे है अरु घ्रीउ यांको महाबलकारे है इसकार
णते सदा घ्रीउ यांको देने योग्य है १२ अव मृषणादिपिंड कह
ने हैं मघा मर्च सुंठ कूठ वायविडंग यमणी लूण सैंधव अनी
स हरदल कौड किरायता जीरा हिंग कचूर एह सम भाग लेवर
अरु सम भस्म घृतकर के देवे १३ ममाष्टष्टिक इनां काक्त

105

स्वस्थानामपि रूपसत्वजननं वस्यं च वृष्यं स
दा उन्मादे च हितं महाबलकरं देयं ह्ययेभ्यः
सदा: १२ अपिंड। कटुकत्रयकुष्ठविडंगव
लालवणातिविषारजनीकटुका हितिति
वसजीरकहिंगुशटीसमभागमिदंविहितं
तलया १३ ममाष्टष्टिकस्तभ शोफामय
विनाशनं अउरोगहरं चेतत्स्योत्कवातविका
रजित् १४ मृषणादिपिंड: पंचकटुपिंडि
काकल्प: । वातदोषहरीहृष्यादीपनीबल
वर्द्धनी अमापहाहृद्यतमा वहि:शीतगुण
स्मृता १५ अनेकायगता वोस्मा विपाके वा
विदाहिनी कफतंत्रीपिपासाघ्री शोणित
स्यप्रसादिनी १६ कृच्छ्रमूत्रातिसारेषु हिता
वातानुलोमनी यस्मात्प्रदीयते तस्मात्प्रति
पान प्रकीर्तितं ११ कटुजाना अरु सोजेके विका
रकहेया है वायके विकारजीनता है इति मृषणादिपिंडी
पंचकटुपिंडिकाकल्प: अव वाकणिकल्प कहते हैं
वाकणि मदिरा वायरोगहर्ता है अरु वीर्यबलको बधा
वती है थकेमको हरकरती है हृदयकों बहुत प्रिय
करे है अरु बाहिरविषे शीतलगुणकरनेवाली कही
है १५ देहके वीच अनेक रोग्यादाग मेरे अरु पाकविषे अग्नि
होकर पचता है अरु अफाराने त्रषा रक्तका नाशकरे है १६
मूत्रकृच्छ्र मूत्रातिसारविषे गुणकरे है और वायको यथायो
ग्यचलती है जिसकारणते वेशदि है तिसते इसको प्रतिपान
कहया है ११

© Dharmartha Trust J&K. Digitized by eGangotri

अरुकोती ग्रामकोपचादेती है और रोगीयोंकी पीडाकोना
शकरै है एहेवारुणी मदिराद्योउयोंको नाशकरै है अरुसम
रोगाकोहितहै ७८ हेमंत और शिशिर रुत विषे प्रतिपानमें
सुरासव शाली सठीके आटेकरके योसिद्ध है सो सुरा है सो
पथ्यकहा है वर्षामें और वसंत रुत विषे मैरेय अरु आसव
मदिरा भेदगुणकारै है ७९ शरद ग्रीष्ममें पीउनाम मद वि
शेषगुणकारै है देशदेश विषे रुत रुत प्रति रोगरोग प्रा
ति योयिसकारने देइदा है तिसतें सको प्रतिपानकहेया

पाचयुत्या मरुष्टानि रोगिणां वेदनापरः भ्रू
यिष्टं सर्वं भूमस्येभ्रु हितं सर्वव्याधिभ्रवारुणी
हेमंते शिशिरे पथ्या प्रतिपाने सुरा स्मृता
वर्षाकाले वसंते च मैरेयमदिरासवौ ७९
शरन्निदाघयोश्चैव पीधुरेवावशिष्यते प्र
तिदेशमथर्तौ च प्रतिदोषं तथैव च ८०
यानयदीयते तस्मात्प्रतिपानमिति स्मृतं ८
पिप्पल्या मरदारु विश्वलवणैः सैले त्रिते
ग्रैष्मिके शुंठी लोध्रगुडुप्रियंगुमधुकैः कु
ष्टाचिते ग्रैष्मिकं द्राक्षापद्मक जीवनीय
मधुद्राक्षा सितैः शारदं मुस्ता पिप्पली बिल्व
लोध्र फलिनी तो है वसंते हित ८२ सिंधूत्था
ग्निविडंग धान्यकक्णा लोध्रैर्विदं शैशिर पंचै
ते प्रतिपान कर्म विहिता योगाः सुरासंयुताः

है ८१ मञ्जा देवदार सोंठ लूण इनोंको तेलके साथ सि
द्ध वर्षामें हित है सोंठ लोध्र गुड फूलफरंग मुलठी कूठ
इनोंककैं सिद्ध ग्रीष्म रुत विषे गुणकारै है मञ्जा तजपत्र
जीवनीयगण रुषभक माषपर्णी मुद्गपर्णी काकोली क्षी
रकाकोली जीवक रुषभ मेदा महामेदा मुलठी मलीर
मनका वेदनखेत एहे शरदविषें हित है मुथर मञ्जा बिल
लोध्र प्रियंगु मलीरकरके वसंत विषे हितकारै है ८२
सैंधव लूण चित्रा वायविडंग धनीया मञ्जा लोध्र इनोंक
कैं सुराकर शिशिरमें हित है एहे पंचयोग प्रतिपानकर्मविषे
सुराके युक्त कहे हैं ८३

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा॰ प्राव्रट ग्रीष्म शरद वसंत शिशिर इनों ऋतुओंके विषैक्र
हो॰ मकरकेदेवे ओरवोउयोंको योपान शिशिरमे हिमकहेया
१०६ है सोई हेमंतमे योग्यहै ८४ इतिषड्ऋतुप्रतिपाने हरीउ

106

स्याण वचे लूणपंज केआरी मेउ मचो चित्रा हिंग यवक्षार
वटलवेल इनकासममचूर्ण सुरामदिराकेसाथ शूलकेहर
करणेवालाकहेयाहै इतिअभयादिप्रतिपाने। वटणदा
नेकीजउ यवक्षार त्रिवी वायविडंग अशोकहृत्तकेसिकउ
कमीला पंज लूण वचे निंब्रुडीकासिकउ इनकेचूर्णकर

प्राव्रट्ग्रीष्मशरद्वसंतशिशिरेष्वतेष्वयोऽप्याक्रमात् हेमंते प्रतिपानंमित्सभिहिंतं यच्छैशिरवाजिना ८४ षड्ऋतुनां प्रतिपाने अभयावसमान्सनमोदेववालवणानि ठउरालभविषकणा शिखिहिंगुयवाग्रजपाठघनाम्बरं। यासहृच्छूलहराकथिता: इतिअभयादिपाने हंनीत्सारग्रनात्रिवृतक्रिमिरिपुवेत्काम्सशोकस्य च कंपिल्ललवणानिपंचवकवचाम्स्रतिडुकस्यतवा: पिष्टैनाहविवंधनाशनमिदं सौभिन्नवातापहं ८५ देन्याद्यपाने। वकुलासमहोषयमागधिकालवणानिचपंचवचातिविषा मरिचानिचहिंगुवचूर्णमिदं सुरयासहृच्छूलविनाशकरं वकुलादिपाने। नेवहणभयाहिंगुपौष्करलवणाष्टक यवक्षारसमभागकंशूलेहन्यात्रिदोषजं ८६ नेवरादि।

केपानहै सोअनाहवंदहोणा समहासेका कवजी इन
कानाशकरहै और सोभितावर्तकोहरकरहै इतिदंत्या
दिपानम् लावीया मेउ मचो पंचलूण वचे अतीष
मरिचु हिंग इनकाचूर्ण समभाग मदिराकेसाथ पा
यनकीहृदयाशूलकेनाशकरणेवालाहै ८६ इतिब
कुलादिप्रतिपानेशूलरोगे सितरू हरीउ हिंग पुष्क
रमूल पंचलूणअठ पहेयवोकेकाथसाथ देणा।
करके त्रिदोषशूलकोनाशकरनाहै ८७ इतिनेवरादि

© Dharmartha Trust J&K. Digitized by eGangotri

मुस्थर प्रतीस वटलवेल वर्चे हरीड़ कौड़ वनगसा दि
ग्रार पापड़ा ८८ केंड्यारी पिप्पलामूल गलो सड़ पटो
ल करायता इनोकासवरंकाथ सिद्धकरे ग्रष्टाविशेष
देवे पद्केमुस्तादिकाथ मंदाग्निज्वर आलदोष गलरो
ग ह्रोणिका सोजा ग्रामवात वलकेनाशमे ९० ग्रशे
केशोथ इनोसभनेरोगांकोजीतदाहै इतिमुस्तादि
काथ मुस्थर ग्रग्निमंठ डारण निंव प्रवल पत्र वटल
वेल वनगसा पापड़ा कचूर प्रतीस केंड्यारी केंड्या

मुस्तप्रतिविषापाठावत्सावैव हरीतकी
कटुकायमाणांच देवदारुसपर्पटं ८८
दुस्पर्शापिप्पलीमूलं गुडूचीविश्वभेषजं
पटोलीकांडतिक्ताभ्यां कषायसाधयेद्बुधः
मंदाग्नौ सज्वरेचैव आलके गलग्रहे ग्र
णिकाशोथयोरामवाते वलक्षये ९०
मुस्तकायोत्रयं हंति मुस्तादी सर्वरोगजित्
मुस्तादिकाथः। मुस्ताग्निमंथ पिचुमंद
पटोलपाठा त्रायंति पर्पटशटीसविषा
ह्वया वासामृता खदिरशिग्रुफलत्रया।
णां कार्थयतो मधुकविश्वकिरातत्तिक्तैः ९२
पीतंजयेत्रुधिरपित्तकफानिलोत्थान्
शोफांश्च हंति सकलज्वरकोटराजीः पक्वा
नविद्रधिगलग्रहपुंडरीककेपावर्त्तकावि
धुरग्रहगंडमाला ९१ गलास्य। विड़गानि
हरिद्रेद्वेसेंधवंविड्मेवच।

रा वासा गलो खेर सहांजना हरीड़ वहेड़े ग्रामले
मुलठ सड़ किरायता इनोबारके सिद्धकाथपीना
होया रक्तपित्तकफवातकरकेयोसोजे हैं ज्वरसभ
प्रकारके कोटविषेरोंको ग्रर्धंग ग्रापि गलह
कन्नाना पुंडरीक रुहमेद कंपवात कर्णकाशाहरो
धगंडमाला हजीरी इनोसभनांकोहरकरनाहै १
निमुस्तादि २ गर्भसूरुत। वायविडंग हरदल दो

भा॰ क्रि॰ ९७ लहरदल सैंधालूण विडलूण वटलवेल पटोलपत्र
निंवपत्र ९४ मद्या सेंउ इनोंकासमचूर्णकरे पहिलेद्रो
ग कोठके कृमियोंके रोगविषेदेवे अरुअग्निकोप्रका
शकरहै आमकोपचादेताहै ९२ अरु सुरा मदिराकेसा
107 थखानेतें कृमियोंकानाशकरहै इतिवडिंगादिचूर्णम्
तिपाने वावडिंग पतीस वटलवेल कोउ इंद्रयवे वचै ९५
मद्यो पिप्पलामूल मरिच गजपिप्पल वनगसो हरीड
ववक खाण जीरेदोनो ९१ वहुखान हरदल दालहर

पाठापटोलपत्राणिनिंवपत्रंसचित्रकं ९४
पिप्पलीशृंगवेरंचचूर्णमेकत्रकारयेत् ए
द्रोगेकृमिकोष्ठेचदीपनंचैवपाचनं ९२ स
र्याचसमायुक्तंकृमीणांनाशनंपरं विडं
गानिविषापाठाकटुकेंद्रयवावचा ९८ पि
प्पलीपिप्पलीमूलंमरिचंगजपिप्पली चा
यमाणशिवावक्षुनवानीजीरकेंद्वये ९२
अजमोदाहरिद्रेद्वेशृंगवेरसचित्रकं अेष
पुष्करमूलंचपंचभिर्लवणैःसह ९८ हिं
गुनालोरुदानंचसुरयाशीधुनापिवा ९९
आमेग्रनीर्णैस्त्ववातजीर्णेऊरुस्तातरेव
स्तपीडनेच सप्तस्मकोष्टकृमिकोष्टवा
धेचाग्रोहितंपानमिदंप्रशस्तं ९ः गुर्गान।
गास्नाविषाविडंगानिदेवदारुपुनर्नवाभा
र्गीपुष्करमूलंचशतपुष्पाहरीतकी १

दल सेंउ चित्रा कठ पुष्करमूल लूणपंज हिंग इसचूर्णको
सुरा मदिरा वा पीयमदिराभरमाध्यमलकरकेदेणेयोग्य
है आमविषे अजीर्णविषे वायकके अजीर्णमें ऊरुकी के
वीचदरदकरके सोरीयोंकापीडविषे श्लेष्मसथानकोष्ठमें
पीड गरके कृमियों करके कोष्ठस्थानविषेपीडा मदाग्निविषे
पहेविडंगादिपान इनोरोगोंकेहरनेवास्तेहितकहेपाहै ९ः
इतिवडिंगादिपानम् गर्गान। रेसण सेंउ वावडिंग
देवदार इटसिट भर्डिगी पुष्करमूल सोंफ हरीड १

© Dharmartha Trust J&K. Digitized by eGangotri

गलो कालीवेल ऊंठ पद्मकाष्ट चिपारा पिपलामूल मरि
च मुथर मजीठ कौलगैड़े मुलठी चित्रा वटवेल मद्या ज्वाहा
गलोट प्रतीस इ इसाक वेदा रूण १ प्रगलकीजड़ बीड़ शता
वर वासा पहेचूर्णागुगुलकेसाथ अथवाछकइनारोगाविषे
देवे ४ सभप्रकारके वायुकेरोग गलकीनाडी ग्रलष्टकेदा
घोविषे पकांगरा विकारमे मंदाग्नि सोज वातवलास प्रकंट
औरमासकस्पाहोवे औरत्रिकका ग्रहरोगीका रुकजाना ग्रथ
रेग वत्तोमारोजाएगी ऊंबहोजाएगा औरवामनछोटेहोजा

गुडूचीशारिवाऊर्ध्वपद्मकंदृढदारुकं ग्रंथि
कंमरिचंमल्लमंजिष्ठापुंडरीयकं २ यष्ट्याह्व
चित्रकंपाठापिप्पलीमडवालभा मूर्वांचा
तिविषावचाजीवंतीहस्तलग्निका ३ पौष्कर
लेसरलंशतावर्याटरूषकौ एतद्गुग्गुलसं
युक्तंकेवलंवापिदापयेत् ४ सर्ववातविका
रेषुमन्याहृष्टेोपतानिके पक्काशगेवह्निसादेच
शोफेवातवलासके ५ प्रस्कंदेछिन्नमांसेच
त्रिकस्तंभेहनुग्रहे एकपक्षहतेपाथेकुब्जके
वामनेक्षय्य ६ उरुकर्णकेमहावातेसामेसा
ध्यास्थिमज्जगे आमेङगेरसंस्कंदेवातशोथेत
थैवच ७ रक्तोद्वेवृवातोद्वेपक्षाद्देवविशे
षतः दापयेन्मतिमान्वेद्योमहारास्नादिकंशु
भे ८ महारास्नादिपाचनम् रास्नाविश्वावि
डंगानिजीवंतिहस्तलग्निका ।

एण ६ उरुककर्णीक महावात आमवात औरसंधिजोड़ रह
डीयां मिंजविषे आमआम ग्रहवातके होपते औरप्रेड
रसधातरुकेरविषेगतहोदे ग्रहवायुकेसोफेविषे ७
रक्तग्रड ग्रहवातअंर पुक्षांर इनोरोगाविषे बुद्धिवान
वैद्य पहेशुभ महारास्नादिदेवे ८ इतिमहारास्नादि ।
पाचनम् । रेसण मुड वावृडिंग इ इसाक वेदा इनका
काथ चौथाहिसा रहेकरके छानवातेलकेसाथ पि
लावे ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ स्थूल और रसधातुके शोष होवे तिङ गाणां वा प्रमें चिरकालके यो
हो॰ उके विसर्के दे और सुंगभजे तिषं इनों रोगों देवासें पहेरास्नादि
१०८ पंचक श्रेष्ठ गुणकार कहेयाहै १० इतिरास्नादिपंचकम् अथ है
रडल हाल हलदी मरिच सेंधालूण कनेर मनशिला कासी
धातु नमेदी जउ हरताल कमीला एलडूष पटोल सरेया
मुथर निंब रसौत नीलाथोथा वावडिंग एहेसभवराबरभाग
लेकरके इनोंकेकाथसाथ तेलकाढे गोमूत्रतेलतैं वारगु
णापाये यबधनाहोजावे इनकेसाथतोउतारलेवे इसके

108

स्नेहं पाययेत्काथं च बहुभोगाविशेषितं ९
स्थूले सुष्कऽरसे वृजे दीर्घकाल सुखेऽोषिते स
र्धीनां व्वलने भग्ने रास्नापंचकमिष्यते १० रा
स्नापंचकं। अथ हरिद्रे मरिचं सैंधवं करवी
रकं मनःशिलातकाशीशं विशाला नटम
ऊनं ॥ कंपिल्लकं सजैरसं पटोलं सर्षपाघने
निंबं रसांजनं तुत्थं विडंगं च समांसकैः ११
पत्तैलं विपक्कं स्याद्द्यात्मूत्रचतुर्गुणं घनी
भूते नवैतेन कषायेन प्रदापयेत् १२ हन्यात्
दुच पामां च कुष्टं च वृषार्षिकं विचर्चिकां।
न पश्याः श्वित्र सत्कृ लेपेन वाजिनां १३ अष्टाद
शानां कुष्ठानां लेपनिद्राशानिर्ययात् कुष्टाघने
ल। रास्नाविसरसं गुनने वा वरूणकं कुष्टसाम्य
गधावला कुष्टमोंदृतकं किरातकं बवा प्रगी
यवानी विषा गधेला मृत्वर दारु पुणाव निगु
नेक्काथ्यं च पीतं रहा।

लेपकारणके कै दही केउ कोउ
बहूतेवैरका चेवलस्थिर कुष्ट मोटे घांकेनाशहोतेहैं १३
एहेलेप अठारांतराके कुष्टको नाशकरनेको इंद्रके वा
त्रके समहै १४ अथ रास्नादितेलम् रसण संर इस्मिट वारु
ण मची अमगंध मणी कुष्ट भगनेरु किरायता वचे ककडु
श्रृंगी ज्वाण पनीस कचूर लाचीया देवदार इनोंकास
मभाग काथवनायके पीलिकरके सोजेको अरुनवा
विषलहूपयाहोवे यहजानी में सोजहोवे।

© Dharmartha Trust J&K. Digitized by eGangotri

लं

तोसिताबीवलककेंनाशकरदेताहै १६ औरघोडेयां
को आगंतुकिसिककारणकरकेहोवे सोजग्रहनिग्रहहो
वे औरकामककरपीडाहोवे इनकेहटानेवास्ते पहेरास्नादि
क्वाथ घोडेयोंकेहितकरकेकहेयाहै १७ रास्नादिवनदे
शकाथ रास्ना भक्तडे विदार गंला ३ इसाक लाखकचूर
र प्रतीस वावडिंग वटवेल परवलपत्र वाला मजीठ पर
णजड इटसिर गजपिप्पल कडेआरी कडेआरा कालीवे
ल इनकाक्वाथ वानको ग्रहत्रिदोषको शमन करताहै

क्षेपयेत्कृपाणिनासपत्निंनयुक्तंवनाश
येत् १६ वाजिनांशोथमागंतुंतद्वाकामाति
मेवच क्वाथोरास्नादिकःप्रोक्तोहयानांहित
काम्यया १७ रास्नावृत्तदेशः रास्नागोक्षुरक
देवदारुरमृतानीवनिलानाशटी संठी
वाति विषाविडंगसहितापाठापटोलंगलू
च्यामेदेद्रभुननेवागजकणात्वहावसिंही
कणा वेनहातहरंत्रिदोषशमनंवन्हेःप
दीपनं १८ रास्नाविश्वविडंगानिशाविवाव
हेमानकं मीवंतिकावलानावदेवदारु
पुनर्नवा १९ काशशनावरीमूलंरास्नाद्वा
दशउच्यते ग्रसक्वाथप्रदानयोदशमूलेन
योजितः २० एलाद्वैपिप्पलीचूर्णक्वाथेन
प्रदापयेत् सर्वशूलभहरोयोगःसर्वलिंगिन
नाशनः २१

औरअग्निवृद्धनप्रकारकरताहै १८ इति
द्वितीयरास्नादि रेणुका सुंठ वावडिंग कालीवेल पर
ण पालकभेद लाख देवदारु इटसिर १९ काहि शाना
वर पिप्पलामूल यहेरास्नाद्वादशककहेयाहै इनकाक्वा
थ दशमूलकेसाथमिलाकेदेना सोदशमूल बिल्ल
अग्निमंथ रुखगाडीला टोटर पाटल कसीर श्रृकनी दे
धार कडेआरी कडेआरा भक्तडेपहेहैं अग्नमृगंदीलोले ति
सकाथमेंपायकेपिलावे तोसभप्रकारकेसूलभंजहुडा
होना अगोंका औरसभप्रकारकेलिंगिलघोडेयांकारो
गहनकानाशकरतोवास्ताहै २१

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰
टी॰
१०९

109

रास्नादिक्वाथ रैसणा गलो परणा वावडिंग सुंठ भंडी
गी भत्तडे देवदार विधारा दादर अरडगंध सोए अमलता
स कंडे आरी कडेआरा २२ इनकापकेक्वाथ वातविकार
में अंगभंजा होवे कोष्टविषे कृमरोगवालेयांको ऊवेवा
मणोहोजाणा अरुत्विमकेविषे दम देरावालेको गेरवा
लतेयाहूषणावालक पीडवालेयोडेयोके रोगांकोहूर
ताहै २२ इतिरास्नादिक्वाथ २३ सिर संठ दिआर छोतर २३
सिर रैसणा भत्तडे लवगडीला धमणी २४ अदक सा

रास्नामृतैरंडविडंगसुंठीभार्गीसदेवद्रुमर
दारुकृष्णा शेफालिनागगंधाशनपुष्पनेत्रसार
ग्वधंचवाहूहन्तीहंचंच २२ वातभग्नकृमिको
ष्ठेरोगिणांऊरुज्ञावामनतयाडवालिना
श्वासकासविकृतंतगामिनांक्वाथएष
जयतीहवाजिना २३ पुनर्नवाशृंगवेरदे
वदारुपुनर्नवा रास्नागोक्षुरकंचैव अग्नि
मंथबलातथा २४ शृंगवेरयवानीचपिप्प
लीजरणावचा एतानिसमभागानिक्वाथ
यित्वाप्रदापयेत् २५ वातिकेपैत्तिकेचैवश्लै
ष्मिकेसन्निपातिके आगंतुकेचैवसर्वे
वेशोथेप्रशस्तवति २६ पाचनविधिः पुनि
वकटुकामुठीपथ्यादारुपुनर्नवा शटीसि
ध्नमरामृक्तः पिंडः स्यात्सर्वशोथजित् शोथ
घ्नीव मदिरावाग्निकणापथ्यादारुमस्तह
मोघयम्

न मद्यं जीरा वधें इनांको समभाग करा
वणा इकाथकर्के देवे पते वार योग है अथवा एक
है वात पित्त कफ त्रिदोष आगंतुक इनां के सभ प्र
कारके सोजेकोदूरकरतोहै २६ अथपाचनविधिकह
तेहो त्रिकुटा कौड संठ हरीड दारहलदर इसिट
कचूर सेंधवलूण इनकापिंड पिनी साथ मदिरके
साथदेहो इ सभप्रकारके सोजेयांकोदूरकरनेवा
लीहै २७ शोथघ्नी त्रिवा मद्यो हरीड नारदारा सुंठ

© Dharmartha Trust J&K. Digitized by eGangotri

हिंग सौंचललूण इनका चूर्ण मदिरेके साथ अग्निके प्रका
सकरणेको समर्थ कहेयाहै २८ अग्निदीपन हरीड़ टाटर
सेठ वामा सैंधवलूण इनका चूर्ण मदिरेके साथ देयाहुआ
मंदाग्निको हरताहै २९ हिंग मधा मरिच सेठ वटलवेल
करंजफल मछ वेल पंचलूण वचे कूठ असगंध प्रतीस २
इनको महीन चूर्णकरके मदिरेके साथ देवे सो घोड़ोके रो
गोको हरणेवाला शालिहोत्रने कहेयाहै ३० इति लघुहिं
ग्वादि। हिंग मधा सेठ मचे कूठ पंचलूण रेसन वचे टा

हिंगुसौवर्चलोपेतं चूर्णमग्निकरं परं २८
अभयाकटुकासुंठीवाटरूषकसैंधवैः ३प
युक्तानिमधेन मंदाग्निदीपनं परं अग्निदीप
नं परम् हिंगुत्रिकटुकं पाठाकुरंजफला
नि च लवणानि वचाकुष्ठास्वगंधानि विषा
तथा २९ एतत्सूक्ष्मकृतं चूर्णं सुरयासह
दापयेत् अश्वरोगहरं चैव शालिहोत्रेणभा
षितं ३० लघुहिंग्वादि हिंगुसूक्ष्मकुष्ठपं
चलवणे रास्नावचाहुडुकैः तिक्तोषणैर्वि
षानिशाकृशरलदेवद्रुमासंयुतैः पिंडदा
रुहरिद्रयानियमितं देयं प्रसन्नान्वितं म
श्वानांमरुदर्हयेयुक्तिरकायाग्निसंदीपा
ने ३१ बृहद्धिंग्वादि। हिंगुस्वगंधाकटु
कामैमोदारहनासकेदाडिमसैंधवैश्च ।

हरपाटा कौड़ खस प्रतीस हरदल कौड़ दियार दाल
हरदल इनकी पिन्नी बनायकरके मदिरेके साथ
देणेसे मन्यागलनाड़ीके रोग नष्ट करनेहै और घोड़ेके
देहकी उदरकी अग्निको प्रकाशकरती है ३१ इति
बृहद्धिंग्वादि। हिंग असगंध कौड़ अजमोद तिंतड़ी
नारदाणा सेंधालूण मधा और हिंगके चूर्णकरके
इनके साथ पीना होया समभरले भ प्रकरजाण ।

© Dharmartha Trust J&K. Digitized by eGangotri

धा॰ रोकेयानानादेहका तिसकोंनाशकरताहै औरयहोउेयां
हो॰ कोष्टदेकी अग्निकों जगाताहै १२ इतिहिंग्वादिघृत सिद्ध
११० है सोंटर लूणपंज यवक्षार वंच झेउ धोम विलकथ कैथ
गिरि विल्व रास्ना गलो हिंग मंघा गजपिप्पल दशमूल
विलएा दगरण सेंटर कसीर पाटल दोयकेउ यारी या
सूरकरणी देथर भन्नेउ नारदाणेकारस तेल घोग सि
क तिनउीकारस मठा अम्ल कांजी मदिरा सौवीरकीजी
भ इनांकोरलाकरके अग्निकरके सिद्धकरे पहीवलवट

कणानितंरामठचूर्णयुक्तं स्नेभापहेचाग्नि
करहूयानां १२ हिंग्वाद्यघृतंशालिहोत्रे घृपा
नांकेलवणेर्यवाग्रयवक्षासमेशीरसोनैर्गुते
मध्ये विल्वकपित्थयोश्च हृत्तगुकरास्नाम्रू
ताराममठ पिप्पलीभिःदशमूलदाडिमरसैस्तैल
वत्वापिवेत्मा हृत्वाम्लदधिवाम्लकांजिकस्म
राभुक्तंससौवीरकं १३ सकलमिदमतिल
सिद्धवतीनेशरीरमविकलंकुर्यान् पितेवा
तविकाराम्लमादीन्नाशयत्याशु १४ घृपा
नांकाथवलेल। पुष्करमूलेशुंठीमागधि
कात्रायमाणमंपुमती हंसबहरसोरास्ना
शतावरीएरंडरवर्णी च १५ कृतकाथामूले
विल्वशटीवनर्जरीकृतम् नीरंसलिलसम
विपाचयेत्सर्वमेकत्राग्नि १६

करकेपोडितयोडाहै तिसकोंपीडारहितकरदेताहै
औरपितके वातकेरोगाकों सभस्तंभ ज्वरजाना देह
का इत्यादिकहोरयोरोगहैं तिनांकोसत्ताबीनाशक
रताहै १४ घृपानांकाथवलेल। पुष्करमूल संठ मघा
वनगासा प्लरकाणी केउआरा केउआरी रेमत सताव
र वेरथर १५ दर्भकाडिनकीयांजड़ा विल्व कुचर इ
नांकोकूटकरके उपरऔर पाणी वणवरपायके सभ
नांकोकठेकरके काड १६

© Dharmartha Trust J&K. Digitized by eGangotri

यवडुयवाकीरहे नोगुणकेपीवे पानको पहेछोडेयो
केवायकेनाशकरताहे श्रथपटुडुयमखीरकेसाथपी
नाहोया श्लेष्मकेनाशकरणेकोकहेयाहे १७ इतिगुडूचा
द्यंतीरं वानाच्चविधिः वनगसो पापडा वटलवेल को
ड पटोल पत्र गलोट किरायता नीमदोजड इनांकोकूट
करकै १८ इनांसमभनांको नेमभांडेविचपाणिपाकरके
सारोरातनसेडरखे पहेपीनेकाथ लेडुरलायकरके
देवे १९ पित्तकेरोगविषे दाहा दम नीरणक अभिना

स्ताअपथःशेषंपानेवानापहेन्नरगाणां प
नत्तैोड्रेणगुमकेत्तीरश्लेष्मघ्नमुदिष्ट १७ गु
डूच्यादिक्षीरम् वानच्चविधिः त्रायंतीपर्प
टकोपाठाकटुकपटोलपत्रव मूर्वाकिरा
ततिक्तमृगादिनीचैवसमौष्ट १८ एता
निवेभाडेपानीयेनसहवासयेद्दृत्तनी स
मिश्रशर्करयाकषायमेतत्प्रदातव्य १९
पित्तविकारेदाहेथ्वासेनीराणकेऽभिताप
व ग्रीष्मेशरदिचदद्याच्छ्रांतानां चैववाहा
नां ५० चित्रकेधात्रकेयाङ्गीत्वगेलागुक्ष
रेणी कृष्णामूलहरीतकीद्राक्षाविकट
नीरके धा प्रियंगुवदरीलोध्रनरंगानालि
केसर मधुकंमधुकेसरंश्रृंगीभार्गीसपर्पट ५२
खेडेनद्विगुणकृताश्वनाश्चूर्णनकारयेत्
पनहोसिप्रदातव्यंस्त्रीक्षवापराह्णके ५२

पग्रीष्मरत्नशरदश्त अरथकेहोयेथोडेइनांविषे
देवे ५० चित्रा नोल आमले दालचीनी लाचीया म
घामरिच पुष्करमूल कचूर पिप्पलामूल हरीड मुनका
केउड जीरा ८ा कलफरंग वेरलोधर असगंध नालीसप
च नागकेसर मुहुआ मुलठ सुपार ककडश्रृंगी भाडिंगी
पापडा ५२ इनकोमहीनचूर्णकरावे लेडद्विगुणपा
यकर्के लेइवटणीवनाकरकेदेवे प्रातकालविषे औ
रसनावेलेदेवे ५२

© Dharmartha Trust J&K. Digitized by eGangotri

शा. दाह रक्त रोग क्षैर रोग वमन तृष्णा के सम मूत्रवालियां ह्यो
हो. उयाको पथ्य है और तेज प्रकाश वर्ण बल इनको वधा
१११ ता है पहै त्रिवृतकादि प्रवलेह श्वास और मांसको वधाता
है ४५ शालिहोत्रे त्रिवृतकादि लेह। मुलठी आमले
मक्षा मत्तीर खेड़ महीन पीसकर चाउलेके जलसाथ खा
लोने पित्तके वास्ते श्रेष्ठ है ४६ कणीके फल नाव मुल
ठी मुनका फालसे मिसरी मत्तीर पायके चाउलोके
फलोपसाथ पीते है पित्तके समकारक है है न ४७ इति पि

श्वासकासक्षयाणां च वमिनो रक्तमूत्रिणां
तेजोवर्णकरं पथ्यं मांसानां बलवर्द्धनं ४४
त्रिवृत्काद्यमिदं लेह्यं जीवनीयं च बृंहणं ४५
शालिहोत्रे त्रिवृत्काद्यलेह्यं। मधुकामलके
श्मसौ पिष्ट्वा तंडुलांबुनाथ पा ह्युसामा
भ्रशर्करायां संयुक्ते पित्तसंशमने ४६ का
श्मर्यकोलमधुकद्राक्षामपरूषकासिता
लोद्रं तंदुलधावनयुक्तं पानमिष्टं पित्तसंश
मनं ४७ पित्तघ्नविधिः कटुचूर्णकसंयुक्तं
मूत्रं मंडनं पाचयेत्सगोमूत्रं श्लेष्मघ्नं शोथ
हं प्रयोजयेत्सततं व्रणे ४८ त्रिकटुका
विडंगामिश्रं मधुना: पकं प्रयोजयेत्सोते तो
द्विवृत संयुक्तं नरगाणां श्लेष्मसंशमनं ४९
कटुचूर्णं श्लेष्मपित्तघ्नं समं गोमूत्रं श्लेष्मघ्नं दा
पयेन्नरं गाणां

तत्रविधिः। त्रिकटु मघा मरिच
सूंठ इनके चूर्णसाथ इनको गोमूत्र पायके काढ़े सो
श्लेष्मको अरु सोजेको नाश करै है और व्रणदादायके
उपर लावे ४८ मघा मरिच सूंठ वायविडंग मिलाय
कर्के सिद्धचे उपानवास्ते देवे श्लेष्मरोगवास्ते मत्ती
र और त्रिवी मिलाकर करके देवे चोउयाके कफके पाम
नकरणेवास्ते ४९ कटुचूर्णयोएवं कहेया है सो
श्लेष्मपित्तके नाश करै है और गोमूत्रसाथ चोडके

© Dharmartha Trust J&K. Digitized by eGangotri

श्लेष्मके हरनेवाला देवे और मखीर साथ कंठको शु
द्ध करता है ९० श्लेष्माघ्नविधिः रक्तचंदन मुष्टा कंग
णी वा रक्तफरंग दाल हलदी हरदल कुठ लोधर
धाई देफुल मंजीठ इनोंको सिध्ध मदिरे साथ बहुतर
कविषे अरुरुधिरके विकारमे देवे ९१ रक्तरोग वा
ल ग्रहकृत अथवा रक्तरोगतिका नाश होजाए उस
कोपहप्रतिपान नाश करता है और ख्याती विषे स्थित
ये रोग हैं सभ और योजे विषे सक्थि विषे तिनको हरे।

मधुयुक्तं वा दद्याद्देवं संसृष्टे तेकंठः ९ श्लेष्म
घ्नविधिः लोहितचंदनमुस्तप्रियंगुदारुह
रिद्रनिशामयलोध्रैः धातकीपिप्पलीशीधु
युतैर्मद्यं देयमिदं रुधिरे च तिरक्ते ११ रक्तपवि
नाशनकृत्प्रतिपानं हन्यूरसि स्थितरोगमशे
षं सक्थिगतं त्रिकसक्थिगतं च श्लेष्महरं मधु
नाच विमिश्रं १२ लोहितचंदनादिप्रतिपानं
पिबेन्मद्यं गुडं तैलं विश्वभागयिकाश्चतां प्र
स्थानमानं मद्यया शैतैलस्यकुडवो भवेत् १३
पिप्पलीशृंगवेराभ्यां देयं मष्टपदं भवेत् स
मग्रप्रतिपानेन विधोलवणवर्द्धः १४ स
घः प्राणकरो वसमग्रप्रतिपानके समग्रप्र
तिपानकल्पः । नागालीरीपयस्यावचवपार
वनांग्निच विदारीशालिपिष्टं च पयस्यमधुम
युतं १

ना है मखीर साथ कफको हरता है ५२ इति लो
हितचंदनादिप्रतिपानं । मदिरा गुड तैल सुंठ मघांक
के चूर्ण पावे इस विधिकरके मदिरा सरानामका दोसेर उस
विषे तेल सूपसेर अरुसुंठ मघापहे अठमाहे सा पावे सम
प्रतिपानकी विधि विषे गुड लूण प्रमाणकापावे ५४ यह
समग्रप्रतिपान सताबी प्राणोंको वधावाला है ५५ इति
समग्रप्रतिपानकल्पः । वंशलोचन खीरकाकोली
वचक मालकंगुणी स्थालि और वाउलेदा आटा उथ
मखीरके सहित ५९

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा॰ परेप्राशयभोजनेनिर्बलहोइ केवलदेखियनकरणेवाले
प्रा॰ हैवें तिनांको अहुथनहै और येइ ग्रासविषइषीहोताहै
११२ और योथोडा खाणेवालेहैन तिन्हांको वजनगुणकारहै ५०
येहोइ मदकेपीणेवालेहैं तिनांको मदिरेसाथखुला
वे पिप्पलामूल सेंठ लूणपंज इनांकोशीतकालमें ते
लकेसाथपीणेकारके होड अग्निप्रकाश और बलतेव
णवालाहोताहै बोड पवहुत हरदल केवल उष्करनू
ल समुद्रलूण असगंध वा शाल इनांको इगपकारकेना

प्राशयमेतद्बलाधानं दुर्बलानांसमस्तं येव
प्रतिहताग्रासेहयायमेदुरवादिना ७ अभि
लवतिनेयेवस्वयाभोज्येत्तानान् पिप्पली
मूलसुंठीलवणैस्तैलेनशीतकालेच ८ पी
तेनभवेद्वाजीदीमाग्नीवर्णोबान्बलवान् उ
दयवनिशोद्भवरुक्षकरसाथ ह्लवणाहयक
णेन ९ दयपान्तारंकत्यामृषणशिखिहिङ्गु
सयुक्तं दधोद्भोमृत्रयुतंयहणीरोगनंरंग
मायत्रये: ९० भिन्नपुरीवायतथासयाग्नि
मिकोष्ठेनेविहिते सीणिकाष्ठकपटूनिपा
टोलयुत्मभेवेदेववाभयानिंवं ९१ अमस्ता
हेतन्वेदस्यो निषाकारनविडंगानि पतेवो
दृश्याणांवर्गेश्रुणिकृतः प्रोक्ता: ९२ मधुस
पिंर्नीरयुतंस्तंरगाणांसर्वकासहर: ।

इवनोंवे फेरमहोमरिच संड हिंग विडा मिलाकेगोमू
त्रसाथसंग्रहणीवाले होउतांइइनांवाहिए ९० जिस्का।
मलदृटा होवे तिसकामदिरेसाथदेवे अग्निकोष्ठवाले
कोवीदिनेदे तिकटा मघा मवे सेंठ लूणपंज पटवलपा इ
टसिटांदानोश्वेतरक्तवछे इनांइ निंव ९१ मिलाकेइत्रारी २
हरवल मढे केलेपत्र वावडिंग इनांगेषधीयांको मही
नचूर्णकारकेदेवे ९२ मधीर होनो इनय साथखाणे
ते होइ कीसभनरोगांकी खांगहरहै ककडसिंगी मु
लठी जलमुलठी कालिवेल महाभंडीगी ९३

© Dharmartha Trust J&K. Digitized by eGangotri

गजपिप्पल पहे योग श्वासके हरणेवाला कहेयाहै ज्वाण
मचा गजपिप्पली सुंठ मरच वचे वायविडंग ९४ कौड प
तोम महातिलेदाभुगा लूणपंज इनांको वाउलेके आटेसा
थ मिलायके जोभोजन है सो देहकी अग्निको जगाता है ९५
गैरवलवणीजीवन आयुषा मांस इनांको वधाता है ९६ कठ
हिंग मचा सैंधा लूण पहे कफवतकफय अंडेको विसकना
गैरकाजीका रुकजाना इनांको हटाता है ९७ इति कफवत
यम थोम सौचललूण मचा कठ हिंग पहे रसोनपंचक

कर्कटशृंगीमधुकं मस्तुलिका शारिवा कणा
भागी ९२ गजपिप्पली विविधश्वासहरः की
र्तितो योगः अजमोदा पिप्पल्यौ विश्वं मरीच
ववा विडंगानि ९४ कटुकानि विषामाषा
स्तिलकृष्णैवैवलवणानि संयोज्य शालिपिष्टे
न भोजनं कायवह्निसंजननं ९५ वल्यं वर्ण्यं
जीवमायुष्यं हरणं चैव कुष्ठं हिंगुकणा सिंधु
रेतत्कफवातघ्नं ९६ अंडचालहरी ह्येतन्मामा
लभक्विवारणं ९७ रसोनसौवर्चलमागधीयु
ह्रामठयोग रसोनपंचकं हितं प्रभाते मह
सीधुना धृतं त्रिकोष्ठगुह्मवातनाशनं ९८
हरीमं हूकमादाय तन्नलं परिशोध्य येत् पि
प्पलीशृंगवेरेण हरिद्रालवणैः समं ९९ पि
ष्टा प्रलिम्पेत्तत्कंठकं वृत्तिकृत्सपरिस्रुतं स्प
र्शेनाविनोदयेद्रक्तो ग्रन्तहिंतेद्धमे १० मस्त
ह्याचहन्नीफलत्रययुता निंवपटोलाम्रते ।

प्रातकालमें सिंधुमधुकेसाथ पीनाहा त्रिक गुह्म अंड
इनांको रुकजाना वायु इनका नाश करता है रसोनपंच
के ९८ हरीरंगका मीलक वा ब्रासी बूटी मगाके फेरसु
कावे फेर मचा सुंठ हरदल लूण इनांके साथ पीसके
उसको लेप करे फेर यव सुकजावे तो पीसके छाणले
वे फेर थोडे थोडेको स्पर्श करावे ... लोहू गलसकतो
केहटलेतालाहै १० इसोत्रपेपर के ... आर
त्रिफला हरड वहेडे आमले निंव पटोल गलो ।

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ हो॰ ११३ इनोंकोविधिसे जलविषेकोउ फेरइणके रसकउलेवे
मुंगी तिसमेंदेके फेरहोउे मषीर त्रिकटा तेल प्रमाणकाल
णपायके युक्तिसेकारे सोचोरेयाको षाणेवास्तेदेवे ११
कास दम सिरकेरोग हृद्रोग वातश्लेष्म सीउ शुकशुकी सो
जा इनकानाशकारहै रुचिकर हृदेकीअग्निवधातीहै एहा
कटुभोजनकहेयाहै सोतेज वल गेज पराक्रमकारहै १२ भोज
नकल्पः तत्राद्रिकटुभोजनं । यव अन गोमूत्रिकरके का
टासिहरिनेयांदी मंचा सेउ मषीरकेसाथ इलायके खानेते

पनांसंभसिसाधयेत्तविधिवत्सूतं हरीवारसं
मुद्गांल्लवविपाचयेनघृतमध्वोषणैतैलेनव
युक्तासैंयवमात्रयाचसहितंतद्भोजनंवाजिनां १८
कासश्वासशिरोगदप्रशमनंहृद्रोगनिर्नाश
नेवातश्लेष्मनिसूदनंवपरमंसिंहाणकोष्ठा
दनंशोषाणांचविनाशनंरुचिकरंकायाग्निसं
वर्द्धनंनाम्नेतत्कटुभोजनंनिगदितंतेजोवलो
नस्करं १२ भोजनकल्पः मुद्गादिकटुभोजनम्
यवन्नकफशोफघ्नंगवांमूत्रेणसाधितं पिप्प
लीशृंगवेराभ्यांमधुनाचसमन्वितं १३ त्रिफ
लावचाग्निकृमारिविश्वतगानीरीभिः कृतंचूर्णं
हृत्वाएवंन्नरमधुमिताप्रकंकफहरंप्रोक्तं १४
पित्तमंदपटोलविडंगवचात्रिफलारजनी
हयविश्वघनैवयुगमयुताः हृद्धनीयुगमधि
गुडूचीकरंजनतगामसमरिवानिंवमागधिकाव
समाविहिता १५ सच्चूर्णयेच्चविधिवत्घृतमधु
पयसानथवातैलेन ।

कफकरमोजेकोंनाशकर
नाहै १३ हरीउ वहेरे आमले वचे चित्रामचो संउ वंसलोच
न इनोंकाचूर्ण और सनका छुहारे मषीर मिसरीकेसाथ क
फकोनाशकरताहै १४ त्रिफलादिचूर्णं । निंव प्रवलपत्र वाव
डिंग वचे हरीउ वहेरे आमले हरदल दालहरदल संउ १८
सिट दो षेलनरक केउ आरा केउआरी चित्र गलो करंजआ
मकेलन वंसलोचन मचे मचो पहमभसमभाग १५
महीनचूर्णविधिसेकारे फेर देवे माखीर उप तेल ॰

113

© Dharmartha Trust J&K. Digitized by eGangotri

इनोंकोरलायककेंचटनीदेवे पहेघोडेअंकेवातकोहर
ताहै ७६ निंबादिअवलेह। संठ त्वाण पुष्करमूल ककडशृं
गी केडेआरा कंडेआरी भंडंगी वच कचूर मघा इनको वेडो
मिशरी मलोरसाथ ७७ पहेअवलेहघोडेयोंको वायुकी
खांग दम हिडकी इनोंकानाशकहेयाहै अरुकठकोशुद्ध क
रताहै ७८ शुंठ्यादिअवलेह। भंडंगी वच संठ वीड दिआर इ
नोंको तेल और घृतकरकेचटनी श्वासकासके हरनेवाला क
हेयाहै ७९ भार्ग्यादिअवलेह। मघा मरिच संठ सैंधवलूण

संभुक्ताल्लरगाणां मवलोहोवातकासहृतः ७९
शुंठीडिरालभपुष्करमूलंककेटकीहृहतीद्वय
मेवं भार्गीवचाशटिपिप्पलिपुष्कः श्वासशिता
मधुनावविमिश्रः ८० एषविधिकथितस्तुरो
गाणांवातकफोद्भवकासनिहंता श्वासहरो
विनिहंतिचहिक्कांकठविशोधनकृदवलेह
भार्गीवचाशृंगवेरमरलदेवदारुवतैलसं
पिंयुतोलेहः श्वासकासहरः स्मृतः ८१ ओषं
सैंधवहिंगुजमोदंद्ववजीरकेदेयाः अष्टांगो
घृतसहशंसमेनोनामपिषालेहः ८२ वातहरो
मग्नांनीमारुतरोगेषुनिर्दिष्टः वलहद्दिकर
श्वायंविख्यातः शालिहोत्रेण ८३ अष्टांगहृणं।
त्रिफलाचित्रकवह्निताख्योषगजपिप्पलीविडं
गानि आभाजीरकपुष्कानायंतीकटुरोहिणीचे
ति ८४ एतत्र्योदशांगंचूर्णंसहसर्पिषाप्र
योक्तव्यम्।

हिंगत्वाण कालाजीरा चिटाजीरा पहे
अष्टांगचूर्ण घोडेयोंको अमृतके तुल्य है अरुघृतकेसाथ
लेहवायुकोंहरताहै जिनोंकेअंगमजेदर्द होन औरवातरो
गोंकेविषेदेनाकहेयाहै औरएहवलकेवधानेवाला शा
लिहोत्रनेप्रगटकहेयाहै ८३ अष्टांगचूर्णम्। हरडव
हेडे आमले गजपिप्पल वावडिंग मालकंगुणी जीरा
काला वनगुंगा कोड ८४ एहेत्र्योदशांगचूर्णघृत।
घृतकेसाथदेनेयोग्यहै वायुकरपीडित औरवातकर

© Dharmartha Trust J&K. Digitized by eGangotri

भा. लकवा और स्वास रोग इस प्रकारके लक्कवेविषे निश्च
टी. हि देणा योग्य है ८२ और या भोजन हुए हैं पछे और हैन तिना
११४ को पछि भोजनके हैया है और वायुकरके या प्रसी रोगक
है हैं तिनांको नाश करता है और वेतो कुटके यो रोग है न
सोभी एकवार देणेकरके क्षणमात्रविषे नाशकरै है इस
मेसंदेह नहि करना और बलवर्णको करता है तिसतैवे
घनिसहै वे ८१ अथ पोटलागड्डचूर्णम् गलो खैरकथ्थ निंव
इनाका सौ पल लेवे इनाको मणि शनि विचकाढे वो

वातार्हितेषु निःस्वासकासार्दितेषु सर्वेषु
भिन्नानामस्थानां भोजनमेन त्रिवारयत्येव
वातोद्भवान् शीतिनिर्हेतिकथितान् विकारान् ८४
हन्ता न्क्षणमात्रेसकृदपि नैवात्रसंशयः कार्य :
बलवर्णकरश्चायं तस्मा त्रिसप्रयोजयेद्वैद्यः
अथ पोटलागड्डचूर्णम् गुडूचीखदिरनिंबमेषां प
लशतंचूर्ण क्वाथयेत्सलिलद्रोणीचतुर्भाग
वशेषिते ८९ दत्तेपलाशतंदेयमभयानां स
हस्राणि पच्यमाने ततस्तस्मिन्प्रतिवापश्च दाप
येत् ८० वत्सः पलानि श्रेणिकमिमान्स्य प्रयो
जयेन् त्रपुषणं त्रिवृत्केतिन्कां क्रिमिशत्रुरयोर
जः ८८ सप्तांशचूर्णीकृत्य योऽपतन्तसमवतार
येत् हौ द्रणाम सहस्रमसृक्को लेहा य स्मा परः परः
खादन येन खादनि यच्चउर्बलखादिनः भुक्ते
नपत्या ते येषां येचसिंहाणकादिनाः ९०

या है साबवाकी है तो उतारलेवे ८९ पुणो हो पतिसके विषे
सां डुबारो मेर हरीडकाचूर्णपावै फेरपकावे कड़ाइ दिवि
च इनोका शतिवायदेवे ८० अथ प्रथमेर पहेवमूपावे मवा
मरिच सोंठ त्रिवा और वावडिंग लोहचूर्ण ८८ इनाकोमही
नचूर्णकरकेमिलावे फेरउतारलेवे मारीरकेसाथलेह
वरणीवणके खानेकोदेवे तोयत्नमरानयत्समलहूसाथ
लेगको हरतीहै ८९ यो है और खाणा खाशाणानहिखोदे
अथवाथाआसो है और बाताहै याप चवदानहि इनाकोपी
नसविकार भी उरुकर हरती है ९०

© Dharmartha Trust J&K. Digitized by eGangotri

जिनांदेकोष्टविषेंकफहै येदेवेंगकरकेदुखीहैंन ११
सभनरांकेमुखकेरोग अरुगलकेरोग हृद्रोगविषें मधा
सवमदिरातिसकेसाथदेवे १२ रक्तपित्तरोगोंविषें घृ १२
तकेसाथदेवे यहैयोडेयांकोंश्रेष्टरसायनऔषधकहिहै
इतिहरीतकीभूषणाद्यलेहकल्पः। वडीबुद्धिवाले
मुनियोंनेनावननसवार मुखगलकंननासा अक्षि शिर
इनांकेरोगांकेहरणकरणेकों औरहिडकीश्लेष्मखांग इनां
कोंनाशकरणेवालेकहिहै १४ जिनांदेसिरविषेंसिंहा

कफःकोष्ठगतोयेषांयेचकासमनिपीडिताः ते
भ्योदेयमवलेहोयंभिषजासुविजानता: ११ मु
खरोगेषुसर्वेषुतथाकंठामयेषुच हृद्रोगे
षुचदेयंस्यान्मधासवसमायुतं १२ रक्तपित्त
विकारेषुसर्पिषासहदापयेत् रसायनमिदं
श्रेष्टंवाजिनांपरमौषधं १३ हरीतकीभूषणा
द्यवलेहकल्पः। मुखकंठकर्णनासान
यनशिरोरोगनाशनंश्रेष्ठं हिक्काकफकासह
रंनावनमुक्तंमहामतिभिः १४ येषामग्रशरी
रेकेचित्सिंहाणकादयोरोगाः कफजाश्चलिं
गिनांतेभ्योनस्यंसदादेयं १५ तेजःस्थौल्य
रूपवलंचसंवर्द्धते:ग्रिमकाये दृष्टिर्दंताक
र्णौहनुचगलसंधयोग्रीवाः १६ पादाश्चसं।
तिमृहत्कारोगास्तस्माद्विनश्यन्ति ऊपरु
न्कुमरोगाणांवलमहाहानिनाकुर्यात् १७
वलेस्कंधौगात्रुमेधैकफचौवक्रछिकेचैव।

णकचक्षुआदिरोग औरकफकेलिंगीनरोगहैं तिन्हांनाइं
नवारसदादेनेयोग्यहै १५ शरीरविषेंतेज अरुदेहकीमुटे
याईरूपवलअग्निवधतेहै अरुनेत्रदंदकर्ण हनुवालो
औरगलकेजोडकराड़ी १६ सेवपहेसभहद्द्रपकेस्थिरहो
तेहैं औरयन्त्रवामेंहोनेवालेरोगसभसमहोजातेहैं अरु
हनिरोगपजोडयांकोहलेतेवकुनवलकरहै १७ और
वलीयांमोडेवारूनेच्यां फिरेगामचेगुदापहेंहटफवे।

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ सो ऐसे होने घोडे यांको नसवार करे होते हैं ९८ नसवार
हो॰ वाले घृत अथवा घृत तेल साथ वा केशक नसवार यथप्रका
११५ र की देवे और स्नेह मध्य स्नेह घृत तेल साथ उत्कृष्ट की
पहें त्रयभेद करे हैं ९९ वातिक रोगवाले तो ई महास्नेह
मिश्रक मध्यम पहदेवे अरु जीवनीय गण। इसका मा
षपर्णी मुद्गपर्णी काकोली क्षीरकाकोली जीवक ऋषभ
मेदा महामेदा ऋद्धि वृद्धि मुलठी इनोके कल्क साथ हो उप
कावे ९: सो पित्त रोगवाले को देने योग्य है और यो घोडे न

पानाद्धृदकासश्च पानस्येन भवंति वाहानां ९८ ह्रे
हेवा स्नेहयुक्ते चापरिहृतमथापि वा नावनं वि
विधेयो स्मृतु मध्यम घ्रोकट ९९ वातिके स्या
महास्नेहे मिश्रके मध्यमं तथा कल्केन जीव
नीयानां क्षीरेण वघृतं पचेत ९: तृप्ति रोगि
ण देयं ततनीणस्त्रयेहयाः शिरोरोगास्त्र
कं॰ नसंपतिरकोपिन वशाम्यति १ स्वेनपंचमूले
न तथा बिल्वशलाटुभिः रास्नायावगुडूच्या
वपिप्पल्या मधुकेन च २ सपिष्टान् पयो देया
दांश्च तैलं च तन्गुणे साधयेत्तावनं तेन वात
व्याधिः प्रशाम्यति ३ प्रसन्नां चैव रास्नां वै तैले
न सह साधयेत सौवीरकेण संयुक्तं नावनं
वातनाशनं ४ पिप्पली सैंधवं शृंगवेरं वद्धृह
तीफलं गवां मूत्रेण संयुक्तं नस्यकर्मणि दाप
येत् ५

तृप्त करके तीन प्रकार शिरोरोग नाम होते
हैं एक पित्त समन होता है १ इस बेलचु पंचमूल कडे आरा
कडे आरी भूरकनी देशार भत्ते इनोके अरु तैसे ही
बिलके कचेफलो करके रेसन करके गलो करके मंघा
करके मुलठी करके २ सेंदरम हीन कुटके दुग्ध घृत
तेल चार गुण पायके सिद्ध करे इसकी नसवार करा
के वातव्याधि समन होती है ३ मदिराको अरु रेसण को
तेलके साथ सिद्ध करे कांजी करके युक्त नसवार वायु को
नाश करे है ४ मघा सैंधालूण सुंठ के आरी के फल गोमू
त्र साथ नसवार के कार्य विषे देवे ५

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रोर नस्य कर्मके सिद्ध होयदे स्तंभकानाशा निश्चय करके
होताहै ९ तेजबल सिंधुलूण सुंठ लाख गुलठ मधा
हरदल स्वरसा वा रसोंत इनको सबोंसजल करके देइहो
इनस्यवार लेगिनजेयां सबकाणी निसको हरहै ग्रोरमा
ड्रेमोटेकरतीहै कांतिकरहै बल उत्साह उरमकुरहै ग्रोर
मन्यास्तंभ शिरग्रह पीडा कफरोग गलरोग इनामें गुणक
रतीहै १ इति ग्राभाष्टकं । रेसण रक्तचेदन झलथ झठ
रवी सेंधा लूण तेल छायपकायाहोया सोउग्र लिगिना।

नस्य कर्मेणि सिद्धेव स्तंभाभावी भवेध्रुवं ९ ग्रा
भासैंधव विश्वलाक्षा मधुकैश्च सहर्दिद्रांजा।
नै रेभिः नस्यमशाग्यलगितहुंदेयसवोंसाव
ना स्कंधस्योल्सकं रग्रभाश्रजनं नवल स्वंबलो।
त्साहदं मन्यास्तंभशिरोग्रहार्तिघ्नं कफकंठा
मयेघ्नस्यते १ ग्राभाष्टकं । रास्ना लोहित चंद
झष्टसरला सिंधूथ्यतैलेपय: पक्वंभक्षणानस्य
या स्तंभ निर्गुणी ग्रीयास्य सद्दालिगिना ८ लाक्षा।
कटूफलं मञ्जिष्ठा तूरकं सैंधवे गुनकं वारुणा
मसिंधुस्र हट्टग्रैपाचयेत्तैलं ९ तद्वीनं तौह
स्यन्तचतुर्थभागेन नस्यं तं नस्य माकृतं कफ
सिंहाणकं मषामनं वापिनादेयं १० ग्रति
नाकके वापित्रिभागं मधु मूर्छितं घेनास्तक
फणिजकरसोन वृहती फलानि कंगलिका
वभिरविमूत्रसंयुक्तैर्नस्यं कफवातनिकृंथि
ने।
रेगवालियांकों बुद्धिवालियाने खाणोंकों ग्रोर
नस्यवारवास्तेसदाही देनेयोग्य है ८ लाख कांफल मजी
ठ भलेरे सैंधालूण इनांकेसहित वारुणीमदिरामिला
यकेतेलपकावे ९ यवढुग्रहोजावे तो मखीर बोयाहै
सापायके नस्यवार वायु कफ सिंहाण करोग इनांकेनाश
वास्ते वोइयांकोदेवे १० ग्रस्तवफलतरक ग्रस्तकुफकेविष
तीसरा हिस्सा सहतमिलाकेदेवे बिलकांतविरा भलेरे
मरुग्रा थोमकेइग्रारीकेफल ११ इनांकोभेडकेमूत्रसाथ

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
११६

नसवार कफवायके जीतनेवाली कहिहै गंडीला अक
रनकेमूल संठ इनाकरकेतेलपकावे ११ इसनसवारक
रके चूणिरोगवाला सखी होजाताहै औरपकजहवाला
तुलसीकीमंजरीअसवगंधपीसके नसवारदेवे ११
औरम्हराकेसाथयोडियाको नाडीआपनकेविरवकर
नसवारकहिहै आभा तिमहरसोंत हिंग मद्या सुंठ १४
हरदल सैंधालूण जठ इनकीनसवारघोडेयाकोअष्टहै
वातकफरोग मन्याकाडीकीरुकजाना हनुयहविषे १२
करवीरस्यार्कस्य वमूलैः सुंठीगुनैः पचेत्तैलं १५
नस्येनानेनचूणिसलीभुवेदकपुष्यकोव
आसवपुंकेविष्टाश्रुदापयेत्स्वरसमंजरीत
सं ११ स्मरयामूरसमीनांनाडीव्यापहिरवेत
नस्यं आभारमाजनहिंगुपिप्पलीविश्वभे
षजं १४ हरिद्रासैंधवंकुष्टं हयानानस्यमुत
म वातश्लेष्मविकारेषुमन्यास्तंभे हनुग्रहे १५
तालुशोषेकंठरोगेगलरोगेतथाहितं १६
नस्येपिद्धाकुंरुनागरवासमैधवमागधि।
काश्वितैवा ध्राणास्यमन्याहनुवाहवलः शि
रोरुकेंदुअवणामयेषु १७ कपिकच्छ्वाम
दुचनरमूत्रसमापुतैः वातः प्रवाहिकैनस्य
गरंडवालउपोहति १८ वचासौवर्चलकुष्ट।
रामठंकपिकच्छुरा आविमूत्रयुतंनस्यम
वेष्मविकारिणा १९
तालकीसोज गलरोग इनोंविषैगुणकारहै १६ संठ ग
डकीनसवार वा सैंधालूण मद्या इनकीनस्यनाशरोग
मन्याकाहनु वफ वति शिर पट गल काणे इनोंरोगों
विषेदेवे १७ मजूली हिंग पुकषके मूत्रसाथ इहनस
वार वायप्रवाहकुनामहै गंडीकायोहलजाना ति
सकोंनाशकरनीहै १८ वचे सौंचललूण जठ हिंग
मजूली स्याहा इनकोभेडकेमूत्रसाथ नसवार स्लेभ
तरोगके औरहरोगवालियोंकोहितहै १९

© Dharmartha Trust J&K. Digitized by eGangotri

पाणाजड जजूली ऊठवर्च हिंग मद्यो ववक सौंचल
लूण यमएगी इनोंका ऊगदाकरके पिप्पलके काथसा
थ अथवा वकरीकेडयसाथ्य नससवारलेनेथे काडेका
आकडजाना गेरअंग्रेजविसकने मुखकाफिरकना इनो
कोहरनीहे २० इतिलावनकल्कः शिररोग नेत्रमुख ग
ल नासा इनोंकेरोगोंविषे गेरनासाकेवीच घायमांसो।
ऊरु ममसीयां इत्यादिरोग २१ श्लेष्म रोग हिड्की सिंहा
णकनाडीव्यापति इनोंविषे धूमपानविधिश्रेष्टकहीहे

परंउकपिकल्कऊष्टमवचाहिंगुलत्याविष्या।
ली वंच्यवैवमवचेलोतरमिदंकल्कमवाघा
लकें कृत्वापिप्पलजकषायसहितेच्छागप
योवाहरेन्मन्याक्तंभनचालनांडवलनेवक्त्र
हरेत्रप्रस्तनः २० लावनकल्कः शिरोरोगाति
रोगेभ्रुमुखेकंठगदेच्छव नासाभ्यंनरगेघोर
व्रणेमांसांकुरेतथा २१ श्लेष्मकासेष्वहिक्का
सनश्यासिंहाणकेष्वपि नष्टेचनाडीव्यापातो
धूमपानविधीयते २२ सुशिरंवैणवंनेत्रन
न्मध्येहादशांगुलं कांचनंराजतंताम्रमारकू
टमथापिवा २३ अंगुष्ठसंमितेछिद्रंपरिणा
हेष्वचेष्टितं ततःकालंसमाश्रित्यतंग्रागार।
विनिवेशयेत् २४ चरीपिधानमध्येतुकार्यंछि
द्रमथांगुलं नेत्रचरिपिधानेनतस्यछिद्रंपिधा
रयेत् २५ पार्श्वेचरस्याछिद्राणिसूक्ष्माणिच
कारयेत् नैवांगारस्थितेधूमे प्रतिध्याप्य प्रयो। ६
नयेत् १

संदरशिरवालीवंशकेनेत्र नालीवनावे
तिसकेवीच वारां अंगुली सनेका रूपे तांबे पितलका
अरकूट जिनामोटा वेष्टा तिसकेछिद्रकोसदा उसकोउ
परविषे अग्निकेअंगारपावे २४ उसको चरीकेढकणा
विषे एकअंगुलप्रमाणछेककरे सोनेत्रचढकेछेकमें
रखे २५ औरचडेकीवत्तीयोंमेंसमहीनछेककरे इसकके

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ हो॰ ११८ धूमपिलावे अरु घोडेयांको केवल अंगारेविषे धूमपाय
केनहिदेवे २६ धूमकार्याविषे वडेघोडेको वतीतुरपि
लावे मध्यकोवीवी छोटेकोसोला २७ देशदोषवलदेष
केवैद्यपिलावे धूमजिसकेअग्रपरसे करके गिलेहोनवा
हरनिकसजावे सिरहोला नासिकाशुद्धहोजाए नोजा
णेहल्का भलीतरांपीता है अरु रसतरांनाहोवे नोजानेजे
हल्कानहीमाराहै औरजीणकुशघोडेकोधूमनापिलावे
कोंयेहलदयतिसकामकजाताहै २९ वालककोयके।

धूमकर्मसहाद्विंशमायपेदुन्नमंहयं मध्यमंन
वतिंशमधमंवापिषोडश २७ देशंदोषंवा।
लंतात्वाधूमंवापाययेद्भिषक् सम्यक्नाविनि
सावः स्यात् शिराशुद्धनासिका २८ इतिसम्यकी
तधूमंविपरीतेनगादिंते नीरोगनदापयेद्धूम
लदयंतसप्रगुणाति २९ वालकानेवगर्भिण्या
वृषस्यविरयोरपि एवंप्रकारयेवाम्येनेध्रुव
मेनपाययेते ३० यस्यधूमप्रयच्छेन्नतौवापिवति
योहयः तस्यधूमस्त्वदातव्याः कलशैमांत्रुषवि
यौ ३१ नासायांपीदुयेद्धूमंउच्छ्वसितिमुखेय।
था नोच्छ्वसितिमुखेयस्तुमरणंसमुवाप्नुया
न ३२ एवंशास्त्रविधानेनधूमंनपाययेदयं
प्रंडुविल्वमूलानिसर्पिषासहभावयेत ३३
एतेनपाययेद्धूमपपीनाकेनाथवापुनः।

होयेघोडेकोगर्भवालीघोडीयावीर्यवाला औरवृद्ध इस
नतोंकेहारघोडेयांकोधूमपानश्रेष्ठगुणकारनहिहै ३०
जिसघोडेनेधूमदेश्य अरुसोपीवेनहि तिसकोमनुष्यों
कीविधिसे घोडेकोछिद्रकरकेवृणियोगपाहै घोडेकोछिं
डाकरकेनाडीकरकेदेवे ३१ नासाविषेपीनाहोयाधूमसुख
मेंनिकासे योमुखवकनेहिकडे नोतिसकीमरणप्राप्तहोर
जान ३२ एवंशास्त्रकीविधिकरकेघोडेकोधूमपिलावे पर
णविलकीमउ घेडमाष्यमिलाकेसवकेधूमपिलावे।

© Dharmartha Trust J&K. Digitized by eGangotri

अथवा छांटरकरके वा भस्मोप्रेकरके गैरदर्भकाई स्नाका
मूलघृतमिलायके ओरेनाईश्मदेवे २१ अथर लेस ... ओर
ग्रा हरिताल विल्वदृन्तकीजड मखीर मूसेकनी जयंती
गंधत्रण तुलसी १६ पाणदीजड गुग्गुल साथे रंडट घृत
साथ मिलाकरके मूत्रवेको टकके झोम्प्ररोगकर्के शुकयो
डेको श्नांउगैषधीयांकर्के श्पदेवे २२ पीतकालमें गोरमो
जनकीपहोपको विशेषनेश्मपिलावे श्मपीनेहोपद्योडे
को पोमनेहे सोमेरनेस्तण १८ तिसदिनविषैस्नेहपान।

भस्मलानिसंयुक्तंमूलानिकुशकाशयोः श्व
घृतेनसहस्मदायश्मममायदापयेत् २१ ग्रा
लाधोरेयाणिकंग्रवोरकु हरितालविल्वमूला
नि लोटमूषकपर्णितकोरीरोहिकेमूरेणा १६
पंडमूलगुग्गुलपातमूत्रेणकाघृतेनाका
पतेराक्षाघमूत्रलमृश्मयेतश्लेष्मरोगार्ते १७
पीतलेपाययेश्मस्मभक्तवंतेविशेषतः श्मपी
तस्यवाश्मस्मवर्ज्जनोयानिमेस्तृणा १८ तदहःस्ने
हपानंबविधास्तानंनथैवच खोदनंप्रतिपान
वलेदोलावनभोजनं २९ श्मकल्पः तेजोव
तीफणिस्पकर्कगुलिकाहरकस्मस्तहरिताले
सैंधवरोहिषकटुकाकटुफलपिानमर्षपरसो
नैः ध. मरिचार्कमूलसहितैःकृलापामार्गत
डुलविडंगैः लान्नाग्रुंठीगुकैःसमभागैःसूर्णि
नैःस्वतोः धा ग्रमस्यचूर्णस्पकर्षवनस्तःप्रतिप
थामयेत् ।
विधिस्नान गुहलणा अहरवोना प्रतिपान
वटनोलूणकरकेभोजन पहेमवमणेहैन २९ इतिश्म
कल्पः तेज वल तिमरु मनुश्रा मालकंगनी नकछि
कनी अथर हरताल सैंधालूण गंधकाग्लाय कोडु काय
फल सेनी सरेयो योम मच शुककामूल मखो धरकूडेके
बीज बावडिंग लाख छुंड श्नांकोसमभागमिलाकर्के म
हीनचूर्णकरके इसचूर्णकोदशमासे छेगुलीकस्की
नालीको रूणीकेसाथमरके नयग्रगुलीनासाविधिदके

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ बुद्धिवालालडकमारे नवशिरकोंउपरखिंचे सोहूवेरेवि
हो॰ षमनवीमले वलकारके ५२ सिरकोउवायकेचोडेका।
११८ होलिहोलिस्रोध्यनेवहूरनिकासे ५४ इसतंरानसनसवा
रवाउहोप चोडेके सिरकेरोग सिंहणक वातकफनेहोया ५१
हा गेरनाडीआपत इसनसआरनेसिनावीनाशहोजातेहैं
पहिनसवार रक्तपित हिडकी दम तप मूर्छाआकुलदीन
धूपकेसाध्यपीडितगर्भवाली स्त्रीचोडीरनोविषे ५९ छेम
होनेकेवचेविषे स्रहसिनावीका रुधिर वा दस्तकरापडे

षडंगुलंवेणमंथीनाडीह्योणनस्तयेत ५२ प्र
वेशयमंगुलेतत्लः प्रथमयेविवृतागः उन्तिसे।
शिरसःत्निश्रृधानेमर्दयेद्दल ५३ श्रवनाम
शिरोषस्पशानैः श्रोध्यापयेत्तिव ५४ एवंप्रयो
नस्यशिरोगतंगदं सिंहाणकेवातकफोद्भवं
व नाशविपत्रेनयनावनेननस्तंरंगसमा।
दासुहस्मात ५५ नसरकेचपितेचहिक्काया
सत्तेनषुच मूर्छितेविह्वलेदीनेयमीनैगर्भि
णीषुच ५६ षणमासिकेषुशावेषुसंघोविम
वनेषुच नस्यकर्मणिमेहेवुमंघपीतेचवाषु
नः ५७ नदापयेत्तथमनेनहिसंघाविनाशये
न मवोकटफलहिंगुसैनाम्रोतिषुमतिकं।
णालवणेः त्वरकफाशिकम्लैः सूक्ष्म
स्तेकारयेच्चूर्णं ५८ हरडीफलसचूर्णंनत्रे
वचनगुणसमायोज्य ।

वै प्रमेह मूत्रविकार जिसनेमदिरापीताहोवे वहुत।
लिमाहोवे थकेयादाहोवे काडापीताहोवे इनाको प्र
धमननस्यपोडकमारके चडारदीहै सोनोदेवे धकर
देवे तोशतावीमारदेनीहै ५८ गलोट कांफला हिंग॰
वचे मालकंगुणी मचो सैंधालूण नकछिकणी मुहू
स्रा चूर्णर इनोकामहीनचूर्णकरावे ५९ गेरकडया।
रीकेफलकाचूर्ण तिसविषे वारगुणाभिलावे पहे
प्रथमननसवार सिंहाणकशिरविषे ज्ञानसीर ।

118

© Dharmartha Trust J&K. Digitized by eGangotri

तिसकेनाशकेवास्तेवकृतश्रेष्ठकहाहै ५० अथवाकं
डेआरीकेफल महीनपीसकेदेवे अथवानासामेयुरह
णकराके फेरघोडेकोवकृतउच्चाशिरकरावे ५१ घोडे
केऊपरचढकेफेरे औरजलकेमध्यविषैस्थितहोकेचि
रकालनसवारदेवे फेरनाउलेफेरे इसतेहस्तिनरोनिक
लजावे ५२ औरपरमेकरकेयुक्तघोडेकोशीतकालमे
प्रथमननादेवे इसप्रपचारकरके असात्म्यविहारने व
हृतश्रेष्ठवदयाताहै ५३ इतिप्रथमनकल्पम् मत्या सु।

प्रथमनमेतत्कुष्ठंघनेनतस्मिंहाणकेशालं ५०
अथवाश्महत्वाविष्टहुहृतीफलमेवदेयस्यात्
अथवानासायहेणापश्चान्तरंगप्रोत्यापयेद्रूः
णः ५१ आहृत्यवाहृयेद्वाहंप्रदापयेद्वापिवि
रसलिलमध्येन वक्रामयेतड्तवापिविरि
ध्नेतसम्यगेवंहि ५२ प्रसिन्नस्यतशीतेनदा।
पयेत्प्रथमनेनरगस्य अथवारेणामेनतभ्
यिष्ठवर्द्धनेश्रेष्ठा ५३ इतिप्रथमनकल्पम्
तस्मात्सस्तरसोननसर्षपतेजोवतीयवक्षारे ः
विस्रैलादाहरिणामरिवंसोतिष्णतिलवृणैः २७
सावरकलोध्रशुक्तैःपिष्टैगोमूत्रसंयुतैर्भिषा।
गा मुखपावनमध्यानां मुखरोगदापहंपरंप्रो।
तो ५४ मुखपावन । महान्तेशिखिसर्षपो
मिमिनिरेकुष्ठोमसेभांजनं नावैष्टेमहसे
पवेनमुरसा गोमूत्रतेलेथवा ।
ध्यर रसोत सरेयो तिमरू यवेक्षार संठ लावी दालह
रदल मरिच मालकंगुनी लूण सेतलोध इनोकोवेध
गोमूत्रसाथ महीनपीसके घोडेयांकामुखकोधुवा
वे यहमुखकेरोगोंकेनाशकरणेवालाकहाहै ५५
इतिमुखपावनम् भलाथ विडा सरेयो देपसोप कस
र कुठ सहांजणा यवेक्षार सज्जीक्षार सैंधालूण न
लसी गोमूत्रसाथ वा सिरका पीरदाङ्प पाठाकेका
ढे अथवा त्रिफले करके पकावे इसतेलकीमर्दनेते

धा॰
हो॰
११९

119

वाजीकरके शुक्र और देह सबकी गया होवे तिसकों सम
करता है ५८ अग्निसमबलकरता है और कफवात सम प्रका
र वोडे थोकासंभ इनुकों हरता है तिसकों गुर्ड सें थालू
ण सजी हरवल सभाजना हालहरवल इनोका चूर्ण
करके थोडे तेल मिक इनोंके साथ सिद्ध करके सवो।
सपील गर्म के साथ मालस वायुके रोगोंके हरनेवा
ली है और पैदा है वीर्य में गर्म है ५० इति अभ्यंगविधिः
हरडल दालहरदल चित्रा में थालूण वो हथा सोप सज्जी

स्वर्जिकैलायसाधुतेवविधिहाडीफलेपावये
हातव्याम विशुष्कगात्रशमनः स्नेहोयमाधुज
नात ५९ अग्नेस्त्वलवलः कफानिलहरः स
भापहोवाजिना नहसेंधवसर्जिकानिशिष्ठ
नेशोभांजनेदाकव चूर्णीकृत्य हतेन तैलच
मयायुक्तेससोस्याभवेदभ्यंगः पवनोनराम
यहरः स्निग्धोसवीर्यपरः ५० अभ्यंगविधिः
रजनीयुगसेंधवहिंगसैंधवचोरकशतपुष्पस
र्जिकातारेः कुष्ठमहौषधसुरसासितरुपतेरु
र्णितैः सर्वैः ५८ तैलेल्समकम्पुतैर्मध्यावोस्त
स्तुगात्रमभ्यङ्गः तत्मर्दयेव वातोव्याधिः
पीडेतनुकुर्वीत ५९ उन्मर्दनकल्पः सर्षपा।
न्कुसुगंधाचकल्केः शोदिकारयेत वाति
केप्रदहेतेनयुक्तसेंधवमात्रया ६० तिलान्
पलाशपत्राणि पेषयेत्सरसमेवच ।

पउल्लार कुठ सुंठ तुलसी सहांजना इनोंसभनोंका चू
र्णकरे ५८ तिनाकों तेलऊरमस्तुमिलाकरके गर्भ स
ब्योसरे देहविषेमर्दन युक्तिसेकरें तो वातव्याधिकीपी
डानहिकरती ५९ उन्मर्दनकल्पः। सरेयां सहांजना
इनोंकोंमिलाविषैपीसके कल्क बनगदाकरे तिसका ले
पवालबालेकों लूणप्रमाणकापथ्येकेकरे ६० तिल
और पलाशकेपत्र इनोंकोमहीनपीसके और सैंधव
लूण रलाइके बालवाले थोडेकोलेपकरे ६१

© Dharmartha Trust J&K. Digitized by eGangotri

सैंधव लूण मदिरा वनतुलसी कालीन्याप्रोय इनोंको
वातव्याधिकौंपाणके छोडके अंगोंकेलेपकरे ९२
वरमीकीमिति देवदार सहांजना सरेया हिंडु इट
सिट यडेल्हार लूण इनोंककेलेपकरे योचिरकालू।
काहेंयालसोजा शताकी नाशहोजानाहै ९३ सर्व
शोथहरलेप: येछोडे वातपित्तकारइखितहैं तिनो
को मठाछतमिलायके सतूआकालेपकरे ९४ लो
घर खसवीरणकीजड ज्वाहा खेत इटसिटकीजड

सैंधवेनाथसंयोज्यलेपयेद्वातिकेहृदंये ९१
सैंधवेवप्रसत्रावक्रुल्मागंयावपेषयेत् सै
धायवातिकेश्वाथोनेरगांगविलेपयेत् ९२
वाल्मीकमृत्स्नामरदारुशिग्रुशिह्वाथकं।
हिंशुननेवाभि: क्षारेणमाहुलवणेनशो
थंनिहन्याद्चिरप्रवृत्ते ९३ सर्वशोथहरं।
शुष्कमारुतपित्ताभ्यामभिभूतायतेरगमा
केचित् सर्वंदधिचूतयुक्तेसशलेपनंकार
येत्तेषां ९४ लोध्रमुसीरमनंतापेतमूल
वंबेत्रवेतसयाः स्वर्णशैवलकर्दमयुक्तो
लेपनस्तुपित्तहर: ९५ क्षारंचित्रकसैंधव
युक्तेस्तनिकांभवेद्विगुणा: श्वेतस्मिका
भागान्समांदद्यापतान्क्तान् ९६ गोमूत्रसा
मायुक्तपिष्टंकथितंनूतोसमादायकार्यं
श्लेष्मगमाणामालेप: श्लेष्मरोगघ्न: ९७ हृ
वीवेरंडमूलंचमधुकंपद्मकंतथा।

वेत्र वेत लखवल नाला विकट इनोंकेसाथ लेपन।
कीया स्ववापित्तको हरताहै ९५ यडल्हार चित्रा सैंधा
लूण अश्वमूत्रकाहरणी गेरमिती केवराबर शनावुर
इनोंकोगोमूत्रसाथपीसके काढके सवोसलेकके
छोडयाको लेपकरोकरके श्लेष्मरोगकेनाशकरणे
वालाकहैयाहै ९७ हवी परगनर मलठ पद्मकाष्ठ
पंचसीर इसवती हेवल पिप्पल स्लाह पारसपिप्पल

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ पहेके हैहैन कौलगोड खस इनोंकालेप पित्तकेसोजे
ह्रो॰ को नाशकरताहै ९८ बडी रुंवल वड झाल वैत इनो
१२० के सिकड उपकेसाथ पीसकरके लेपनपित्तके नाश
करणेकोंवहुत श्रेष्ठ कहेयाहै ९९ पचलीरहहोंके।
कल्ककरके अथवा वनमालतीका केवल कल्कपा।
120 णीकेसाथ पीसके वयेहोएपित्तको पहेलेपनकरे २
वोड रुंवल वैत इनकीयाजगे ओरपिप्पलकीयां ओर
पंचोंकेसिकड इनोंकालेप व्रणघाय ओरसोजेको ना

लीरिणः पद्मकोशीरैः प्रलेपः पित्तशोथहा ९८
न्यग्रोधोदुंबराश्वत्थप्लक्षवेतससंभवाः वल्
कलाः पंचसस्नेहा लीरपिष्टा प्रलेपने ९९ प
वानां लीरिणां कल्कैः शीताकल्कैश्च केवलं
पिष्टा तोयेन संहृन्ते पैत्तिकान् प्रलेपने १०
जटीवटोदुंबरवेतसानामश्वत्थप्लक्षेण सम
त्विताना मवांचकं पंचमहीरुहाणामिति
व्रणान् अपस्तुतमेतत् ११ तथा लीरेणमा
षेण कथितेन रूपलेपयेत् त्रिगुणं स्फटिकां
कृत्वा गोमूत्रेण विपाचयेत् १२ एतेनापिस
तैलेन श्लेष्मिकान् प्रलेपयेत् प्रलेपयेत्त
तैलेन तिलतैलेन वा पुनः १३ एतत्स्यप
थ्या कार्यं स्वेदेन न समुल्लेपयेत् श्लेष्मिके च वि
कारेषु पैत्तिके च विवर्जयेत् १४ लेपकल्पः
शुष्कान्यपि च कार्याणि स्निग्धः स्वेदोपलाहना

शाकरताहै ११ तेसेंहि उपमाध्यमहामिलाय काउके
उपरलेपकरे अथवा त्रिगुणीमिनी रलाके गोमूत्रसा
थकाडे इसकों सीलगमेंकरके श्लेष्मरोगविषे लेपन
करे अथवा इसको सीलगमेंतिलाके तेलसाथ लेप
करे १३ इसीलेपकों मिनीमिलायके श्लेष्मके सोजे
विषेलेपकरे ओरश्लेष्मरोगोंविषेकरे अरुपित्तके वि
कारोंविषेनहिकरे १४ इतिलेपकल्पः सवेकलेपका
ंओंकोंवीस्वेदहोनतेलादि ओर सेक वेपन नवायदेनेहैं

पथ्याविधिकरकेकीयहूये अरुजीवतेहोयपांचोउ यों
कीवावातहै ७९ अलसी सोंउ कूलत्थ हरदल तिल महो
इनोकोमिलायके पीनेहोपहणेकके औरलूण अवल ७९
कांजी तेल इनोकरकेउनकसिद्धकरकेचोउकों वंधनकरे
सरेयां यउ कणक खल समभाग और परणकोजउ औरवी ।।
जे महो अलसी कूलत्थ तिल इनोकोमहीनपीसकके
लूण जलतेल इनोकेसाथसीलगर्म वेघवंधनकरावे
पहेउपनाह वायुकेहरणेवालाहै अरुसभतरांकेसोजे

नामयंपतिपथ्याश्चांके किंउनजीवितोह्यान ७९
अतसीविषकूलत्थैरजनी तिलमाषसउतैःपि
ष्टैः लवणाम्लतैलयुक्तैः सिद्धैरुपनाहयेदथ ७९
सर्षपयवगोधूमैः किण्वसमैरंडमूलफलैश्च
माषातसीकुलत्थैस्तिलैस्तपिष्टैस्तैःशुक्ताः ।।
लवणाज्यतैलयुक्तैः स्वेदोसउपनाहनंभिष
कुर्यात् वातहरंशोफघ्नाणांसर्वेषांपाचनंश्रेष्ठं
७८ इतिकाचितिविषाग्निकटफलवचाकाशी
शसौभाजनं दंतीनागरमनःशिलालमदनंचो
षंलवणार्सर्षपैः सर्पास्फोतनुविडंगराजकवि
शालोभैःसहिंगवासयैभार्गीतकललवणास्तु
वत्सकयुतैःक्लिन्नैर्निकामिश्रितैः ७९ पिष्टैःर
वेणयुक्तैर्निपेयमेरंडतैलसंयुक्तैः पथ्याश्वि
कणउगालवनात्रुनिजचासवप्रपथ्यैः ८०

यांकेपचानेकों बहुतश्रेष्ठगुणकारहै ७८ करंजुआ अ
तीस चित्रा कांफल वचे काही सहांजना दंदणदानेकीज
ड पगेतार मनसिला हरताल राउा मचामोरच संउ सरे
यां सर्षफूल कूरेयाल वायविडंग और हरदल सौपुर
हिंग कूठ भंगीगी दालचीनी लूण ५ कोगउ सज्जी
इनोकरके पुनःदूध जल वा उगधकरकेपीसे फेर प
रणकातेल विचपायके वंधनकरे जहांदूठी वधा
गईहोवे औरकउगानाडी विषे जेवां नातूसोजे इनो
विषे बहुतश्रेष्ठ गुणकारहै ८०

© Dharmartha Trust J&K. Digitized by eGangotri

पा॰
हो॰
१२१

121

वरमीकीमिटी मह्रां मसर चित्रा चोक सहांजने
कीनड यगेत्तार सजीखार पंचलूण सेंधा सोंचल
विड समुद्र सांवर ८१ इनाकोगोमूत्रसाथ पीहके स
रोस उपनाह बंधनकरे पहूपकादेताहै सितावी
औरसोजेकानाशकरताहै ८२ वातस्लेष्मकेविकारवि
षेउपनाहश्रेष्टकह्याहै औरयेपित्तककेरोगहोवे ति
सको ठंडीयांवस्तूसाथ बंधनकरेवैद्य ८२ सूलकोका
उगदावनायके घेउसाथमिलायककें घायकेवास्ते उ

वाल्मीकमृत्तिकामांसीमसूरंचित्रकंतथा
हेमक्षीरीसिग्रुमूलक्षारीलवणपंचकं ८१
गोमूत्रेणसमंपिष्ट्वासत्तोलमुपनाहनं पा
चनीयंभवेच्छोथशूलपतुप्रविनाशनं ८१
वातश्लेष्मणिसंदुष्टे उपनाहः प्रशस्यते पै
त्तिकाश्चवयकेविच्छीतलैरुपनाहयेत् ८२
यष्टीमधुककल्केनवघृतेनसमूर्छितं ब्र
णेश्रुप्यपनाहार्थेरक्तपित्तेप्रशस्यते ८४ उ
पनाहः । अथपश्चशमयत्यग्निः शूलंप्रविला
पयेद्गुनोहरति संशोषयंनत्रणानांवातंचैवा
नुलोमयति ८५ पंचविधमग्निकर्मस्वेदा
मर्दनलवणतैलेन तप्तेनस्नेहेनवातथा
पयसामेदसावैव ८६

पनाहबंधनकरे रक्तपित्तविषे पहेश्रेष्टकहेया
है ८४ इतिउपनाहः अग्निकर्मदग्धकरणा सोजेको
शमकरहै शूलकोहटापदेताहै औरपीडाकोहरता
है अरुघायकोंशुद्धकरताहै अरुवायकोंयथार्थच
लाताहै ८५ अग्निकर्मपांचतरांकाहै सेककेसाथपर
मापायेदेणा मलना औरलूणतपायकेसेकदेणा और
हतनेलादिस्नेहकरकेदाहदेणा ओर दुग्धकरके
सिंकलकरके ८६

कोइककैवैद्यचोडेकों दोप्रकारकाकहतेहैं एकलोहे
का औरमेदसका तिसकेविषैंचोडेयांकों मेदाकाग्र
हकरेयाहै जिसकारणतें विसृपनहिंकरता ८७ ला
खभत्तेडे मेदहस्लिकंकार गलथप सिथा मनसिला
लूण ८८ इनांकेचूर्णकरकेयुक्त वसा मिंफ वस्त्रकेसा
थवटीबनावे मेदोवर्तिनामबनाकरके लायकेसाथ
पलेटलेवे ८९ तिस्कोअग्निलगाके विंडप्रमाण अग्र
ल अग्रलके छिंडेदाहदेवे अरु इसमेदसाहकर्मकों

हि विपंग्रुवंतिकेचित्तस्मात् मेदस्सावबाहि
नी तत्रश्रेष्ठं मेदोयस्मात् करोति वेदनां ८७
लाक्षावज्रकरालस्सर्जमधुच्छिष्टगुडनटोल
वणैः ८८ एतैश्चूर्णैर्वसाश्रावस्त्रेणकारये
द्वर्तिं मेदोवर्तिका — हृत्वा वैवालकं केन
सेवेष्टा ८९ सम्प्रज्वाल्य दहेद्धि विडं रेभिको
गुल्मेनरभितेः शेसतिमेदप्रवहियान्।
भूसर्वेभूसंस्थिते वाते ९० अस्थिगतेमज्जा
गते इलिते वैदाह्येद्यस्मान्न भूयस्तमवा
प्नोति रोगवातकफात्मके ९१ रोगःसाम्य
तिदाहेन तस्माद्दाहः प्रशस्यते प्रशान्ते यस्य
योव्याधिरग्निनामाद्यनात्मकः ९२ प्रकुप्यते
समस्मुनस्तं चैव परिवर्जयेत् ।

सलाते हैं सभयानओंकेविषैंस्थितवायुकेविषैं ९०
अस्थिगत अरुमज्जाविषैं प्राप्त वातकफके रोग तिन्हां
कों हालैकरके सिनावीदाहकरे फेरउसचोडेकों
वातकफकेरोगनहिंहोने हैन ९१ दाहकेकरणेक
रकेरोगशांतहोजाते हैं तिसकारणतेदाहश्रेष्ठक
हेयाहै अग्निकरकेदग्धकरेया फेरयोवायुकारोग
कोपकरे तिसअग्निकर्मकेशांतहोयदेयां तो तिस

© Dharmartha Trust J&K. Digitized by eGangotri

शा. हो. टी. १२२

122

कीचिकित्साकों त्यागदेवे यन्त्रम कमान सूर्य चक्र व
छि स्वस्तिका वटकेपत्र बिंदु इनकेसमरेखा श्रीवृक्ष मे
हाश्रृंगी करोंकला मच्छ मकर मत्स्य पेट खजूरा इनके
पादस्वरूपकीतरांके दाहकरे इतनेप्रकारकेदाहकरे
जैसाजैसयथाहोवे तैसाहीदेखकेकरे औरहृदयस्था
न मर्म तनी रोमपंक्ति इनास्थानांकोछोडकेअग्निकर्म
करे अथवाबुद्धिमान सूक्ष्मरेखा अरुउपरालीकरे ने
त्रो औरमखोर औरवर्णकेसमहोवे तोहछीतरा द

यन्त्रार्कचक्रशक्तिस्वस्तिकवटपत्रविंदवो रे।
खाः श्रीवृक्षाष्टापदमत्स्यमकरखर्जूरकाप
दाः १३ एते दाहाकार्या स्थाने यथायोग्याः
हृदयं वै सममर्माणि नाभिदेशं व रोमराजीव १४
परिवर्ज्य देहस्यान्तस्त्वभेरिवाभिरूक्षगंभीरे ने
त्रौमध्ये सवर्नेवा सूक्ष्मगद्वयं विनिर्दिशेत्
ततो व्रणस्य वक्तव्यं घृतेनाभ्यञ्जनं यदं तिल
कल्कं घृतयुक्तं कार्यो दालेपनं प्राज्ञैः १६ सं
नानपिटकेदग्धादुष्टोणिसमपिसगैरिकं १७ अ
ग्निकर्मनामाध्यायः मोहनकतरूकनस्वदग्ध
भस्मपंचाटकं त्रिगुणेन लेत्रिगुणेनिद्दिष्टम
भस्कता १८ परिस्कंतनात्रपात्रेतुष्कतावप
वेदग्नो ।

गयहोयाकहे १५ तिसकेउपरांत चोडे
कोंत्रयदिनचेउमाथ्यटकोरकरे औरतिलांकोत्रुगदाघृत
रलाकेलेपनकरेवैद्य १६ यवपिटकापीगुणीयाहोवे
तोद्यायविषेचेउतेगेरीदेवे १७ इतिअग्निकर्मनामाध्या
यः । मोहनतरूचेटापाटल तिसकोंरूखीतरांदग्धकरके
उनकीमणकवासाहालेके त्रयमणपाणीविषेपायके
सनवारीभुणलेवे फेरत्रामकेभांडेपायकेअग्निविषेका
डे यवकरइछीको चमणेलगणवालाहोवे तोतिसमें

© Dharmartha Trust J&K. Digitized by eGangotri

रनांगेघथीयोंकाप्रतिवायपावे क्वाहर्णकरकेदेवे
हिंडू. प्रतोस्त विश मह्यं सेडवेरयां शोना पादानाम
टांटरे कालिवेल ११ पिप्पलामूल रनांसभनांका
हर्णे सरइकविवपादेवे गेरस्तरामदिरा दोसेर मि
लादेवे १॰ यवसासिद्धहोजावे तोउसनेलेकेसेदर
लोहेकेभांडेविषेपाररवे यहेक्षारवैश्वानरनाम।
करके कहेयाहै अरुवहुतश्रेष्टगुणवाला है १

दार्वीकाविलिप्तेयदातत्र हिंसतिवि। ११
षाग्निकृत्साविषघ्नवास्तुकनाशकश्यामाः
कुलामूलंचैषांसर्वेषांहर्णेयेमलान्य।
ष्टै प्रतिवापोदातव्योयोऽपःस्थाप्तःस्वरा
प्रव्यः १॰ सिद्धचोहृत्यैवंविनिक्षिपेदा
यशेशुभेभांडे क्षारोयंस्तमगुणाःश्रे।
ष्टोवैश्वानरोनाम १ दुष्टव्रणेषुदापो।
नाडीकिटिभानिदद्रुकुष्ठानिश्वित्राणिमं
डलानिवंहन्तिसम्यक्कायुक्तस्तु २ हेमंत
शीतमुक्तस्यनिदाघेप्रातरोपिनः वर्षात्त
विगतात्रैवक्षारोभवतिरोगहा ३ पित्तैव
ष्टितयादेयक्षारेवेणुशलाकया

यहेक्षारदुष्टव्रणरसोली अरु ममेसीयां नस्सर
किटभ कोढभेद दद्री कुष्ट श्वित्र खेतकोढ मंडल
कुष्ट रनांकोविस्यकरके योडेआदानासकरताहै २
हेमंत और शिशर मेंनहिदेवे अरुग्रीष्मऋविषे
भोजनकराके प्रातमेंदेवे अरुवर्षामेंवदलनाहोवे
तोदेवे यहेक्षाररोगांकेनाशकरणेवालाकहे
याहै ३ तेवेकरकेहमाष्य वेंतकीशलाइलेप
टकरकेक्षारलावे चोडेकीसमर्थकोंजाणके

© Dharmartha Trust J&K. Digitized by eGangotri

शा. टी. १२६

123

क्षारकीमात्रायोडे ४ क्षारकेरोगविषैलाके उसदे
हस्थानकों नेवे वादलिसाथ खदरते यवसोस्त्रग
स्थानजामएकेफलके रंगसमहोवे औरयमाके
रंगकाहोजावे तवमखीरकेपाणीसाथ वा डुध
ग्रथवातिलोंके कल्कदाजलसाथ क्षारकेस्थान
कोसमकरकेधोके फेरघेउसाथ थोवटकोरकरे ६
फेरमखीरकेपाणीसाथघायकोलेपकरदेवे पहे
व्रणघायकीक्रियाकाक्रमकहेयाहै १ इतिक्षाराध्याय :

इयेविज्ञानसामर्थ्ये क्षारमात्राप्रयोजयेत् ४
विकारपातितः क्षारः पित्तप्रक्षालितेदेहेत्
नेत्रभावेस्थितेविंधोद्धस्समनिभयदि ५
मस्तदकेनपयसातिलकल्कोदकेनवा क्षा
राग्रमशमंकृत्वासर्पिषापरिषेचयेत् ६
मस्तदकेनात्रलिंप व्रणप्रोक्तक्रियाक्रमः
क्षारोध्यायः। यथाशालेदहस्संजलके
दारसंस्थित तद्धस्यएदहतिपोपिते
वाजिनोस्थिते ८ रुधिरेणप्रदुष्टेनदस्यमा
नस्यदेहिनः नामहसायनेकिंचिन्नका।
र्यकोवसेवन ९ तस्मादष्टस्यरुधिरप्रदुष्टम
वसेचयेत् दोषारक्तावित्तायस्मादाहानां।
ख्लसर्वदा १०

जैसेगार्मेजलकारेविधैस्थि
तहोयादाहशालियानाकोदग्धकरताहै तिसकी
न्याईप्रगणाविकृतरुधिरस्थित घोडेयाकोदग्ध
करताहै ८ उष्टरुधिरकरकेदग्धहोते घोडेकों
लेहकुरानेदेयरें होरऐसी जैषधीआविहारका
वालीकोरनहि ९ तिसकारणतें घोडेकाविकारर
हनिकालदेव निश्चयकर्केचोर्यांकोरोगलहूके
हिग्राश्रयरहितेहैं तिसतेसदाहीरुधिरकाढणीचार
प १०

© Dharmartha Trust J&K. Digitized by eGangotri

निसकारणते घोड़ेयांकायोरुधिरकढणाहै सोसभ
रोगांकेहरकरणेवालाकहेयाहै औरढरणेवालेका
थकेहोएकालिसावालअवस्थाअरुद्धा इनांकाल।
लोहूनहिनिकाले ॥ जिसघोड़ेकालहूकढणाहोवे
निसनूंपहलेघृतपिलालेवे स्नेहकेपीनेहोयांदोषप
तलेवगनेवालेहोजानेहैन सोस्नेहकरकेमूर्छितहोये
ओकानाड़ीयांकरकेसुखकेसनावीतिनांकाहरणहो
ताहै घोड़ेयांकीयांचौहटनाडियां वढणेछेककरणा

अस्कन्देकस्नातस्नेषांसर्वदोषावकर्षणः
भीतेश्रान्तेक्लान्तेबालेरक्तहृदमवेक्षयेत ॥
शिरायस्यभवेद्धयान्तसर्पिःपाययेद्धय
द्रवीभवन्तिदोषास्तुस्नेहपानेनमूर्छिता १२
ङ्गुनानांहरणंचापिशिराभिःक्रियतेसुख
वतःषट्शिराछेद्याभेद्यावेध्याश्चवाजि
नां १३ स्फिक्षणीस्तनगायाचशिरेद्वेद्वेश्व
कीर्तितेमूत्नायास्तुनरोष्टेचछेद्येद्वेशि
रेमते १४ एवमष्टौशिराछेद्यानिर्भेद्याः
षोडशाष्टाणुस्नवेशेखललाटेवताल।
प्रोथाश्रयातन्तो १५ द्वनुनेकणेनेद्वे।
द्वेशोषावेध्याःशिराःस्मृताः पदेशिराच।
तुष्षष्टीयासुकर्मप्रतिष्ठित १६

चीरणेवालीयांकहियांहैन १३ स्फिक्षणीमेदो उ
नरांमेदो मूत्रविषेदो उतरकेओठविषेंदो एहेअ
ठशिरानाड़ीयांचीरणेकहियांहै १४ एहेअठछे
घकहीयांहैन अरभेघयोसोलांहैनसोसणस्नव
शेख ललाटतालू प्रोथ अरुकपान हनुकर्णइनांके वि
षेयेहै नाड़ीयांदोदोभेघकणे इकइकणेकहीयांहैन
औरसभवाकीदीयांनाड़ीयांवेघकहियांहैन इसप्रका
रचौठसिराहैन जिसजिसकार्यवास्तेकहियाँहोनतिस
विषेकरे १६

शा॰
टी॰
१२४

124

नालूकीयां त्रययोरेखा है तिनांको छोडके अरु नालू
के दोनें पासे दो दो वा सवा दो अंगुली छोडके नालूके अ
अगे कीयां सिरांको वेधे १८ यो श्रोथ की नाडी है सो पुटों
के दो अंगुली ऊपरतें वेधे अरु ये ललाट विषें हैं सें अत्ति
कोणतें दो अंगुली की विथ्यर है यो अस्कपान की सिरा।
है सो नेत्रों के दो अंगुली हेठतें अरु शंख की अपांग तें
अवटे ने हो अंगुली उपरतें अरु स्तवकी सयितें वेधे ना।
डीयां १९ इसतें उपरंत निश्चय करके पार्श्व के हेठ चार।

उर्मीस्निसस्तनकांवंशस्योभयतोंऽगुलेस्ता
है हंगुलमध्यनाल्वग्रनालश्चो है शिरेवेधे
उपरि वधूटयोरेवलु हंगुले श्रोथजं वेधयेत्
हंगुले वात्तिकूटाह्ललाटश्रितेह्यंगुलेच
वथ्वापाध्यधस्तात् १८ शिरेवास्रुपानाश्रि
तेह्यंगुले वाप्यपांगात् शिरेशंखेनेह्यंगुले
चपरिष्टात्स्तवसेवसंधेस्त्तवेधयेत् १९
अथ खलु विडभागयाश्वीदयस्नाश्चनाभि
स्तथैवांगुलेः स्वस्तिकेनैव वध्वा सिरकणे
नेवेधयेत् हंगुले वाहुमूलात् तथोरस्थया।
वेधयेत् २० षड्भिरुर्ध्वं किणादंगुलेवाकुम
ध्यस्थयोर्द्व्यंगुले वाप्यधस्तात् किणास्पृव
पार्श्वयोर्वेधयेत् २१ उपरिवत्नेरंगुले कूर्व।
भागस्पृष्टनात्तु नोरध्यधस्तानथैवाषिके

अंगुली विडुभाग निसको स्वस्तिकयंत्र साथ वंनके कणी
कोयां नाडीयांको वेधे यो उरस्थ छातीके बाहूमूलतें दो
अंगुली छोडके वेधे २० अरु किणस्थानतें छे अंगुली
यांकसके उपर बाहूके मध्य स्थित यो है तिसतें दो अंगु
ली हेठ किणके पार्श्व तिनांको वेधन करे २१ कूर्च भाग
के चार अंगुली उपर अरु नालु यांके छे अंगुलीयां हेठ
रेषका है तिनांको वेधे अरु कर्णिकातें दो अंगुल उपर

विषेंकूर्चेतिनकोवेधे अरुयाकरनेकियाँहैन सोकहीतें
अठअंगुल अरुकोष्टकीनाभितें अठअंगुलीऊपरतेंवेधे
अथअववस्तुनिकरकेकरूयाहोयायोयंत्रककर्कटनामस
स्थानवेरकारके तिसतें अंगुलिवेसपार्श्व अरुतेसेही।
आसनतेंदोअंगुली इसप्रकारचारअंगुली छोडके ऊं
वकेविषेंयोशराानाडीयांतिनकोवेधे अरुपुच्छमूल
नेदोअंगुलीअगे अरुडंवकोपलटके अगेकीनाडीवे।
धनकरे २२ औरपिंडकेपटोंकेहेठतेंवारअंगुलस्थान

वेधयेद्धस्तलेऊर्ध्वंदिकायामथोद्धेनेवकूर्चं
योर्वेधयेन्कर्णेकर्णनोष्टांगुलेनाभितो
ष्टांगुलेकोष्ठेवेधयेत् २२ अथस्तनिको।
ष्यितेनयंत्रेयणवेककर्कटास्येनवस्थानतो
द्व्यंगुलेवेसपार्श्वेनथैवासनाद्द्व्यंगुलान्सेव
ववारिसुत्कापिरेपुच्छेनेवधयेत् द्व्यंगुले
पुच्छमूलाच्चसंवेत्यपुच्छस्याग्रेपिरेपुच्छे
नेवेधयेत् २३ अथस्ताडरुपिंडमांविस्त
व्यचतुरंगुलेउपाडुनेपिरेवेधयेशास्त्रे।
नविज्ञानता २४ उपरिष्टात्द्व्यंगुलेनरो
मान्तखुरसंधितः अंगुलेपार्ष्णिणीपाडवरो
मानेतत्रवेधयेत् २५ संधिभागाद्द्व्यंगुलेथः
स्योवत्तेवधयेत्स्युरे शोधयित्वात्नमद्रकोन
लनेवेधयेत्पिरे २६

छोडके शास्त्रकेजाननेवा
लेवैद्यनें उपांकोयानाडीयांकोवेधकरणेयोग्यहै २४
और रोमान्त अरुखुरसंधितें दोअंगुली ऊपरनो अरुपा
र्ष्णिणी इस्त्रीकेत्रयअंगुलीहेठतेंवेधे रोमांतविषे २५
अरुसंधिभागतें दोअंगुलीहेठ स्थावरनकीयां अरुस्र
णकीवेधे आरुपादनलकियांनाडीयां मंत्रकोपुरक
रकेवेधे २६ ॥ ॥

भा.
टी.
१२५

125

और अगेके वा पिछेके संधों विषे सदाहीं इसन तें सिरा नाडी
यों वेधने कहिया है वायु करके ला हूआ गवाला पित्तनें का
ला अरु कफनें पिछल चिपानो वाल अरु सभनें चिन्हवा
ला होवे तो सन्निपात तें जाणें २८ यो रुधिर सहै के लहू
वागरहै सो शुद्ध कहिया है तिसके विकृत होए देयां ति
सडु हूल हूकों बाहर निकालदेवे इसके वलकके स्व
भावतें ही सिरा नाडी स्थिर नहि रहती २९ अरु मत्स्यकी

पूर्वापरेषु पदेशु पववेध्याः सिराः सदा
रक्तवातान्न्सफेनं पितान्नूलं समपिच्छलं
तु कफात् सर्वैर्लिंगैर्युक्तं तत् सन्निपाता
हि जानीयात् २८ पाशशोणितवत् शुद्ध
नश्यते स्रावयेदस्कदुष्ट सिरात्तस्मात्
तानास्ति वलाहोषास्वभावतः २९ मत्स्य
वत्परिवृत्तं तत्स्माधचेन वेधयेत् रक्तये
पु विकारेषु इस्वेरक्तावसेचने ३० ततः पि
त्तसमुद्दिष्टां क्रियां सर्वां प्रयोजयेत् एवं
वाते च पित्ते च कफे रक्ते न वाजिना ३१ सा
धारणीं क्रियां प्रोक्तां पथ्यां ये व्याधयो मताः
रक्ते प्रदुष्टे मात्रेत्ति प्रेयदि न सिच्यते सम
नस्योरक्तापी वेज्वरश्च संजायते त्विप्रं ३२

माई सो रोग पायके फिरतो है तिसकारणतें यत्नकर
केवेधे रक्ततें यो विकार है तिनोंमें पहले लहूनि
कासना गुण है ३० तिसके पीछेतें यो पित्त विषे वि
धि चिकित्सा कहि है सो सभकरे इस प्रकार वात पित्त
कफ रक्त करके घोडेकों ये रोग करें इनोको पट्टे साधार
ण क्रिया कहि है ३२ यव थोडे काल हू विकृत होया है ति
सको सिता भी बाहर कढदेवे नेतो तिसको उस छातीमें
मोंनाप ज्वर निश्चय करके सताबी होजाते हैं न ३२

© Dharmartha Trust J&K. Digitized by eGangotri

सभऋतुओंविषेंरुधिर शांतसमेंनिर्मलदिनमें ना
नोवऋतगमी नावऋतठउहोवे ऐसेकालविषेंलरू
कडनेयोग्यहै १४ अरुचोडेकोंपाणीपिलाके औरथ
केमेकोहटाके अरुवनकेचोडेकोंवेधकरे अरुनाडी।
वेधकरकेचोडेनूं १करात्रखानेकोंबुद्धिमानकछुन
हिदेवे नातोचलावे १५ फेरवरतकेपीछेचोडेनांई
क्रमकरकेखाणादेवे पूर्ववत्‌टणघाय फेरलूण फेर
ग्रासअरुपाणीथोडागमेदेवे १६ इतिशिरोवेधविधिः

एवींक्रेविमलेकालेनातिशीतले
सर्वेष्वृतुसकलंशोणितस्रावि सेवन १४
पानीयपीनमश्वंविश्रांतेयंत्रितविध्येत्
विद्धंतचारयेदश्वंरात्रिमेकांविचक्षणः १५
उपोषितायदातव्यंक्रमेणैवचखादने १६
एणतिलवणग्रासंपानीयंमेदमावरेत् १६
शिरावेधविधिः स्वेदःकफवातहरोपि
ष्वनिमोक्षणोरुजाघ्नश्च कायस्यमार्द
वकरःपापथ्यानापावनस्तेव १७ अभ्यक
स्यतदोषाःस्विन्नस्यद्रवीभवंतिवाश्वस्य
स्त्रोतोमुखमापन्नाःशास्त्रेणतन्निर्हरेत्
स्मात् १८ भंगस्वेदःशाकरवालकत्रिशाकु
नसाककललाश्च।
अवस्वेदकहतेहां स्वेद
कफवातहरहै औरएष्ठतेशाहरइनकोखोलताहै पी
डाकानाशकरताहै अरुसोजेकोपचादेताहै १७ अ
रुच्छतनेलकरकेअभ्यकमालामकरेहोप औरस्वे
दकीनेहोपहोडकेदोष वगनेवालेहोजानेहैं अ
रुनाडीयोंकेमुखविषेप्राप्तहोयोंकों शास्त्रकरके
पीछेनें वाहरकाडदेवे १८ अरुभंगास्वेद १ शाक
१ २ वालक १ त्रिशकुन ४ पुलाक कलला नष

शा. पिंड कूर्पफला ए हेद शाखेदकहेन ४९ अग्निमेष्ठ
हो. कषगडीला ४ रसिर तुलसी अंक परण विलण सह
१२९ जण इनोंदेपत्रोंकेजलोकेकाथका सोभंगस्वेदक
हेयाहै ४९ यौउ कुठ हाथी इनोंकियालिंदालेके गो
रउयनैमठामिलाके गेरभंगस्वेदकेयोपत्रहै तिनो
केसाथ सोनिश्चयतें शंकरस्वेदकहेयाहै ५० योप
रणकेपत्रोंकेविचलेनरकीमूठ कपडेसाथवत्रके
अरुतिसकों ठीकेरविषे वकृतहल्छीनरांभने एहेवा।

126

एषपिंडकूर्पफलाःस्वेदाएतेदशप्रोक्ताः
४९ नक्तोरीवर्षाभूसुरसार्केरंडबिल्वशि
ग्रुणां पत्रैःसलिलक्काथाभंगस्वेदःसमा
ख्यातः ४९ नरगोहवारणानांउरीषमादा
यदधिपयोमिश्रं अंकेवस्त्रभंगैःस्वेदः।
स्वल्पशंकरोप्रोक्तः ५०। एरंडदलानरितो
वधावस्त्रेबालकामुष्टं नीत्वाकपालभृष्टा
मेषभवेदालकास्वेदः ५१ गोखरतुरगगु
रीषाणिदधिपयोभिश्चमिश्रितेरेभिः स्वि
नैवस्त्रैभंगैर्वेहेम्निशाकृत्स्वेदःसमाख्यातः ५२
माषान्सवान्कुलत्थान्निष्पावानस्वेदयेत्तथा
वस्त्रंसवदाम्लीवासानवपुलाकःस्मृतः
स्वेदः ५५

लकस्वेदकहियाहै ५२ अरु गोका
गोहा खोनेकीओर घोडेकीलिद अरुउपतेमठा इ
नोंकरकेमिलावे इनोंकरकेसेउहापवस्त्रोंकेसाथ
भंगस्वेदकेयोदयकहेन तिनोंकरकेवेने इसस्वेदा
कानामशिरहत्यागरकहेयाहै ५३ महां यवो कु
लत्थ मउवो इनोंकों सेउके फेर वस्त्रविषेवेनके
वह्नन गरम करके योस्वेदहै सो पुलाकनाम
स्वेदकहियाहै ५४

© Dharmartha Trust J&K. Digitized by eGangotri

और कनक धान मूली प्रियंगु फूल फरंग अथवा कंगु
नी पहिले दूधसाथ सेदकर्के ४५ तिनांको सीलगमें क
रके यो स्वेद है सो कललक हिआ है थोडेके शास्त्रजान
नेवालियों ने जलविषे सेडके यवांको और तीसराहि
सालूण वहुतगर्मी भुडीविषे वधे हो ४६ इनांको व
डेगमें यो स्वेद देवे सो तषस्वेद कहिआ है कृषाणाविव
डी वा तिल वाउल इनांकरके वा क्षीरणकरके वा दूधवि
षे सिद्ध अन्न ४७ और तिल मह्हा कुलथ इनांकरके यो सो

गोधूमशालिमूलकप्रियंगुभिः क्षीरसंयुतैः
सिद्धै ४५ नैस्तस्त्रवोलैः स्वेदः कललश्चोक्तस
शास्त्रज्ञैः वारिसिक्तांस्तु तुषान्त्रिभागलव
णोष्णांस्तु तैर्भ्रष्टान् ४६ वध्नीयात्तान्घट
केषु तं स्वेदं इत्युक्तः कृशरेणपायसैर्वाऽ
ल्माषक्षीरसाधितैर्वापि ४७ तिलमाषकु
लत्थैर्वा पिंडः स्वेदः समाख्यातः कूर्पान्पा
षाणाद्यान्वह्निना संतप्य कारयेदुपरि ४८
क्षीरेण सेवितानां वाष्पेण स्वेदयेन्मृष्ठे मह
नावस्त्रेण हृद्यः श्रोणीं वत्रिकेव संवृतः को
ष्ठः ४९ कूर्पस्वेदः कथितो व्रणस्वेदं प्रवक्ष्यम
धामने अतसीतिलगोधूमान्किण्वं लवण
च कारयेत् हृदौ ५० दग्धमास हृदमं पीयनहृ
नन्तीवामयेत्युक्तः ॥

पिंडस्वेद कहिया है कूर्प ठीकर पथ्थर इत्यादिक तिनां।
को तिनांकों अग्निविषे तपत करके उपरसेके ४८ दूधक
रके सेचन करणेसे योउपर हवाड है तिसकरके सेकदे
वे मस्तक अंडविषे देवे ४९ अतयोडेको श्रोणि और त्रि।
कविषे वस्त्र वस्त्र करके लपेटके स्वेदकर्णे योग्य है प
हे कूर्पस्वेद कहिआ है सो व्रायके स्नावको समकर है ५०
अलसी तिल कनक तिलखल लूण इनांका चूर्ण देही

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ टी॰ १२७ केसाथरलायके बुद्धिमान एकराज़रखेछोडे उसकेसा
थछोडेकोलेपकरके अरुउपरबहुतुवस्त्रदेके फालखे
डकोअग्निकेसमगरखोकरके उपरफेरबुद्धिवालावैद्य
पहेफालस्वेदविक वाहलगिनवाले छोडेकोश्रेष्ठकहे
आहै ५२ अरुपृष्ठस्तंभ उरुकर्णक मन्यास्तंभइत्यादिरोगहर
रहै एकनिर्वातस्थानविषे घरजागबनावे अरुचारद्वारक
रकेपुरुकगिरदबणाके उसकेविचघोरेकोवाउकेसुंदरह
छीनदावतके स्थिरकरे फेरउनांचोंनाडराजेयांविषे वह्नी

अदिहेतेननवहनेवसंहकुम्भानतोनेरेतत ५१
वह्निसवर्णेफालेचरितेनबनाययेन्मतिमान्
फालस्वेदस्त्वेषांप्रोक्तस्त्विकवाहलेगिनोश्रेष्ठः १२
पृष्ठस्तंभोकर्णमन्यास्तंभादिरोगहरः निवा
तंशरणंकार्यंचतुर्द्वारंमहत्तिकं ५३ प्रवेश्य
तुरंगंतत्रसम्यकंयंत्रितेस्थिते ततोद्वारेषुते
ष्वग्निज्वालयीतपृथक्पृथक् ५४ तत्रतंस्वेद
येद्वैद्यःसार्द्धवेलेनसंवृतः विषगवातमहा
स्तंभउरुकर्णेवातशूलिषु ५५ इत्येतद्यत्रकस्वे
दःकार्यःसर्वगतेनिले सकर्णेरंध्रयापरेनि
मुष्ठेगुह्यस्थानराणिच ५६ प्रतिद्वारानियदाष
ष्टमुखंचपरिसुष्यति नदास्वित्तरंगनितो।
याःप्रवलागोनवस्थितः ५७

वनिअग्निजगादेवे ५४ तिसघरविषेघोडेकोवैद्य।
स्वेदकरावे गिलेवस्त्रसाथलपेटहोएको अरुइनांरो
गांविषेंपहेस्वेदकरावे विषकवात महास्तंभ उ
रुकर्णक वातशूल औरसर्वदेहगतवायुविषे पहेय
त्रिकस्वेदकरणयोग्यहै यवकनांकेद्वारोंते गुदा
अरुगुह्यस्थान औरअंदरतेपरसावगे औरमुखसके
अरुअंगहलणतेरखवानहिहोसके तोजाणे अव
स्वेदहलाहोयाहै ५८

127

© Dharmartha Trust J&K. Digitized by eGangotri

औरअतीसार ज्वर दम कोढ पित्तरोगवालेक्रिमिगर्भ·
वालीस्त्री जिनांदाउदवकृतव्रणगयाहो इनारोगांवा
लेयांकोस्वेदकरणाश्रेष्टनहिंहै ८८ इतिस्वेदविधिः
अखियांकोपहिलेगोमूत्रसाथ अथवा निंबकेकाथ
साथ धोयकरके रुईपट्टेकरके पीछेतेहोरप्रक्रियावि
किन्साकरे ८९ मुलहठीपीसकरकेदूधकेसाथकाढ।
के अखियांविषेंआश्चोतनकरेकाविडसाथअतीसार ९०
णीयां पहेस्त्रीउयांकोवकृतश्रेष्टहै औरनेत्रांकोहितहै

अतीसारज्वरश्वासकुष्ठपित्तविकारषु कृमि
गर्भोदरानेत्रस्वेदानेष्टाविशेषतः ८८ स्वेद
विधिः प्रक्षालनयनामादौगोमूत्रेणाथ
वाकषायेण निंबस्यततःपश्चात्प्रयोजयेद्
क्रियामन्यां ८९ यष्टीमधुकपिष्टंपयसाके
थितंनेत्रयोःअर्थात् आश्चोतनमेतत्सर्वेषा
वाजिनांश्रेष्ठम् ९० मृषणसैंधवगैरिकस
मनालतालीसपत्रलाक्षाद्भैः सुरदारुकुष्ठस
रसोमनःशिलाशंखफेनैश्च ९१ मंजिष्ठात
गररसांजनैश्चवकाद्रुबीजसंयुक्तैः प्रभि
वारुणिमंडेनपेषितैःकारयेद्वर्तिं ९२ तां
वर्तिंमहतोछायायांपरिशोषयेच्चापि यस्या
श्चश्रवतेनित्यंकंडूरेयस्यलोचने ९३

मर्चां मरिच संढ सैंधवलूण गेरी मालती तलीसपत्र
लाखवहेडे देवदार कुठ तुलसी मनशिला शंख समुद्र
फेन ९१ मजीठ तगर रसौत हेडवांकेबीज इनांकरकेयुक्त
अरुवारुणि मदिरकायोउपरकामंडहै तिसकेसाथइनां।
कोपीसकेवटीवनालेवे ९२ सोवर्तिगिर्दकरेतेंछायावि
षेंसुकालेवे जिसघोडेकेनित्तअखीतेंअस्रुपातवगनेर
हते है औरजिन्हांकीयांअखियांमेंखरकहोवे तिस्कोंइस
वटीकरकेनित्यअंजनसलाईपावे ९३

© Dharmartha Trust J&K. Digitized by eGangotri

था॰ हो॰ १२८

128

हरीड कंडिआरीकेपत्र कादि लोहचूर्ण मधां सैंधालू
ण इनांसमभनांको पीसके निर्मलजलविषें घोलके का
ढे यवघनीहोवे तो छाणकरके तांमकेभांडेविषेधारेरा
खे ९५ पहेसलाईचोडेयांकेनेत्ररोग हरकरणेको व
हुतश्रेष्टहै और मासवधजाना पटलकावप्रवारक
फोला ९६ मखीरसाथचोडेयांके इनांरोगांको सम
करतीहै कंडेआरीकेफलमुलठी मनशिला ग्रामेदि
जचूर्ण ९७ जितनियांसमवस्तूहैं उतनासैंधालूणपावे

वर्त्तानेमेतयानित्यंमेनयेन्मतिमानिभषक्
श्रभयाहहतीपत्रंकाशीसंलोहचूर्ण मधु
कंसासैंधवञ्कोष्ट्रामश्छेमलिलसमा
लोड्य क्वथितंतत्समधूनोभूतंपरिस्रतंताम्र
भाजनेस्थाप्य ९५ अंजनमेतच्छ्रेष्ठं रगाणां
नयनरोगहरं मांसाधिकानिपटलंकाचश्च
वारकंशुक्रंच ९६ तोरुणसमायुक्तंप्रसमये
वेतदष्णानां हहतीफलानिमधुकंमनःशिला
ताम्रंजरजश्चैव ९७ यावन्मात्रंसर्वेतावन्मात्रंच
सैंधवंदद्यात् पिष्टायमानेनतत्प्रलेपयेताम्र
भाजनमनेन ९८ गुमानिधापयेन्नित्यमेवंत
समवाञ्माणि अम्बुसजलेपिष्टंतदंजनंनेत्रयो
भिषक्कुर्यात् ९९ लिखतिपटलानिमांसंशु
क्रंवनाशयत्याशु मनिष्ठाहरितालमनःशि
लागैरिकंचदारुनिशा १००

फेरवकरीकेदुग्धसाथपीसके इसकने ग्रामेदा मांग्रा
लिंबदेवे तिसकोंगुप्तस्थानविषेंरखे उसपात्रमेंस
नदिन रात १० फेरउसपात्रतेंलेकरके जलकेविषें।
पीसके वैद्यआंखियोंविषें अंजनकरावे ९९ मांप
टल छोडदे तिनांकोंछिन्नदेतांहै मांस फोलाचिटाहो
जाणनेत्रका तिनांकोसिनावीनाशकरहै मजीठहर
ताल मनशिला गेरि दालहरदल १००

© Dharmartha Trust J&K. Digitized by eGangotri

मद्यं मरिच सूंठ योम लाख लोध्र सभसमभागपी
सके वतीकरे अरुकफकेनेत्ररोगविषें चोडकीअं
खीमें लगाईपावे औरवी योअन्नीरोगहै तिनविषें
पावे ११ चिरमद्य मद्यं लोध्र रसौंत वायविडंग ह
रीड भलावेकेफल इनोंकोपीसकरकै लोहेकेभांडेकों
इनोंके कल्कसाथ वैद्यतिसकोंलेपकरे सतरातो उ
सकोंरखछोडे ११ पहेंअंजनचोडेयाकेफिरकइमादि

कटुकत्रयंरसोनंलाक्षालोध्रंसमांशा-
नि पिष्ट्वावर्तिःकार्याःकफजेनयनामये
नेरोगस्य ११ अञ्जनमेतत्कफादन्धस्य
हितरोगेषु स्रोतमरिचानिकल्कालोध्र
सांजनंविडंगानि ११ अभयाभल्लातका
फलंपिष्ट्वाकार्ष्णायसेपात्रे कल्केनाने
नभिषक्प्रलेपयेत्सप्तरात्रेमुषितन्तु ११
अष्टकेष्वादिहरंतुरगाणामंजनंप्रोक्तं ४
लेखनीयांजनानि हरीतकीफलानिसं
धीरसांजनंगैरिकंविडंगानि मरिचानि
निष्कलबीजंगंडीरसर्षपामधुकं ११ प
लामलकंविवीस्तरसाकालानुसारिवा
मूर्वा शिग्रुकणाहरितालंमनःशिला
वीरकंकटुका ११ श्यात्ताम्ररानिगवां
मूत्रेणनाम्रभाजनेसत्तुयान् ।

केरोगहरणेकों वहुतश्रेष्ठकहेयाहै ११ लेखनी
यांजनानि केरआरेकेफल सूंठ रसौंत गेरी वाव
डिंग मरिच वैंत मोकरी करेला सरसों मलठी ला
वीयां आमले करसी तलसी कालिवेल गलोट स
होजनो वाचां हरिताल मनशिला वीरआकोड ११
इनोंकोगोमूत्रसाथ महीनकरके ताम्रकेभांडेविषड
ालवे ।

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ यवपहेमकनावे फेरइसीतरे सतवेरी भावना
हो॰ देवे ७७ कपिलागौकेदुग्धकरके ओरकांपरोलके
१२९ के ओर मरुओकेरसविषे ओरआमलेदेरसकेविच इ
नामैंभिन्नभिन्न इकइकविषे भावना बुद्धिमानदेवे ७८
129 वारेवार सकामकाके भावनादेवे इकइककी ह
छीतरे भावनालगीहोइयो जानके जवसकजा
वे तोग्रछीतरेपीसलेवे ७९ इसकोंनेत्रविषे अंज

पतक्कंक्षंसुमेव भावयेत्सप्तकृत्वान् ७७
कपिलायास्तुक्षीरेण कांस्यनीलैः फणि
जकरसेन आमलकानां वरसेनैकैकंभा
वयेत्सप्ततः ७८ भावयित्वा च तथा च सु
कंक्षंसकृत्सकृत् भावितं चैव विज्ञाय
भूयः सुक्ष्मंपपेषयेत् ७९ अंजयेच्च तदृशी
तेन षीतले शोपिसेचयेत् पतस्रवाके
मुंजं मुंजजाले चिरोषितं ८० इतिश्चूर्णी
ननेश्रेष्ठमादेरेण प्रयोजितं मरिचरसांज
नकृष्णात्रिफलासिंधुसलोहचूर्णीस्त ८१
सतालापिष्टवर्तिच्छायायां शोषयेन्मतिमा १
न् कंडूसतिमृंराहन्यात्तृगराजरसेन वा ८
सोरसैरकरानाश्वस्कंदतोद्देण योजिता

नकरे फेर शीतलवस्त्रसाथसेचनकरे शिरमें प
हेसलाई प्रवारकसारी प्रतिविषेजालामुंज ओर मु
नजाल चिरकालका ८० पहेश्रेष्ठचूर्णीजनविधि
साथपायाहोया इनारोगोकोंनाशकर्ताहै ८१ मरिव
रसौंत मंशा हरड वहेडे आमले सैंधालूण लोहचूर्ण
इनोंकोमहीनकरके वटीगोलीवनाइके छायाविषे स
कावे बुद्धिमान सोअंजन भांगरेकेरसकरके पायाहोया
खुरक ओरतिमरकोंहरनाहै ८२ अकतलसीकेरससें

© Dharmartha Trust J&K. Digitized by eGangotri

लङ्कीयांरखांकोकहतेहै मन्नोरकेसाथ अतिआवकें
छूतसाथ अञ्जोसोरवकों नेत्रसंकोचमें गौकेदुग्धमेंप
टलतें ८२ कांपरोलसाथ काचरोगकों मरुञ्जकेरस
मैंनशानेकों अरुमनुष्यस्त्रीकेदुग्धकरके फोलेकोच
सकेपावे ८४ अरुतेलमेंपीसकेहरिषिकाकों रसांञ
नुपानीकरके रतनारोगकोंहरकरतीहै ८५ यहेअंज
नमाषप्रमाणचौडेयांकोंवैद्योंनेकहिहै औरशीत
कालमेंप्रातऔरसांके अरुतीक्ष्णामेंअथिपावे ८६

छूतैः पुष्पाक्षिरोगंचगोस्त्रीरैः पटलंतथा ८३
कासवनीलैस्तथाकाचंनुक्तांध्यंचफणिज
कैः उद्धृदमात्रुषीस्त्रीरैर्हस्तासम्यकनिय
च्छति ८४ माषपरिमितमंजनंशुलमनुर
गस्यशास्यतेतन्नैः प्रातःसायंशीतकालेव
हितंचतीक्ष्णाहे ८६ तैलेनहरिद्राहषिकांव
वाविनांहंतियोजिता ८५ कर्षौमनःशिला
यासैंधवकर्षमन्थेवशकेरायाः द्वौचरसा
ञ्जनकर्षौमधुसंयुतंमजनंश्रेष्ठं ८७ पिप्प
लीलाभयामांसीवाहिफेनमञ्जकम नी
लोत्पलंशंखनाभिंसौवीरंमरिचांजनं ८८
लोहचूर्णंचकांचचस्मशुक्ताचूर्णानिकार
येत् नदेनदंजनंश्रेष्टंतिमिरेसंप्रकी
र्तितं ८९

दशमासेमनशिला और सैंधालूण
मासेदश षंडवीमासेदश औररसौतवीहिमासे २
नकीसलाईमरवीरसाथबहुतगुणकरहै ८७ मजी
ठाचीयां हरीड [illegible] हफीम केसर नीलकमल वाना ८८
पे शंखनाभि शंखचंदनसुरमा मरिच कालासरमा
लोहचूर्णकच रतनाकामहीन चूर्णबणावे सोयहे
अंजन तिमिरकेवास्ते बहुतश्रेष्टकहेयाहै ८९

© Dharmartha Trust J&K. Digitized by eGangotri

धा॰ और मुंज मुंजजाल बुद्बुद अश्रुपात अभिघात चोट
टी॰ लगणी और अक्षिपी ली यों हो जावें यों इनों रोगों वा
१२० लियों को गुण करहै ९० इति अंजनकल्पः जीवक
ऋषभ पद्मकाष्ठ लोध रेवसकालिवेल मुलठी का
130 कोली क्षीरकाकोली वंदन विदा कमलमूल भप छ
हारे दाख तिल स्याली और पंचवल्लीरहूल वडीवड हंव
ल पलासतथा रसपिप्पल तिन्हों का कल्क मजीठ सन
हीर इनों को दुग्ध के साथ पी हके चोलले वे ९२ और

मुंजेषु मुंजजालेषु बुद्बुदेचाश्रुपातिषु अ
भिघातेषु पातुं च यदञ्जनं नेत्ररोगिणां ९०
अंजनकल्पः ऋषभकजीवकपद्मकली
ओशिराणिशारिवामधुक हेकाकोली
वेदनघालूकविसानिखर्जूरे ९१ द्राक्षा।
तिलाविदारी पं चानां क्षीरिणांतथाकल्क ९२
मंजिष्ठां सपयस्यापिप्पलीपयसां समालोड्य
दशमूलरसाढ्येनतमधुसर्पिःशर्करासमा
युक्तं दद्यात्वपयो वस्तिवाराणंवाथवास।
म ९३ सर्वमांसस्वरसमधुराहारांभोजन।
यित्वाततः अथजीवनीयपक्केन सर्पिषावा
नुवासयेदक्षम् ९४

दशमूल एवं कहेया
है तिसका रस अथ मिलाकर्के और मद्योर घेउ खंड
इनों के युक्त मिलाके पयवस्ति नामपछकारी पंज
वार अथवा सनवार देवे ९३ अरु सभप्रकारके मांसर
सके साथ भोजन खुलाकर्के अथवा चोहुंको जीवनी
यगण पुरुषाक पालक भेद माषपर्णी मुद्गपर्णी
काकोली क्षीरकाकोली जीवक ऋषभ मेदा महा।
मेदा मुलठी इनों कर के सिद्ध की या यो घृत है तिसके
साथ अनुवासननाम वस्तिपछकारी वडावे ९४

© Dharmartha Trust J&K. Digitized by eGangotri

इछीनंतांक्षीरवस्तीके चडापेते गुणायोकेहैहं सो
कहतेहां घोडेयांके वात पित रक्तकानाशकरती
है ओरहितहै वलकरहै आरोग्यकरहै ओरसुख
करहै ओरदेहकोस्निग्धकरहै वीर्यकोवधातीहै
ओर येघोडेरुधिर पछावसाथकरतेहैं येमूत्रकृ
छ्रकरकेपीडितहैं ९६ येथकेहैन अरुविवर्णहो
पन भारसाथदुखितहोयहैन ओरजिनांकोकेडद
डहोए येडेटेकेमूर्छाहोगईहोवे अरुक्षतचायकर

सम्यक्कृतस्यगुणावदंतेक्षीरवस्तेस्तु वा ९५
तेपित्तरक्तेप्रणाशयेद्वाजिनांहितोवलः
आरोग्यार्थेश्रेष्ठः सुखोवहः स्नेहनोहृष्यः
मेहंति शोणितंयेतमूत्रकृच्छ्रादितास्त्र ।
येवाहाः ९६ श्रांतायेचविवर्णाभारेणपी
डितायेपामादंडुयेषापतितायेमूर्छिता
क्षतक्षीणाः ९७ ग्रीष्मशारदीचवाहायेचे
वोस्माभितमास्तु तेषामस्तेतनसमोहित
पथक्षीरवस्तिरस्यानां ९८ शर्करापलमेकं
स्यान्मधूकस्यपलद्वयं पलंघृतस्यतैलस्य
क्षीरस्यापिचषोडश ९९ क्षीरवस्तिःप्रदा
तव्यः कोष्टदाहनिवर्हणः इतरवस्तिवानं
दद्यादेभिश्रमेषजैः १०० क्षीरविधिः ।

केक्षीणहोन ९७ अरुग्रीष्मशारदऋतुमें गर्मीक
रकेतप्तहोन उनांघोडियांकों पहेक्षीरवस्ति अमृ
तकेसमहै ९८ खंडचारतोले महूअठतोले अठ घृ
तचेउतोलेवारा दुधसोलांतोले ९९ क्षीर वस्ति
देणायोग्यहै सोकोष्टस्थानकेदाहको हरकरणेवा
लीहै ओर उतरवस्तियोहै सोभीइनांओषधीयांकर
केहिदेवे १०० इतिक्षीरवस्तिविधिः ॥

© Dharmartha Trust J&K. Digitized by eGangotri

130

© Dharmartha Trust J&K. Digitized by eGangotri

इसीप्रकारकरके योवस्तिका पक्षकारी तिसको येवास्तिद
मेरू निहाकरके भस्तिकोभरे संस्कारकरके अरउमरवस्ति
कानेत्र शोलांअगुलीकरणे १ मध्यहलकेपरकेवराबर मो
टी अथवा द्वारकेअनुसारकरे अरुकर्णिका उपरविषें न
करे श्रोरस्थितहोयचोउकालिंगवाहरकफके पैहलेकेम
लवस्लप्रवेशकरावे २ फेरहनसें यत्रको मलकरके यत्न
करके तिसकोदवावे श्रोरवडेवोडेकेअपसिरस्नेहहनादि
अनुवासनवस्तिविषें प्रमाणकहेपाहे ३ इतिउत्तरवस्तिः
वोडेयांकोवस्ति वहुतश्रेष्ठकहिहे सोवस्तिमासकोंवधा

यनैनैवप्रकारेणानेत्रंदृष्टोक्तसंस्कृतं नेत्रम
मरवैलस्लकार्यंवेवोउशांगुले १ मध्यनाभि
परिणाहंसमन्त्रात्रेमकर्णिक स्थितसर्षपा
श्रनिष्क्रामस्यस्रवर्व्वप्रवेशयेत् २ हौतेनपंच
मप्यकेनैवतिस्त्रीष्प्पलैः उत्तमाशस्य
कुरवः स्नेहवस्पवानवासने ३ उत्तरवस्तिः
हृद्गः शुद्धिजननस्लैनोऽस्यविवर्जनः
श्यामो प्रास्यैतबस्तिः सर्वरोगहरः परः ४
पश्चात्सगन्पयकेचिद्रगावानसमञ्जवाः ५
त्रिकस्तंवाहनःप्रोमकालेणवस्तिप्रशास्यते
मलेशिकोपथाहसः श्राल्पादृबर्धनेभरा
नयानुवास्मिननास्योगुणैःसर्वैःविवर्ज्जेत् ६
पामाञानुलेनोपस्यबस्तोस्नेहःसमाहितः ता
गणमयिकारेषु मूलाघेषु बवाजिनां ७

तिहै श्रोरदेहशुद्धी नेनत्रूपइनकोंबधानीहै श्रोरसमरोगांको
हरणेकोंसमर्थहै ४ श्रोरपीपिचलेपासेकेपेउरोगवाञ्चके
रकेहावै श्रोरत्रिकस्तंभइत्यादिक रोगांकों वस्तिबहुतश्रेष्ठ
गुणकारकहिहै ५ मैनमूलाविषेनलकेदेणेकरके ह
ष्णाखाटोले इत्यादिकमंगोंकरकें निरतरवपनाहै ने
संहिचोजन्अनुवासनस्नेहवस्तिकरनेकरवे समगुणोंके
रकेवपनाहै ८ जितना प्रमाण स्नेहहनादिकीवोडे
कों मुत्वमाथपानकरणेकीमात्राकहिहै ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा०
हो०
१३१

131

उतनी ही वस्ति विषें हित कर है और घोड़े यांकों शूलादि रो
गों कि अधिकार विषें और स्नेह कल्प में नाना प्रकार को यां बस्ति
एक कारी यांका ही यां है न यथा क्रम करके निरूह बस्ति अ
न को संधियों विषें घोड़े कों पुष्टी वा मेल यो है ८ और निरो
ग घोड़े कों वस्ति हित कहि है अरु रोग वाले यांकों सदा
हित कर है अरु निरोगी घोड़े कों एक बेल भोजन की
ये ह्राय कों एक दिन बस्ति चरावे एक दिन न हि चरावे ९
अरु एक बेले भोजन के मध्य बस्ति कर्म सम अरु न मैं क

स्नेहकल्पवती विधा वस्तयः संप्रदर्शिताः
यथाक्रमेण रुक्षाणां पुष्ट्यर्थं सन्धिषु ८
आरोग्याणां हितो वस्तिः सर्वदा विनाम्नो सदा भवेत
लोहितेभ्यः हितो वस्ति रेकांतरम रोगिणां ९
एकांतरं भोजनं स्या द्रेमवेलेषु सर्वतः व
लमांसं विवृद्धि रूपं शोभा न यानमा १०
एकस्य भोजने न वस्ति नाशो पमा यन्ते प
निद्रा नाम निषेका न्यथा शास्त्र विवर्जयेत ११
कृशा स्थूलो विनकुष्ठ कामसा सो निवा हता :
विषदृष्या नि क्लांता श्रम त्रिभिना स्तत्पार्दिता १२
हृद्रोगे दमेदाग्निरोषि वास्क मरोपिनः प्री
ताभि द्रुतास मसाजः स्थिताः शास्त्र लिनः १३
शेष्या भिनाया नीमा रहि कानो उद कोटराः
मूत्रकृः सोहना स्वे यानिमा स्व कर्मसे विनः
१४

है या है सो बस्ति बल मांस को हित कर है और रूप शोभा बढ़ा
ने वृद्धि करती है एक काल बस्ति अरु एक भोजन न करके हो
ने है अरु इन विषें या मुनीयां ने त्याग ने कहे है न मेशा आज्ञा के अ
नुसार माग आरे हैं ११ यह इन लिखा वाल हुत मोट को उवा
ले रंग दम वाले और घोड़े को जिस को गति [illegible]
[illegible] भाव का आ होवे विषकर रदृश्य बहुत के या होवे
म्र क्षा कर के शुक्र और भुषा कर के इति होवे १२ और
घोड़े को जिस की गति न होरो होवे मन्दाग्नि वाले न खा को ल

© Dharmartha Trust J&K. Digitized by eGangotri

कों जिसकाल हदविकन्न होपादाहै अरु वहूत नष्टीन अरु हस्
अरु वहूत नगामी अरु पोदक्षीन तो स्थित नहीं और प्यासप्र
वाले कों ११ और पोनासनापअति सारहिडकी ककरकेपी
डित और उदकों निरूह कर्म केसेवने वाले कों निषेध करक
रै १५ दरवाले इनाकों अरु वनें से हदिन है अरु चोडे कों निरूह
कर्म के सेवने वाले कों निषेध करै १५ और योडेकों
नाडी अरु नस्य कों व्यापगी विकार विषें अनुवासन वस्ति ना
देवे सो वस्ति गर्भ अरु गर्भ वाली योडे कों और वीर्य कों नास
करती है अरु मुफ कों विगाडदेती है १५ और छोटे विछे रे

नाडीनस्याद्विषमोवर्तनाद्वास्याद्व्यापन्नरोगमः हे
निगर्भस्मगर्भायाश्चक्रूरकोष्ठस्यकोपयेत् १५ शि
श्रोष्ठवनचक्षुस्यन्निरूहंनप्रदापयेत् हीरव
स्लिरतनेस्लेषामवेगेःवलवर्जनः ११ मूर्छा
भ्रमभ्रमस्यकामन्तराघक्लेशानाशानाः गर्भि
णीनामपवक्षेनशार्दूलीक्षयप्रशमने १९ अना
स्याप्यास्तुयेप्रोक्तानाडयेनैनिरूहयेत्
अथवातोरुशक्रेनेनवास्याप्याश्चनसंपिड १
पावगर्भपरिक्षिप्तानामण्येवनिरूहयेत्
स्थलाभिघस्नायावोपालिगयेवकफनाहि
नाः १९ वृत्तलक्ष्मभेनेवारिनेस्वहानवासेन
गनागनेनिलानेवस्मृगस्वहाभिपीडिने २०

कों निरूह वस्ति सुकृपक्षकाविनादेवे इसकारण करके उनो
कों हीरवस्ति सवती है बल कों सुपातीहै १६ और सोमोरहवेगद
मरंगान्तरमागरवेदरन कों हरती है अरु गर्भवाली योडी कों ए
नें ने यारद अरु ग्रीष्मविषे अरु है १७ ये अस्थापनवस्तिकरने
को नाहिकहे तिनांकों नाहिकरके निरूह वस्ति करै अथवा
इनकों संपिविषें मरबीर सायस्मी रवस्ति देवे अरु पे गर्भ कर
के रवित है तिसकों भी ऐसे ही करै १८ मूर्छा वा कफ वा कों अरु
निरूहकर्म कों ये होय कों कफ कर वस्तिहित है अरु कफ रत्नहवालि
के पीडे कलाअरु होलेग्रा ग्रहि मनै है अरु योसहकर पीडित है
अरु आग्रहोणकरके अरु वस्ति के अरु वायु करके डरियन नि

© Dharmartha Trust J&K. Digitized by eGangotri

पथ्या [illegible] १३२

132

नोकोसुरामदिरासेहकरके उत्तिनःयोहै २० हरीनकाहि
रुतकषायकरकेअग्निकेप्रकाशवत्ते अथवा षेनपाटलके
टापाठलका स्नेहकाहूननैलवा अथमेरवामूर्ण मरवोर
माथहोवे २० औरदशमूलकाकाथसुवगावरवसुकाहो
मूत्रनिसकेपुक्त औरसेंधालूणमत्ताश्रुङ्कचूर मरकनी
वैसूण सतावर २१ इनाकावारांनोलेकल्कऔरचोडवी
पावे पहेनानामकारकेद्व्यमिलाकेपायहैनिरूहबस्ति
है सोबलकेप्राप्तकरणेवाली कहीहै २२ इसकोदितेदे
फेरमडकेसूहके निकलेहोपथ्या रुत्ताभोजनखोए॰

पथ्यादिवृतैर्दीमर्धेभ्रात स्वकोथवाम्पथ्या
सहस्पकुडवंचूर्णमधुनावाचसंभवेत् २०
दशाह्वमूलकाथस्तुपस्यान्मानाविनःसमः
सिंधुकुस्मांविमशाटीशिखारास्नासनावरी २१
पवोपलंवंकल्कंशालेवापदापयेत् संयो
नेपयोविविधःनिरूहोयंबलावहः २२
दत्तप्रमागतेस्नेहेभोजयेद्रहभोजनं स्नातः
नेवपदानंघनोगांवेवप्रशमयेत २३ एकां
नरमथेनसप्तरथोरस्यादितिस्मृतिः मधुतै
लकःस्नेषानिरुहःसर्वकालिकः २४ स
म्पाकदमोनिहन्याभुवानरोगान्विधानपि
पि सर्वेनेषुनिरूहोयंकालेदमोरसायनः
२५

कोदेवेफेरभोजनकेपचेदेइपरंनखावदनेपाणादे
नेकोंप्रहकरेयाहै २३ एकदिनविचसैंछोडकेत्रयवा
रदेवेपहेकाहिहै यहेमधुतैलकनामनिरूहककेह्याहैस
मकालविषेकर्णीकह्याहै २४ यहेविपिसंदोषोको
रोपपक्वकारी हृदहोयदेवीयवानरोगहेनलिनांको
सतावीनाशकरतीहै अरुयहेनिरूहसभस्रलनमेका
लमेदीपाहोयासमभोगदरअरुसबवस्याहरहै २६

॥

॥ ॥

॥ ॥ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

निरूहवानादिरोगांकेफेरदेकनाहै औरपहरोग औरश्रेष्ठस्कं
पश्चिमकोहत्रिक इनांकाबोलकपाणणिनांकोंहरनाहै २६
वहै वालबलासत्राफराडकणकइननेरोगसुहरसनराकेयो
होरोगहेनतिनांकोंआस्थापनहेहवास्तिहितहै २७ आ
स्थापनविधिएकवारकरणेयोगहै अरअनुवासनवहै
नवारदेवे जैसेंहारसत्रिरस्यादि वस्रकोमेलकोंसताकी
हरकनांहै तैसेंहिभलिविधिसेंदेहदोषकरवोयवस्तिरोगां
कोंहरकरनांहैसर्वोनरनेंकहकरके २८ अनुवासनवस्तिक

निरूहस्थापनदोषाणामानाहोसंनिपातिके
पित्तरोगहरणस्कंधः क्रिमिकोष्ठमलकग्रहः २६
वनौषानवलासस्थापनस्याकणकग्रहः एवं
प्रकारांस्तथान्यांश्च आस्थापनेहिते २७ सकृ
दास्थापनंकार्यंवहूनस्थानवासने यथाहा
रोमलेसर्वंवासोमालिनमाप्नुतम् २८ सयो
गवतिभिःशोधान्दोषानाकुक्षिसमर्वतः नहरा
स्थापनेहतिरोगान्सर्वांकप्रयोजिते २९ आ
स्थापनकृतेदोषःशुद्धकोष्ठस्यवानिनः व
स्तिसमर्थोभवतिशुद्धेऽलाहे ---- ३०
स्कंधकाणिकेन्द्रेषुत्रेनेमेकेनवाहित आनि
रुद्धस्यवस्तिस्तनयवेदमहागुणाः ३१ पश्चि
हेनवद्धाहोहादशांगुलमानकं आपामेनम
वेनेत्रवास्तिंयथाहकर्णिकम् ३२

यके रसकीयरोगजिसकेअरअशुद्धहोयाकोष्ठजिसवोडेका
तिसकोंवस्तिसमर्थकरहोनीहै ---- ३०
अरअपरहैकर्णिकाअरनेत्रजिसकाओरयकछिद्रवालीहो
वेपचकाशीमाहिनकहिहै अरजिसकोंनिरूहनहिकरीहोवे
तिसकोंस्नेहवस्तिवहुतगुणकरनेहिहोति ३१ वस्तिका
फेरमयाथानांकेहाण अरवस्तिकानेत्रवारांअंगुलविस्तारा
का अरछिद्रदोकर्णिकावालेहैवे ३२

शो
दृ
१११

133

और बडे छोटे के वास्ते निरूह बस्ति का द्रव बारा सेर प्रमाण का
देयाहै अरु पैछ्यवर्णके त्रयपल वा तीन तोले प्रमाणहै, पहले
पुटका ११ त्रयवार नग पल चूर्ण वढावे अरु क्रम धारा सेर
वढावे और छोटे कोंमध्यान विषें न्यून ह्राले अरु वायदाणानांदे
वै १४ यव भोजन पचनावे गुरु कोष्ठ स्निग्धपञ्च होवे तो वै
य छोटे को अस्थान बस्ति करे प्रवेके विषें स्वेद स्निग्ध माल
स अहनि निरूह विधि कीने होय कों १५ फेर छोटे कों समस्थान

अग्रमाखे निरूहस्य भिन्नमर्द्धांफकें भवेत् पेष्या
णां त्रिफले द्घाणस्य मेरुटके भवेत् १३ त्रि-
भिर्वा रेन वपलं कषायो यस्य मात्र के अस्या
पीनमध्या हभोत्यवाद्न वर्णिने १४ मोणां
ह्रां गुरु कोष्ठ स्य मात्राय पन्निषक् प्राक्
स्निग्धस्विन्नस्य मध्यकें निरूहेण प्रपादिते १५
पारेव क्रामये स्नेह मेथ शिरा स्यात् वे आयः
प्रकेटनो बस्ति दिनो यः कोष्ठ शोधनः १६
रक्तो पोषा कनाद्वोनो दोषाणा म पकर्षणः
सम्यक् निरूहेन श्लेनमा विशेष यत्न नः १२
हापयेत्नीरवस्तीव कोष्ठ राह निवहेणा २
रुप्रत्नीननदर्प्रपलोलत्तु विक्रमः १८ २
हृस्त्रत्रगोध्यप्रशुमाणा विटपमोहिन: ३प
श्रोनविकारश्चन याद्वारभिलाषवान् १९

विषें स्वेद पूर्वके आदि विषें प्रक्षेदन बस्ति देवे रसगी कोष्ठके-
शुद्धकर बस्ति करे और रसी मसी बालादिक दोषों के बाहर करणे
वाले और रूक्षीनगी निरूह के वास्ते रुवनि कलेदे कों विष
में २० फेर कोष्ठ के दाह के रसाणे वाले तीर बस्ति नहि देवे य
व को मलनिकलत दय चपल योग्य बलगानि १८ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

अरु मूत्रवेकरके मलमूत्र निकसे दाहो पका और दूरहोणा ७
हाणमल अरुधाम होयाहै विकार जिसको अरुभोजनकोप
वरछा होवेनव और सभकार्यविषे प्रहनहोवे तोजाणा इछि
नरो इसकी अस्थापनविधि होइहै अरुजिसके दर्दवंद होके
अरुकूखिविषे अफरा अरुअंगनके होवे और पछावका
रोगहोवे और ४० अरुजिसके शरीरविषे गुरुता देहमा
राहोवे तो इछिनरो निरूहनहि होयकाल लक्षण है अरुगुदा
विषे फिरके फेनउनकोनिकासे अरुपीडासाथकिले अ भा
मलनै विना उगवछोतै वहनेनिरुवाले थोडे का लक्षण जाने
हीनप्रयोगाद्वा हस्त्यश्रमस्यगात्मापिनो वहः श्रा
न्ताहृष्यांग कुक्षिर्वेलभ्भवंस्मूत्रनिग्रहः ४१
भवेद्रूक्षं वातास्यखडीनिरूहस्य लक्षणं अपा
हस्म गुदं फेनं प्रवाहण्यस्मै वेदने ४२ कफे७
शोषशीर्षं दयस्यवानिनिरुहिनः सनिरुढ
विहितेनेस्नापयेस्नापयेत्तदने ४२ वाताशेष
मन्नेहवशीतोस्मैनचवासिरिणः स्नानपानग
नोम्भुसानथानलभतेत्पयं ४३ शैवाग्निरूह
रुदेहदेहकाहूमिनानलः ४४ अथदशाम्
लेणाठाशानाववीशारिवारकुम्भपामा दं
नोवलाम्बदेष्वबधीभ्रुपोगूकंटकायुः ४ ५
श्रातावपाटतूषकञ्छरुटकामरनकुलस्यवद
रपवाः सर्वैषामवैषोपलशनमेकेनलहोमा ४१
अरुसंदरमद्भूरुवस्तिहोयथोडेकोजानकरके और जुनदोषजाए
के पीनल अरुवागमेंमलकरकेतिसकोनुहोले अरुपिलावे ४२
अरुस्नानपानकोंपाश्रहोय थोडे छेशाकोंनहिलभदा ४२ म
लभावनैनिरूहदेहको दग्धकरनीहै जैसे अग्निकाष्टकोंजात
तीहै ४४ द्रशामूल विल्वग्निमंथटांटरकमीर पाटल
अरुकनी टेघर कडे अदिकडेपारा महडे वटलवेलशाना
वरकालिवेल त्वी मवो टेहण टाणोदिनड पमणी
महडे इटपिट सहेजणकडे आरी ४५ ४६ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा॰
टी॰
१३४

134

अम्लनास बासाकालिवासागलोकुलथवेर यवोरंनोस्म
नोकायमाण साफेबागोसेर हर मणइकजलमेविधिसेका
डे निसकायजनविषेरनोकाझ्णप्रनिवापपावे त्रिकुटा वी
ट नगरमलठ दालहुलदीसेथालूण रेवट हरोडवहेडे आ
मले ४७ नदव लाचीया रेसन मजीठ कुठ यवहार गोमूत्र
काहा औरतेपेदापालीइनोकरके वातकफ विषे निरूह
वस्तिपकुकारीवडावे ४८ गनेरीरहोडद रावमिसरी इन
कीपकुकारि रक्तप्रन पित्तविषेदेवेओरमोपसेथालूण रा
डानेलमायचोडेकोपेदेनिरूहवडावे ४९ मेनीसरेयाका

विधिवन्निक्वाथनलेहयाच्चेमानितत्रषष्ठा
नि त्रिकस्यालनगरमधुकदारुसिंधुमये
णकोविफलाः ४९ क्वाथनैलागास्याभे
निस्याचैवकुष्ठेच ह्यारोमग्रेनकेनषोदके
योजयेकफेवाते ४८ ईलरसंपयःफाणिते
श्रितावरकेचाष्टेच पानपुष्पालवणैम
दनैलेनयुक्तेस्याजिनेनिरूहमिमं ४९ सैन
धवाद्यंककल्कंदशमूलकाथमिश्रितं॰
धीमान् लवणाम्लयुतेदघाढर्षामनिरूह
मस्वेभ्यः ५० लवणस्नेहमधोयकल्का॰
सिन्धद्यैः सधान्याम्लैः सैनसिन्धवाद्यकक
ल्कैःदशमूलकाथमिश्रितंमतिमान् ५१
शीतनमयेपित्तिरुक्ष्तंरोगभ्योदापयेत्मात्रः

नगादा औरदशमूलकाकाथलूणअम्लकेसाथवेद्यवर्धाअ
नविषेपकाकारिदेवेचोडेनाई ५० औरसेथालूण हूतवा
नैलगुडमचासेरया कोजीसतोमरीयांकाकल्क नग
टादशमूल विलण टडरणटाटरकसोरपाटल केडे
आवकेडे आविष्टरकनीदेयार भवेडेरनकाकाथ साथबुद्धि
मान् वेदशीतरूकविषेनिरूह वस्तिचोडेयोनाई डआवे ५१
कालेतिल पद्मकाष्ठ कमलनापेवा छिटावंदन मलटी
कालेवेल रवस ५२

© Dharmartha Trust J&K. Digitized by eGangotri

उपसाद्य पच्छकारीशारद और ग्रीष्मविषे देणेयोगहै सो
य मचोंमृग रवर्वमूलटकूट मरेया ५२ सैंधालूणभिं
गी जाण वेवद मलीर यडो गुड इनोंकेचूर्णकरके को
नीतेल मदिरा सत्ते गोमूत्र इनोंकरकेंदेवे अथवा यडो
वेर कुलथ इनोंकों अरु दशमूलकेरसकरकेदेवे और
मांसरसकीजीवा मद्य राइके काथकरकेदेवे अथवा
सभनोंकोंकिठेकरके चोलकेतिसकारके वानवालेयो
डेकोंविधिसेंपच्छकारिदेवे अरु वहनअमकरकेपके॰

शीतन्तिलपयःकोमलचंदनपद्मा द्दृशा
त्रिवेशीरः ५२ ह्रीवेरपुनैर्दांतयः शरत्स्ववामि
निदाघेच शतपुष्पामागपिकामलवचाम
धुकक्रुष्णसिद्धार्थैः ५३ सैंधवभार्गीघनमोदा
रेणुकामधुपवानिगुडैः पभिःपिष्टैःको
त्रिकतैलफलाम्लकमत्रयुक्तैः ५४ यवको
लकुलत्थानांदशमूलरसेनवामिश्रैः मांस
रसमद्यमदनक्वथेनसमायुतैस्त्सुवैः ५५
आलोडितैस्त्वविधिवन्निरूहयेद्वातिकेनरागं
श्रेनेत्रमपोरमानोहिताम्बुनलवसयः ५६
अथश्रोमकषायपुनैःसम्पुमसौः शार्करापयो
भिस्त्वपित्तविकारेणार्नेनिरूहयेद्वात्रिवोपो
मात् ५७ त्रिष्टैःशानपुष्पादिभिरष्णयपोवं
त्रिनैः समूत्रैस्त्सवैःप्रवैगादितेनिरूहयेत्
श्लेष्मिकंनरंगं ५८॥

शेषांयोरेषांको जलकीयांपच्छकारीपांवहननहिंनहै ५६
अरुपित्तविकारवालेचोरेकोंशीतकाथहिमोंकरकेशुक्ल
मलीर वोडा ठेह दुग्धइनोंकरके निरूहवस्तिपच्छकारि
डडावेवलनरवेघ ५७ अरुश्लेष्मरोगयुक्तयोडेको योमूत्रविषे
करेयाथोसनपुष्पादिचूर्णमोपवादिमोंअरुउग्रपयीनिना
मूत्रमहिननिसकरकेनिरूहवस्तिकरे ५८ वस्तिनिरूहक
ल्पः एवं कल्पसंजनतीयेसमामम॥

© Dharmartha Trust J&K. Digitized by eGangotri

धो
हृ
१३८

वडे विस्तारवाले पां अर्थवेद रूपी समुद्रने सहित के दार
मावाली यां ओषधि यां की दोर यां ति ना करके हलोक का
यों को करते हैं १ अब चिकित्सा कल्प हृदय कहया है अब
सूत्रकल्पविधिकाहिस्से हैपने जिसने चिकित्सा विषैं रो॰ २
गका स्वरूप नहि नाणे यां ना ना अन रसों ने परेड निदानस्थ ण
रोगों का निदान कारण कहया है सो होन रोका है एक अ
पर्णों ने होना है एक रूपारे ने कहया है इसको परमें होणे
वाला रोग का अवकाहे अब एक अर्पणे ने कहया है २ बुद्धिवा

वस्तिनिरूहकल्पः एवं कल्पसंग्रहेन नोयम
म्मामम् ॥ विस्तीर्णान्स्वं रोगमसमरसः सरसा
निमेषनानि अभ्युत्थानान्यथेन लोकाकुर्व
नकर्माणि १ उक्ते चिकित्सा हृदयं कल्पस्थलस
मासतः नवृधेन चिकित्सायां निदाने स्थाण
नःपरे २ विवि यं निदान सर्वरोगाणामात्मय
श्रुपरस्य श्रुहिविधा परोक्ष्य संभूत आत्मनः कु
पितः ३ अमशासागिविषमा प्रोक्तस्तागं
नक्तमतैः यान स्थानं नियनरतैः सावा रेभि
रवैसभिनलस ४ अप्यशानानीरां लववनले
वनेभ्रवन रागस्य हीनात्रविषमाः नृः स्वलस
कृपास्व वानिलप्रकने ५ भ्रोपसंध्योरकुम
निस्रसमासाकन सलस्य एवं क्रोपितो वायुर्ने
नयन्तिर्यग्वानवान्निनोपविकारोस्य ६ ॥

लेयों ने आगंन कथके माश स्वप्र हार अग्निदा है विषरनों ने क
हे आहैं और हार ने अदिने यो हैं तिनों के सेवन करने करके
यानूस्थान विषैं आसयप है वानदितिनों करके छोडेको होते
है नविकार ४ अरु अध्यासन अनों रां के विषैं होर भोजन करणा
अरु अनीं रां रसलव रुख ल के न रण वा चलना और रफकाइनों
ककरके छोडे कों और थोडी अथवा विषम चटवप अग्निवा
ले कों और बहुत मोटवाले सकों और वाम स्वभाववाले कों
और अलटहको वारु तरवोणवाले कों वायु बहुत कोप कर
ता है और वो इयां कों इतने रोग उत्पन्न करता है ६ ४

© Dharmartha Trust J&K. Digitized by eGangotri

अबतिनांरोगांकेनामविस्तारसेंकहताहों मन्यास्तंभ अरुनग
हृहहस्तंभलकवाअपतंगवातवला उरूकर्णकविश्वकवात
त्रिकस्तंभसरग उन्मादआक्षेपकडेफडीसरगवतें पहेवातरो
गांकेनामकहेन औरनांकेनाम सर्वविषेंकहेदहेन और
रोडना चोटलगणी करडांवंधनाभारहेकणा बहुतमार्ग
चलनामेंडेस्थानइनांकरके ९ और विकडनदीरेतरना
विषेंचलनेनें अरुउचीतिदीहृष्टवीमेचलनेनें उसराइवि
षें अरुटौलानें पाहनलकेभजणेनें औररवहुतदौडनेनें

तेषांनामान्यनुनामसमासतःसंप्रवक्ष्यामि म
न्यास्तंभहस्तग्रहहस्तंभार्दितैकपतत्रकाः ७
वातबलासोरुकर्णकाकुब्जकवातत्रिकस्तंभाः
स्रगउन्मादाक्षेपाभ्रमवर्तेभिवव्वातरोगाणां ८
अन्येषामपिनामानि सर्वमेवापरेशानि प
तेमभिघातान्निद्रवंधनभाराधयानः स्या
नैः पंकनदीसिकतासुवविषमावनिवा
हनादपस्खलनात् सबलनानलभेदाहापा
वनादश्वरक्षपवनेदोषाढा ९ उत्पद्यतेवि
षोनिरसानामर्दनान्येव ११ वातनिदानं ॥
अथ शमदीनिदायेवाहनोमध्ये उत्तेवमध्या
ह्ने लवणाम्लकटुरसानेवधूपिहेमेवमध्या
ये १२ नभसलिलैर्नापिवनः कटुकाम्लसमोव
दरपौश्च अम्लेस्यानेवापिनिशानसैलैलव
णदानाश्च १३ ॥

दौडेयांकौ रक्त अरुवायूकेरोग उत्पन्नहोकेतिनांविषें
प्रवेशकरनेहे इसितरांग्रहिनवीहोनेहेन ११ इतिवाननिदा
नें अवपितकानिदानकहनेहे शरदऔरग्रीमरुतनुवि
षें रसंपेहेगीसनाबीचलनेनें औरलूणअम्लकडुगामेंइना
देवहनसेवनकरदेहोपचाडेकों १२ १३ अरुवहनगर्म
जलपीनेहोपको औरकौडेअम्लस्याविदग्धहव्ययोग्य
म्लहोकेपचणेवाले औरवहुतगर्मस्थानविषेंस्थितहोय

© Dharmartha Trust J&K. Digitized by eGangotri

को और तेल लूण खाणेसें वर्षाकालमें शुक्त वा शिरका मद्य
बहुत अबल मस्तकी नीसौवीर कांजिभेद ग्रहणमें ऽपय २
नाके पान करनेवाले चाहे कौं पित्तसवीरनें कोपकरना है
इसप्रकार पित्तके कुपित होणे से यां यो रोग ये इंके होने है
ण तिनोंके नाम भिन्न भिन्न कहता हो १५ नीलाणक शि
र पीडा विसर्प रक्तपित्त अभिताप नेत्रशोथ विद्रुन्ति अंग

वर्के दधिवान्त्यं मस्तु च सौवीरकं पयोम
से लभते पानं तमल्लवणार्क्रुम्पानि पित्तमस्य
म्य १४ प्रवर्क्कुपितेनैपित्ते भवन्ति येस्मायपः ल
वाहानो तेषां नामानि पृथक्पृथक् वर्क्ष्य
वक्ष्यामि १५ नीलाणकः शिरोरुकपीतसर्पो
रक्तपित्तमभितापः वक्त्रशोषश्च नेत्रावि
द्रुन्त्विमाङ्कनातापश्च १६ लवणास्यनदाया
यतनवदोषक्षेव मूत्रकृच्छ्र च प्रवल्गसा
ग्याघिद्विघ्योना: पित्तजारोगा: १७ पित्त
निदानम् ॥ प्रक्षिप्तमस्तेन मदंतः पिब
नो जलमाविलमस्तो च पुरा मधुरास्फाद
पिलिबबृहल्लवणानिसेवमानस्य १८

ताप १६ लवणास्य पनस दोष मूत्रकृच्छ्र ओष्म स्थापन ९
ये पित्तके रोग प्रगट करे है न १७ इति पित्तनिदानं ॥
प्रक्षिप्त -- होइ बल्ल मम और स्नेह खानेसें अरु कैा
ला पाणि पीणेसें अरु मधुरा रा मदिरा और मिठे द्रव्य
टहीउ इ लूण इनोंको सेना करनेसें हो पवोइको १८ ॥
॥ ॥ ॥

ऐसे चोडे कों श्लेष्म को पकरता है ऐसे सर्वो रंने वधेपारा
तपि रकों बिगाड देता है अरु कंठनाडी सें प्राप्त होके १
स्थित होता है अथवा वायु कों रोकता है गल विषे प्रा
रक्त साथ मिलके पहे मुख अरु कंठ के रोगां कों पैदा
करता है मुखपाक अवामंक जिह्वास्तंभ प्रमूल १९
उपजिह्वा रोहिणिका गलग्रह कंठशालूक आदि २०
न जेष्ठ रोग वानक डष क्रुशा वमन २१ कफ रक्त

श्लेष्मा हृदयस्थ कुपितोपरि हतः श्रोणितं च
हृदयाते आश्रित्य कंठनाडी मसोस्थितः प
वनस्य कोवा १९ कंठे रक्तेन युक्तो नन्तयति
मुखकंठजानिमानोगान् मुखपाकमवा
नेकं जिह्वास्तंभ प्रमूलेच २० उपजिह्वा रो
हिणिका गलग्रहं चैव कंठशालूकं आदि
दन्तमो रोगं वानकं मय कृशमपि हर्हि २१
परिकुपितेन रक्त कफ रोगा हैनमवंतिवा
हाते पवंचान्ये [illegible]मपि समस्तवः श्लेष्मरो
गाणां २२ श्लेष्मनिदाने वक्तविधा स्तारमे
[illegible] श्रोणिते मांसवहाडिमापाति
ते नोच्यायामवर्जनात् २३ कठशाल वणा
स्नानो रसानामपि सेवनात् [illegible]मसीवा
पिवनः [illegible] २४ ॥

के कोप होय पैदे चोडे पा कोर नने रोग हूदे है न इसन री औ
रवी कफ रोगां कों उत्पन्न करि है २२ इति श्लेष्मनिदाने
बार प्रकार के पो आहार भोजन भरव भोज्य चोष्य लेह्य
पेय इनां के रसों कर के युक्त पले होय चोडे काल हू और
मास वहून बपया ताहे व्यायाम परिश्रम न हि करणे
नें २३ और कोडा अम्ला लूणा गर्म रसों कों सेवा करणे
नें मो रमदिरा अंबलपान करणे वालेकों और स्वा
नाम मं राता दे होय कों २४ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा
हो
१३२

137

अरु स्थानविषैं हिलडेरह्लणेवलेछोडेकौं रुधिरकोपक
रनाहै सोलहुनाडीहारमेंप्रमहोके अन्नभावकोंप्राप्तहो
करके २५ विदग्धहोनाहै सोविदग्धहोयारोमकूपोंने
लहनिकाशनाहै अरु अग्रभागशरीरकेविषैं श्लेष्मसा १
थमिलकेवहनवधैयादा पाददलकेअोरसेवोंकेरोग
मसूरद्रवणक दर्भ ग्रावसेवसिमकदेरेहरो पांमवेर
विवर्चिकापिल्लपाद २७ मांसवधनाणमेंवोंविषैं वर्न
निका विगालिका श्लीपदः प्रकोष्ठ उन्मीली अलूकपा

स्थानस्यमन्नं रसस्त्रोणिनेसप्रकुप्यति ५
नाभिगाग्रोणिसंप्राप्तामग्निप्रभैर्विदह्यते १
विदग्धं रोमकूपेभ्यो रुधिरः संप्रवर्तते । अपि
ष्ठमग्निमेकायश्लेष्मणामरुद्गमुच्छ्रितेन २६
नलरोगाःश्वाफरोगाःमसूरदृष्णकसूदर्भ
स्त्र आग्रस्त्रवः पांमुलोरोविवर्चिकापिल्लपाद
स्त्र २७ पांमुलोवर्ननिकाविडालिकाश्ली
पदः प्रकोष्ठस्थ उन्मीलूलूकपादःकेशमं
डुकनाश्च २८ रोगाःश्लोणितदोषेणमेदसं
वृन्ध्वमाद्योप्सानां अथरक्तेनविकारना
दनेस्येपिनाक्से २९ कुष्ठदद्रुश्चपामावि
सूरथदगुदहेलिकापुंडरीके पद्मांग मेद्रशो
फावदनगलगदाश्चालवषाश्चापिरोगाः अप्राय
तणाचश्चोफाभवानिमिरसिकरुकचाश्रुदंकेदरा
जीवसकोगंडमालाक्षयणाश्चागदाःकोष्ठ
शोफाश्चकेतुः ३०

दूकेशमंडूकनाय पदेरोगरुधिरकेविकारकरकेऔर
वी होडेयांकोंहोनेहैनधोलिनोकोंकहनेहो २९ कोढद्री
केडविधुररोगगुदहेलिका पुंडरीक पद्मांग मेद्रशोथ
और मुख गल आदि इनकेरोग औरमूत्रस्थानविषैं शोत
औरश्वानिपीड़ा अर्बुद केदराजीवरूकेगंडमाला और
अोझकेरोग कोष्ठशोफ स्तुरक ३०

© Dharmartha Trust J&K. Digitized by eGangotri

परिसर्प स्वरमोक्षः मशारिक श्यापिचाय इनतेरोगनिस्रवतें
रक्तके कुपित होयतें होतेहैन ११ इनिरक्तनिदाने हैरा
नन् रुधिरवातपित्तकफ इनोंकरकेयो होयरोगहैतनि
हूंकानिदानकहेयाहै जैसेहैंनरोगरूपचारपेहैन और
वाइके जीवन और शोभाकेहरणेवालेनिद्राकानिदान
आदिकारण कहेयाहै अवतिनोंकेरोकनेवालेपोडया
यहै सोकहनाहो १२ एहेनिदानकेनामस्थानचतुर्थस्थान

परिसर्पः स्वरमोक्षः मशारिको विद्रधी व्रण
स्त्रैव नार्यंते वल गोगा पते रक्तेन कुपितेन
११ रक्तनिदाने उक्तोसस्कपवनापित्तक
फौस्वानां यान्निदान मिदमावयनस्क
राणां अयसम्प्रतोविनविभून्याथद्वारका ४
ण नेपांतुनिग्रहकरान् कथयाम्युपायान् १२
एवेनिदाननामानि समासमानि पवेव
तुर्थस्थाने समासमम् ॥ ॥ ततोविकारे व
निलाज्ज्वेष्टपुराणाकमभ्यंतनमेव सर्वं उ
न्मर्दनं वानदंरवकुपीतन्स्वेदापनाहोनद
नेनरंव १ स्निग्धेनतासं परिहरयेद्वस्ति
स्थापकुर्यातुधियावसेकं स्नेहोनरोवेवं
मदव्ये द्वाकल्याननतलप्रथिाशास्त्र वे
ध्या: २ आस्थापनेचापि पथ्यापदिष्टमू
वोक्त कल्पन च बस्तिकर्म ॥

समासमम् ॥॥ वायुकेविकारहोयपदेपो पोकहियां माल
मोहैनमोपूर्वकरे और यो वायुकेहरनेवाले पदेंकीमालम
करे फेर लेपनकरे १ जिसकेपरे वोडेंकों सेकदेवे उसको
स्निग्धकरे अरुस्निग्धकेमार्ई रुधिरनिकासे सेहकर्मके
उपरवतुन स्निग्धकरकेपिावेपकरे २ अरुआस्थापनक
रुपविधि अनवासनकहेयाहै और वस्तिकर्मपक्वकारी
सडानोस्निग्धवस्तिअरुनिरुहवस्ति अनुवासनपदेवि
धिमनदिनचोरेमुकरायके औरभोजनकरावे २ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हृ
१३८

138

और वायु की वृद्धि ग्रह हानि ज्ञान करके अरु इक्कन रोग वि-
किन्सा कीने होय थोडे को आपाम कार्य विषें थोडे थोडे
अभ्यास में पाउने वाईय ५ इति वात चिकित्सा पित्त रोग वि-
षें पहलें लङ्कं करे फेर जलादि सेचन पान लेप नशास्त्र वि-
षें कहे होय पीपित्त के हटाणे वाले सो करावे ६ आस्थाप-
न बस्ति कर्म न सवारय है के रे और शीतल जल विषें न्हाले
अरु ठंडे हि भोजन देवे ६ इति पित्त चिकित्सा कफ के कोप

स्निग्धं च बृंहणं चान्नं वातेऽभ्यंगः समादनं मर्दनं प-
रिभोजनं च ३ वातो बलाबलं ज्ञात्वा समस्या कु-
र्यात्क्रियाः प्रायशो मृदवः क्रमशो
ल्पशोल्पशः ४ वातचिकित्सा रोगा
त्युपतिके पञ्चकर्माद्यभ्यासमेव नसर्वं प-
रिषेकपानलेपानाभ्यासकेपि समशमनं ५
आस्थापनं वस्ति कर्मानं वमनान्निवकारये-
त् शीतं तोयावगाहं च शीतानभक्षान्निदा-
पयेत् ६ पित्तचिकित्सा कुपिते कफे रू-
क्षाणां कार्यः क्रमस्य मासं नाभिषग्ना कटुति-
क्तकषायाणां च कुर्यात्सम्यक्पावनास्येव ७
पानाय कटुरूक्षं दद्यानो लीलकपक्रमेन्म-
निमान् आस्थापनं सन्वामनं समयनो ह्य-
वपनादव ८ लेहास्त्र निपानानि च धूम-
कटुभोजनं प्रथमं चैव दद्यान्नस्य सितकु-
पिते नस्यानि नस्याकफात्मानि ९ ॥

होय है थोडे थोडे यो को सेप रूखि रवाके दावे अरु कोइक मैले निक-
रने को के रेके मत के का पुवावे ७ अरु पान वास्ते कडुये देवे और
गीलाय खांकार के चिकित्सा करे बुद्धिमान वैद्य और आस्थापन
अरु अनुवासन बस्ति और रमीलाव पन ८ और अरु आस्थापन
न धूम कटु भोजन प्रथम नतीलाग नस कार और दरसी को प्रतिमा
वालिये न सवार श्लेष्म के विकार में देवे ९ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

इनों की चिकित्सा रक्त के रोगों विषें आदि विषें लहू कढाइ
वे के रेचो सर्व कहियो विकार की साधारण सो सभ निस विषें
योहै ॥ इस प्रकार वात पित्त कफ रक्त इनों कर के उपजे दोषों
की साधारण क्रिया कही है अरु इनों ने यो उपाधि कहिया है न
तिनों की वर्णादि यों रोग हैं तिन की चिकित्सा क्रम के अनुसा
र कहते हैं पहले जे प्रकार के यो रोग हैं वर्णादि जैसे सजावी
जीव के इस कंपते वले हैं ऐसा और कोई रोग नहि है १२ जिस
कारण तें दोषों के देह के मध्य विषें मला होते हैं विषमासन

सेव्या चिकित्सा रक्तजेषु विकारेषु सर्वेषु रक्ता
वसेचने ततः पित्तसमा हितुं क्रियास र्वो प्र
योजयेत् १० एवं वाते च पित्ते च कफे रक्ते च
वातिनां साधारणी क्रिया प्रोक्ता पथ्यामेया
पयोमतः ११ वर्णादयः क्रियालेषां प्रवक्ता
म्यनुपूर्वशः एवं नामोपाधिःस्पष्टः इन वाति
नीविनेसयः १२ अनन्तानां निकायेषु मलानि
यथा निरामाणां विषमासनाद जीर्णाभ्यासमृक्ता
मतिशोषणं तथाध्यशनात् १३ रुक्षाहारा
दम्लरसेस्वोष्णं तुल्य सेवनाद्वेग श्रमासनाद
व्यायामादन्यर्थे स्वेदसेवनाद्यपि १४ रूः
क्षानुवेपशापनादेव क्रोधेनाल्पदोषाः
कुर्वन्ति मार्गरोधं ततः समानो निहन्ति कायाग्निं
१५ निरुणध्य पानमार्गे ततः स्वयानो ग
निग्रहाः

नेकायेमल देशों ही होवते वहुत मावे अथवा
बहुत भुरवहोवे तें थोडे रवावे और अजीर्णों तें और रुक्ष ताप का
भोजन के शोषण करण कर के और भोजन के पचे बिना फे
र भोजन करणों तें १३ और रुक्ष वस्तु के खाणों तें और उष्ण वि रुक्
ने मल के बहुत सेवन तें बहुत भोजन तें और कुपित के नहि कर
णें अरु बहुत स्व दहन ने लादि सेवन तें १४ अरु मेरु इस नीर
स्थान विषे वमने अरु सेवन करणें तें इनों का रणा करके कोप
को प्राप्त होए दोष वातादिक सभ हारी कों रोक लेते हैं अरु समा
नावायु देह की अग्नि कों नाश कर देता है १५ सो प्राप्त न वा युके

139

मार्गकोरोकर्ताहैतिसकारोगनेंअपनाबासकीगतिभहहो
गोतेंसोउद्धपनिछ्रियादा सोवनेंवटांकोंकोहादिखैनीयव
डेपीडाघदेकर्ताहै १९ औरमलमूत्रअथोवातनइनांको
रुकदाहै औरवडूनपीडेकोंकरताहै १७ अरुतिहाके
नामअरुचिकिस्तातेंउपभिनभिनक्रमकरकेकहतेहो
पकसमितावर्तं औरकृतआवर्तं मूत्रग्रह औरमृगआव
र्ते १९ एकमूत्रआवर्तेपवनोदर रक्तप्रमेह औरकोरह
ष अरुदशमासहविवर्त एहेदश घोडेकोंदशआवर्तक

इयंष्याजिननेसोवनोनकोबुद्धाकरणा
लोचान् १९ विण्मूत्रवातरोधाजनयन्ति
वेदनांसभशो १७ तेषांतुनामानिपृथक्
पृथक्क्रमेणवक्ष्यामिनन्त्रिकेन्मा सभि
तवर्तस्वयकृत्वर्तोमूत्रग्रहोवैमृगावर्त
एव १९ मूत्रक्षवर्तःपवनोदरश्चरक्तप्र
मेहोगुल्मकोरहछः मान्द्रेवर्तोदश
मोहिवनावनोरमेयुपदशप्रदिष्टा १९
आध्मापनेपश्वामकोहिवनोकुक्षीसुकष्टा
पमिवीक्षतेच श्लेष्मसमालनैथवनि
द्रापणवानिमस्कोनिवपग्यसृति २० स्वा
सोपानिकायनिक्रुविनावआस्पवशोते
भवतिहपस्य अङ्गाससआपानिवपस्यशो
तोयःक्कुक्षिकोवामभिक्रुंचनेव २१
यामिभ्रंशकाभाःपिटकाश्चपस्यरक्ताः
यामिन्तरनामवति ॥

हैहैन १९ जिसवर्तकी
वेदवटवालेघोडेकोंआफराहोवेअरुवारंवार वतीकों
देखे औरमूत्र और गोवरमलनीहाथकेकाले होवन् और
सकेहोन २० इसरोगसेभीभारीवीनासे और सूरवेजिसका
टउदोव अरुस्वासकीभीनलहोवे अरुपोसवांकोंकिदेक
वे २१ और जिसकेंपेवनसेरपांकेदाणीकोनेंगांफीं गुल्ली
होन अथवासककेवागनिर्षेलालेंगकोंघोहोता जिस

घोडेकी चिकित्सा उपाय नां करे तिसकौं निषेध करके आगे २२
सर्वविषैके हैं योग्य उपचार अनीगांमादिक तिनां करके कुपित
यो अपान वायु सो विशेष करके नष्ट हो यादा कोष्ठ स्यानवि
षैगामसै यादृसो वडी पीडाकौं उत्पन्न करता है २२ घोडो
उठउठ करके वारंवार वैठे और अंगांकौं किठे करे और
व्याकुल होवे अफरा अफरा होवे और शिर वहूत भारा होवे व
ठे यत्न करके धारे और मलक वानि कासे २४ और उदिर उ
द्र फिरणा वारंवार और वायु नष्ट रवि शेशाव्द वहूत करे

स्यादेतैर्नोपस्याद्भिरूपमेन नाकिपोन कर्णी
दोपवर्ययेत्त २२ अपचारैः सर्वो मैः कुप्यति
वायुस्तेनापानस्य सविमूढः कोष्ठगतः
मेहनपार्विवृद्धनांनो बा २३ न मलं रेणां वि
लिखन् उरेण हितिपत स्यानेमना यना
माकः २४ विक्रमाल्मनेब्रूते उस्याघोस्याप
विशोनिमकुंवतिमवि हूलोद्दघोष्मानः
गुरुपारपन प्राषुरोधमामसमनुस्त्रजं
ति २४ पारिवर्तने मेद्रूमेद्रु गवेलोलन टरम
मात्मम स्पर्थः पस्य स्यान्मनवाजीम भिन्नव
र्निर्विनिर्दिष्टः २५ सभिन्नवर्त्तिनिर्दाने
गुरुदौर्बल्यान उपलस्यादोपमानां जनेक
यान् वक्रमणं पाद्यिसमे यांतितत्नो धावनः
प्रकाशते २६ सर्वपलवणाद्योऽसैः पिष्टैसने
लेनसंयुतैरभिः ॥

नाहै जिस घोडेकौं वद्धमलपण
होणसो सभिन्नवर्चि को कहे याहै २५ इनि सभिन्नवर्त्तिनि
दानम् बुधिवाला वैद्य तिसकौं पट्टलें छुड़के चूर्ण करके न
मकार वाउे और मलाइया वे और समस्त पृथ्वी विषैफेरे औ
र उडावे तो नव मलकी गांठ मोजाता है २६ सरसों लूणम सो
गरि वपुडू पीसके तेलकै साथ रलाकर के इनौं करके ग
वर पिंड कुचिस्नो विषैमर्दनकीने हो पवंयर साउ आवै वा २३

© Dharmartha Trust J&K. Digitized by eGangotri

अरुमदिरासैंधालूनतिंबवणमसांवर्चविकड़ मसोंमरि
चमुंठ यरकाधझा औरमैनीसरेपारनाकोंगोमूत्रसाथ
हहिनतंपीसकरके २८ वटीबनापके लिंगऔरगुदामें
वेंदेवेअरुफेरग्रास्थानकायत्रुल्लिपछ्छकारी उड़ादेवे अथा
प्रथ्येसेर रलनाप्रमाणमूर्वेहृझोंकरके शास्त्रप्रमाणनदेवे २९
मठामस्लकांजीसुरामदिरावारनवदारमोमूत्रईनाकरके
औरसमदलूणसाथ वेनझकककरेन्नरनाकेरसकरके
सौवीरकांजीभदनेलरसकरकेपुत्रक ३० निरूहअयवार

ऊतिनलरंपहंप्रभ्यकेसेटयेन्मानिमान् ३०
सरपामैयवनिवेनिरंहोपिष्यालिवचामा॰
घैः गरहभमरोरसर्वपपुमैःगोमूत्रंमापिष्टैः २८
वनिभेहनपात्रुनिरयादास्थापनंननपुर॰
भान अथर्हमममात्रेमेभिरंदेयोपथमाणांम २९
दपिमलघरालारमत्रैःसामहलवणपुमैः
निशुलार्ककरंजनरसैजेतैः सौवीरकनेलंस
मिश्रो ३० कार्योनपानेत्रहाःप्रशणाविरामू
त्रमारुताहृष्टे सातेमागेसुरेविधादास्था
पिनंवाह ३१ यानलवनगरवासाापथ्यकम
रदाकडुष्णाहैः मरलपपस्थानेनापुमैःसी
रोगामपिष्टैः ३१ पभिमैलैविपचेद संगे
वानवामनष्टे पनरानेशामपानेकाष्ठ
सेगात्रनेसेव ३२

कराकेयोगपैहे उगाके मलमूत्र वायकेवाहर करणेवा
ले यवनाडीयोनोवाहकमुह होजावें नौआस्थापिनवा
हमोकेनदेवे ३१ नाल नमर रेमण पप्रकाष्ठ देवदारु
हमूलवचीत सौवकांकोजीसामनरवीर न्नाहाणहूसम
ममुहगवमाणपीमके इनोकरके तेलपकावे सौतेल
मालमअरुवनिकेवालिवहूनवस्टहे और काष्ठ कवा
झुकोअरुसारेशरीरके वानकासमकरनाहै ३३

जिसको हे का पेट मलादकों से भरे पारा हो वे जिसको पेट
ले पानु नहि देवे जिसने वस्ति करके शुद्धकोधवाले को
पान देवे २४ लूण पंज ५ सुंठ मरवा मोरिच मनीशला
वीयां समाल गरहू धूम कूट भडिंगी हरा मदिरा साथ वो
हे कों सभि हो रोग की पीडा के दूर करणवास्ते देवे २५
और अभयादि पान सरा साथ देवे अथवा बहूलादि अ
थवा दंत्यादि पान कवनी अनाह सभ मार्ग बंद होजाणे
इनका नाश करदे है २६ वसमा के पत्र पीस करके मदिरे

नो हि श्रेवैदानबंधपानेन रोगस्य शांको ष
ष नस्माद्वस्ति विशुद्धस्य दापयेद्रसपाना
नि २४ लवणानि मद्योषधमागधिका
मोरचानि विषलहरेणुमभाः इद्दनामग
भार्गी सरा सहिता न रोगस्य सभि वकना
पहराः २५ अभयादि सरापाने व ह्लाय
थवा पुनः दन्त्याद्यमथवा पाने विबंधाना
हनाशने २६ नीलिका घस्तनापिष्ठा सुरया
सहदापयेत् माषोदावर्ते गुल्माकु सभि
लानाहभेदने २७ अतिविषमरवमद्योष
धविश्वककुहैलहरेणकाभार्गीः सुरा
के पुष्टदरयामसहसेपुनेपाने २८ य
घ वेनभवेन्नस्य सनतोविस्राव यो श्री गा
और मैपांड को हे शा मलपूर्णांने वाह्निकमेव ३५

साथ देवे तो माष उदावर्त गुल्म कसभि अनाह इनो
के भेदन करणवाला कहे याहे २७ अतीस मरिच
सुंठ चित्रा कूट लाचीयां रेणक भडिंगी अर्कके पत्र
पुष्टी दिवेनालके मदिरे साथ पान देवे २८ पवारस
करके गमनाहोवे नवनाडीसो हल दहनिकासे छाति
की उपाडकोह इनो विषे अरु इसनें वीसमाना हो
वे तो अग्निकर्म दहन देवे २९

© Dharmartha Trust J&K. Digitized by eGangotri

(141)

अरु रोगी के रोग के परिपाक विषें और विशेष क्रिया चि
कित्सा ना करें को जो और रोग ना पैदे करे तिस कारण
तें और क्रिया निरंतर ना करे ४० इस ते यो चिकित्सा
का हित है सो करै या उस काल को अरु उसके योग है अ
रु उलटी अगली पिछली विपरीत चिकित्सा रोग को नहि
हरकर्ती है ४१ यो क्रियाक्रम विना अथवा उलटी चिकि
त्सा कीने होय यो रोग समन नहि होना है अरु फेर बधता
है ४२ और सो प्रथमन नसवार सलाई मालस स्वेदपसों

क्रियाविशेषं जन्नेयुन्ध्यारिपाके न रोगिणः
न स्यात्सम्नेकार्यो क्रियाने वचकारयेत् ४०
अयोगादेशकालेभ्यः क्रियानकालयोगि
की नयस्ता विपरीता वा क्रिया व्याधिं नि
वारयेत् ४१ क्रमहीने क्रमे वा व्यत्यस्ते वा
चिकित्सिते न व्याधयो यान्ति समं वर्द्धन्ते भू
यएव हि ४२ प्रथानेरंजनाभ्यंगैः स्वेदनै
स्नानवामनैः निरूहोदन्नरेपानैः शिरा
वेधाग्निकर्मभिः ४३ कषोत्सारात्रिसि
क्ताग्नः प्रकाभिनविमर्दनाः एवमाद्या
भिन्नास्तः संभिवपरिपीडिताः ४४ सभि
सचिकित्सा कसत्याख्यामस्मभ्रंशात्तु तास्था
रोगवयायपयेत्स्यं ४५ ॥

अनुवासनवस्तिपक्वकारि निरूहवस्ति अरुउत्तरवस्ति
पान नाडीवेध अग्निकर्मदाग ४३ अरुपीलगामेमल
साथअंगयोने अरुफेरना और मलना इनोंकरके स
भिन्नरोगोंसेपीडितनाडीवोंमें समस्याहोनाहै ४४ इनिस
भिसचिकित्सा ॥ कसभोजनके रोगोंको कुपित होकरके
तहां पवनोंके रोगोंको कुपित होकर नाडी को धारण दे
हे मर्मस्थानकों पीडितकरनाहै वमन ४५ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

अरुचिनामरोगकरकेदुखितहोयघोडेव्याकुलहोनेहैं
अरुवैठनेहैंनअरुवलिकोदेखनेहै अरुअंगकोकि
ठेकरनेहै ४५ आफराबडाहोनाहै अरुवारंवारपृ
थवीविषेविलटैहैंन इनालक्षणवालाकहतवाले
घोडाकहैयाहै इसकीयोक्रियाकरणी हैसोकरै ४६
औरअतिनेसकीयांअग्निकीमाई लक्षण अथवापी
लेहोवे औरअतिकरकेसहित अतिवर्मलालहो
वैनोनयनामयकहे ४७ कहवतनवालेघोडेकोउदम

अथातैः प्रपीड्यमानाः स्युर्विह्वलाः सन्निषी
दन्ति नेत्रयः अभिवीक्षन्ते च कुक्षी स्वकां वय
मोक्षमाणाः ४५ आध्मायन्ति वाप्यर्थं भूमौ
परिवर्तन्ते तथाभीक्ष्णा पषवल्लक्षणवर्ति
क्रियामिमां वाश्य कुर्वीत ४६ नृपते पस्या
ग्निनुभेदश्चपनेपिंगलेन यथाचाहृगः स्त्र्य
नेवर्णानिबविनिर्दिशेत्सायमस्तोगने ४७
तोरपिष्यालिनैलपानेवैरक्तवर्णेनेदयान्
नैलेमापिमेल्लवमेदः पानायवादेयं ४८
सैंधवंचित्रकं वन्मकंहिंगवलारेणकाकु
नेवृतिं धूतमधमभागकंविनाशोद्रक्तवर्ति
नो ४९ मिनमिज्जार्थकंकल्कः सैंधवयामा
म्लेनैलमेपुनः नरेंदनरांनिकद्वः पश्चाद्ले
क्तवर्तिनो ५० कृथिनेहिपवमलेलोरे
वैमांनेनचापेल्याणि मधुकेसरलेकुष्ठया
प्रनांविभर्द्वकाहेव ५१

कोतेलपीनेकोदेवे अथवा
तेलघृतों दहींमिलायकेपीनेकोंदेवे ५२ औरसैंधालूणचि
त्राकोगढहिंग ऊ लाचीयो रेवद इनाकाचूर्णकरकेघोडे
मदिराकेसाथरक्तवर्णकोदेयकरनाहै ५३ सेनीमरेघो
कानुगढासैंधालूणकोंजीऔरतेलसाथरक्तवर्णवाले
कोनिरवलिइसकोदेकेसेहकहिहै ५४ दशामूलकाका
थऔरजवऔरइनांवल्लेगांकापानिथ्याथचूर्णमूलदेवीउ
कुष्ठनरवहिस्मार ५५॥

© Dharmartha Trust J&K. Digitized by eGangotri

श्री
हो
१४२

142

रेचणाइनांकरकेतेलसिद्धकरेसोतेलमालसञ्चरूवस्ति
विषेंहितकरहै फेरऊष्ठवनेवालेकों भगंदरपोशडेह्या
हैसोकरे ५२ इतिरूढावर्तचिकित्सा मर्मोपुरुषकेह्रो
पकोंमार्गकरके भारकरकेपीडितकोंतृषावालेकों मा
डेस्थानविषैंस्थितहैयाकोंवायुसर्वीरनेकोपकरताहै
वोडेकोंसोवादपुस्थानतेभ्रष्टहोयादावस्तिमूत्राशय
कोंरोककेस्थितहोताहै औरलिंगकोंवीरोकताहैवोडे
कामूरुनिनांदोनोस्थानोंविषेंवडीपीडाकरेहै ५४ आ

रास्तावृतेलमेभिःसिद्धस्यान्मदंतेवस्तौ
भगंदरवतनःयोन्यपूत्रंवर्तोता ५२
वृत्तवतेचिकित्सा उष्माघ्रातस्यासनिमा
रेणापीडितस्पृश्यतस्य उःस्थानेभ्रष्टस
नःपवनःपरिकुप्यते स्थं ५३ स्थानात्तु
तस्ववायुर्वस्तिसंरुध्यानिष्ठतिरुपस्य मे
वेवकुमाउतयाभवदेवनानीवा ५४ आ
ध्मानःप्रोक्षनःभितेवोजीपतेव्सेनत्र
परिवर्ततेगुभ्रमोकुतोचनिरोनतेवानी ५५
मृत्रगुहरस्यानांवर्धपरेनविनिर्दिशस्मात्तः
पनानिमाध्यवृणाणमाध्यवृणायवर्तने
वानोगोतानमहोरस्कारः शपावनालोनि ५६
द्रोषः वानेननेवचीमोतनस्पोविकित्सां
नकुर्वीत ५७

फतरोणपरसामदेपीडालिंदनाहिंहोणी
उपरवाइनाभेस्वनहिहोगा औरभूमीविषेंअरुलिंगकों
औरकुक्षिकोंवारवारदेखताहै इनोंलक्षणांकरकेवि
देयाकामूत्ररोगहैयकेहै यहसाध्यलक्षणांकरकेवो
लक्षसाध्यकरनेहै ५८ औरकोंलक्षणकरदेन आ
रे शूलिलालनालूकालाचिंदाहोवे अरुजोभगूरी
गोडवीकोले अरुईवकरकेनाउालेकानाहलो
वे औसेलक्षणांवालेवोरकी चिकित्सानहिकरे
५७ ५७
५७
५७

सायम्मत्र ग्रहवाले घोडेको पहले मंडीके चूर्ण करके वस
वार और मलाई कराने अनुपान देवे दानल और मावाने
गुडपाय करके देवे ५८ और अर्क दपत्र विजावर्च समुद्र
लूणइनोको गालकरके चूर्ण बनाके सुरामदिराके सा
थ हाडिमान वेघपिलावे ५९ अथवा गोनेदारसमूत्ररोगवा
लेनाई वैद्यपीएवास्नदेव इसकरके मरेयागयाहृदयनि
मचोडेकाजिसकासनावीपछावखुडनादाहै ६० घाते
गुडसाथमिलायदे और मधक मलजड और मचापावे यहे

साध्यस्याविषचूर्णेन कारयेन्मधमन्नोनने
पूर्वेपाने च कांभगुडेन सगुडं वदेवादकं देयं ५८
अर्कश्चबालविवर्ककवचालवणासमुद्रलवणम्
गुडः दग्ध्वा चूर्णीकृत्वा सुरयासकपाययेन्म
तिमान् ५९ इन्द्ररसवाधानापदापयेन्मूत्र
रोगिणेश्वान्नः पनेनभणीकोहस्यमूत्रमा
क्षुवर्तने ६० मक्कनाडसेमिश्रान्विशाने
नैत्रवापिच्यालिंदयात् पतनसरयायीवाम्
त्रसरवरीभवति ६१ मैपवपनशनपुष्पास
मन्नापामार्गनेडलकणाभिः यान्याबुतैल
मिनशासैपेश्चदेयानवृद्धस्य ६२ यववदर
कुलस्पेरंडवनकपाषाणभेदकुहैस्य
मासीमोरटपुष्पैः सपारिवशाणैःसर्वै : ६४
पभिःपयोविमिश्रस्नेलेनमष्टकविधापयेन्म
तिमान् ॥
सुरामदिरामेदानिसकेसाथपीएकरके
मत्र संदरसंकरकेहोनाहै ६१ सेपालूणमथुर सोप
मिठे मालनीगुडकेरावाडलैदीयोकणीयांवावुलेरीमयां
पनीयांवालानेलसेनि मरेया इनोकरके अवंकहियोवि
पिहैजिसमैनेनि ग्रहवलि मूत्र मार्गविषैदेवे ६२ और यवेवे
रकुलथ परणादेजर अक पाषाणभेदकुट फडगुडि
मोरपी वालीवेलइनोसमनोदाचूर्णकनाकरके ६४
इनोकोअग्य साथमिलाकेनेलहाडिनगपकावे इसकरके

© Dharmartha Trust J&K. Digitized by eGangotri

शा०
हो०
१५२

143

यो कल्पविषें विधि कहि है सो अनुवासन वस्ति देके और स्नी
रवस्ति वरजावे ९४ मूत्रकृच्छ्र विषें अरु मूत्र के वेद होय दे या
गुदा और मूत्रस्थान कों पोंके चूर्न साथ हरथ मलके तिस
के द्रव्य दारोंषधं देके त्रिकाविच नी दाह घटकर के मूत्रागार
को द्वावे नो मूत्र सनावीर ब्रन जाता है ९६ इति मूत्रचिकि
त्सा यो चोग विसरन होके ठिगटा है और थर सको वे
आफरा कर के पुरुष अरु मोखको न रो मतिन होवे अरु अदि
नइ होजान और जीव कलीनै वार निकल जावे ९७ अरु गा

अनुवासनं प्रदेयं कल्पोक्तोऽथ वस्तिश्च ९४
आवेज्य मूत्रकृच्छ्रे शपाणि मन्यमपायुव इत्यले
नहनं दद्यान्त्रिकदेशेन यो मूत्रं ९५ पी
डनं वस्तिदेशेन मूत्रमार्गप्रवर्तने ९६ मू
त्रचिकित्सा पःपतति मूढसत्वःसिमोध्मो
नोगता गुवज्ञानो स्यात्तालु ध्येनेत्रस्पाको
निद्धाति निरस्यानि च ९७ अनूर्ध्वं केटेनम्य मा
गरज्ञपी ष्मास नैव पानेन्यं दनैरवादश्वे
निद्धातो जीवन्नेष मरगवति ९८ मगवनैः
खानसमाना कुपितो ननयाति इति मज्जवने
नेषणं नेनाध्मानेनान्यथौ विवर्मेनेव रनानो
घः ९९ मःमातिमसार्थ्यपादानविप्रविला॰
ष्यश्च त्वेपने होनः पषावनं गुरुवैनेकि
यामिमाचास्य कुर्वीत १००

लेकर के निरंतर आलूकरे अरु रुक जावे - - - -
उपरैल वे और वरून के से अरु दे तो कर के भी वट के अरु दम
णा मगवनि के केदन पेट मगावनिं मीवन्नुन है २ इति मगव
नि समकर के आफरा सव्ला बिलाणपी डा होणी ९९ यासवेर
लैं रोग अरुनचो सफोड़ दे गीपा मुखवा के पाना णा कंवण
दीम होना इनोंन लक्षण ने पुरुष भी नाशे अरु इसकी वदे
गो के गी चिकित्सा सो करावे १००॥

© Dharmartha Trust J&K. Digitized by eGangotri

इसवालेचोरकोंपहलेंहौलिहौलिफेरअरुजलकेविषैं
नहोलेअरुपाणिपिलावे नहि फेर मर्दनकरे फेर पर
सापुआवेसेकटदेवे ७१ अरुयोआदविषैंकहेयोवायुके
हरनेवालेमलमसकेसोकरावेअरुवस्तिकल्पविषैंये
निरूहसोकरे औरफेरउसकेपीछेनेपक्काविचड़ावे
वहूनगुणाकरहै ७२ चित्राज्वाणाववकमरिचमगंगूड़
हिंरलूणापजोंकरकेचूर्णमदिराभेदसहशसाथसत्रवने
वालेकोंपानिपानवासेदेवेसोगुजरवर्नकोहरताहै ७३

अथपाने श्रेकामणमादोनोयावगाहनैव
वपानशाहिनेवक्रयोन्तपश्चात्पेननेश्वर ७१
शबोक्तानान्नरानभंगाकारयेन्मयाश्वेदा
न कल्याकस्मानिरूहोवास्तिस्नेदनेनरेशा
स्वः ७२ दहनानमोदवविकामरिवकणा
विस्फुहिंगोभिलेवणैः सुक्तासरापदेयाग्र
निपानेगुजरवर्नहरी ७३ यस्पस्नेह्याश्या
साहिक्तावेवोपजायनेसस्य नस्यनेक
मेनक्रयोन्नपसस्यादवेलोवान्नो ७४
गुजरवर्नः अपवातैःसर्वोक्तैगौनिमूहोमा
कनोत्सपानस्त उदैकमनेकोद्दनिकण
ऊिननःशाकन्मूत्रैः ७५ आध्मानेननो
शनिविमूत्रशाकन्माकनेनिवहैस्त अश
नस्यायोयानिशानिसविहुलेसगल्वुनिन
रगः ७६

जिसकोहोय्यासहिदकीहोनावे जिसकी
चिकित्सानाकरे अरुजो निबल है जिसकोनाकरे ७७
इतिगुजरवर्नः सर्वथाकहे अपचारनिनाकरकेअपिनदो
षाआपनवायुविपरीतगतीहोया उईयाअकरकेमल
मूत्रकारकेरुदयकोंरोकमोहै जिसनेथाफराऔरश्वला
केयोगकीन्याई टमलेताहै और मलमूत्रअधोवायु
केरुकनेकरके बारंबारउदरदाअरुवेदराहै अरुवी
ड़ायाहोनाहै ८० ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
१५४

पहेवानोहरवालेकेकहेहैन अवअसाध्यकेकहतेहैं ये
जोयोग्य विहोनसवोकेकष्टकीनरोयेपाहै अत वादग्र
मिदाहकरकेहोसकरहेहोनि ११ शिरटीलसहैयादा
घककेननिहैअतिपानिसबलपहेलसलअसाध्यकेक
हैहैन पहेविषमअग्निकेरोगकोदेखकेवोडेदेरोगगो
देनानएवाला असाध्यको योसहरोगकोचिकित्सा
करिहैसोसभरसविषकरावे १८ मरवववर्चवित्राकोड
गुडमालकंगुणीवावग्गि सवाइहिंड-सवाइनाकेसा

वातोदरीतिकाथितोत्रपमसाध्यम्प्यवहत्से
वाम्य यः कास्थवहुमेतः प्रहारमाग्नेवन
पति ११ सत्तःशिशेयकर्णाः त्व्यातः को
शितोद्यसाध्यत्व अयमग्निविकारेत्वम
मीतवरगुम्परोगितः १८ असाध्यम्पव
क्रियावेसर्वासो भीतकीकुपान मरवव
वानलकटुकानागरनेभोवनीविडंगेल
र्दनिहिंगुकणाभिःप्रानिपानेवाकाणिहेया १५ ८
रानिवानोदरचिकित्सा अथनिपानोस्या
सातीणाम्पपोरनम्पवाम्पथः अनुभेमाद
कपानलवणाम्लानिसेवणाद्वेव २१ वदु
वासभियोगाद्वाविसम्पाम्पथेनोपिवास्य
म्य यवं कुपितेपित्ते प्रोणानमाम्प्रस्थ
यति २२ नरानेनप्रेरितमम्पमत्रमानिसप्य
योन रेकेननम्प्लरेगासमुत्रपनेअल्पशस्रवदू
वाणि २३

थ मारुतिमदिरापीनेवासेहेय रनिवामे
दरचिकित्सा ॥ मारुकेवलनेवालेकोगमेम्प्राप्तहोयकोलि
मेकोपीडावहुनहोनेमेआसमेफोना अपरेआरलूणकोव
हनेमवाकरणोने औरवाकेसेपाणने अथवावहसेरकराय
होरेको रनाकारणाकरकेकोपकोप्रामहोकोपिनआरके
कोसनाकोविगाडदेनाहे २२ सोरमकावापुकरकेवलाचाहो
या मुत्रमार्गकीयामारीरोगमेप्राप्तहोताहे निसकारणाने

© Dharmartha Trust J&K. Digitized by eGangotri

घोड़ा लहूकोमूत्रकरताहै घोड़ा अथवावहुमासतत्र
टाहै ८३ घोघोडाजिसविषेनिरंतरबहुतदमहोवेअरु
शिरभारावडेदुखकरकेधारटाहै अरुखोवेनहिसोअ
साध्यहैसोजीवतानहि अरुयोसाध्यहैतिसकोआट
विषे शीतलसभचिकित्साकरवे ८४ लाचीया सिंव
लकेबीजमजीठमनकातेल इनोसराममदिरामेदतिस
केसाथपीणाकरके रुधिरप्रमेहवालाघोडासुखिहो
जाताहै ८५ बुदबेडासलटकोपफलडंगपसाथद्राक्षे

पलनन्मस्तमातेभषणं गुरुपारपनेशोनवा
टबे नमनेविस्ताथ्यस्पतकुसर्वशोनाःकियाः
कार्याः ८४ एलाशाल्मलिबीजंमंजिष्ठावे
वमधुरमाथैलपननरसपायोनाशोणित
मेहोसुखीभवति ८५ वीरंसपिमंथकंपः
पमाकरफलपुनेतेननसमस्कपकंवसो
भृणोक्षपःप्रदातवं ८६ नपुबीबीजेमूलेम
शाकेरेनडलोतुनोघ्रके रक्तप्रमेहशाम
नेकल्पपानाददंपस्पात् ८७ वर्षाभूर्व
वलेमहपापमाक्काथयहहस्मोव नन्तोर
शकेरपापुडेनमहूपापयेकोने ८८ हवो
वेदनपधकसन्कलोरितवस्पधाशोर
पंडपधश्रुकंपपमाविहप्रलेपनेन ८९

नागंकाडुके वारंवारबहुतवारवस्तिपक्वकारिदेलेपो
गपहै रुधिरकेपकावबालेको ८६ लोरंदबीमअोरजड
लेडुबाडुलैदबीसलो करकेपोणेमें रक्तप्रमेहकोशम
नकरताहै ८७ और इटसिरधमणीसहीथमणी और
कडेआरि कडेआगान्पकेसाथकाढे सोडुदखेडवाग्र
डसाथदेडापीणेकोदेवे ८८ खवलकीयाडुबा वेद
नपमकाहसने औरदीरहल बडु बडी कंवल सद
पारलापिप्पल इनोकेमिकडु लखी पाणापडइनोको
डुग्धसाथपीसकेलेपनकरे ८९॥

© Dharmartha Trust J&K. Digitized by eGangotri

श्रो
हा
१४५

नापैकामूलकंदसंगाडेराजमोथा इनोंकोंपीसकेउद५
साथचटाइहिपीनेवासोदेशोकरेहेन ९० इतिरक्तप्रमेहचि
किस्सा॥ मदकेकरनेवालायाकोदरानिसकोंखांदेकोंऔ
र मदकरपानीमैंवोहेकोंवानपित्तकफऔररक्तपरस्प
रवधेहोय औरक्रोपितहोयदेमदस्त्रमलमूर्छा खेदपरसा
निसविषेंहेलेपकरे औरसभक्रियाशीतलकरेतोइन
हे ९१ शीतलस्थानविषैंरवेहोयकोंगोपकालेपकरा

इनालेनीकेंदघृतेनसंगाढकमधकसेहकं
पिष्टा चौरघृतेनसंकलैतेश्चोनेपानापरेचसा
न ९० रक्तप्रमेहचिकित्सा मदनेकोद्रवमद
नःपित्तेनोमदनोदकेनपाघस्य दोषाखप
सरकोयमोसमूर्छिताःकोपिताः ९१ ननय
पाःशीताःशीताःसर्वाःक्रियाःकार्याः ९२
स्थानेस्थितमस्याशीतेप्रलेपगोमयेनकुर्वीत ७
पितवेदगमलेशितनसंधपलवणतेनसघृतंक
कर्पोरमोनइहपकाशपशापनेपघ ९४
नेनिपीमारभन्लेलिमघृतापुकपानापदानस्यै ९
मधुकलिदारोगोडुलेनोधःकाष्ठंपपाकेरातोदः
कल्कोकेनेनपानेपदापयेब्राहमामेधः ९६

है फेरबेबेमाथमालकोर औररदबाबेसमनोंगोमोंकें ९३ दशाम्
लकाकाढऔरशोनीसेरथोमिपालूताभैलोमिलाकेइनोंकोमि
इऔरपत्रइनोंकोंउखललिलेकुटकेरसकरलेबेसोरसमखो
रमामापीऐलाइडेवे सोमलपूरकफकोंकटकेबारानिकाल
देनाहै ९५ मलट स्थालिमधोलोपरकसीरइनोंरमृगदाखे
इ और मालीर करके बेपबनर पीलेकोंदेवे ९६ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

लसाहोकेजड़ और गंधकाबायमघर इनोंको मोदराम
राकेसाथकोरहूक्षकेशांतकरणेवास्ते पीनेको देवेना
र देवे ९२ जिसकोयाम्रहिलालहोजाए औरकंठवक
ठ्तमेगजड़होजाए आफराहोवे औरथोडादीखेउसको
वास्ते चिकित्सानाकरावे इतिकोरहूक्षचिकित्सा ९८
अजीर्णशूलकापोदोराहै जिसनाईस्वेद हननेलदिदेईए
अरुस्वेदकेपानकीयेहापनाई जलदाएण वाय रोएे
करके विक्रतवायुहोकरहृदयविषेविस्तारकरबध
नाहै जिससेमलालिद्भेदकोप्रापतहोतिहै अरुस्वेदबारवा

लेष्मांतकफामूलेनशैवल्तणामस्तकेवेव
सरणमानेदंयंमस्नानेपकोरहूक्षस्य ९७
अहोमोपस्परस्येनेवेपनेवालिमातृशः स्त
आध्मानेल्पमेशपोननस्मैकारयेक्रियां ९९
इतिकोरहूक्षचिकित्सा यसमेलनीर्णशूलमूप
वाचिनो संप्रदायनेस्वेदः पोनस्वेहपनल
खादनमथभोजनेचापि ९९ स्वेदस्यकापवा
रेणनस्यवानोभृदीयनेकोहि अथभियनेषु
गोषुस्वेदवासवनेनेभीहतां १० पारिवर्तनेय
शतपामभयंशूलपीडितोवानोपघानमः
पोदहोमदूषिणास्वेदवनेस्त १ हिंसतिवि
पलवणावबाकसाभिवाभूणेगजानसे
पानिपानेदानमावनाशिनीस्वेदवनेमय २
आस्थापनेवकायंयवकोलकुलत्थपंचमूले
स्त निःक्वाथैःभिआपंककल्कैनवनेलमूके म ३

इतिकसदाहै १० अरुजिमीविषेविलटाहै वडेमू
लेकरकेपीड़ितहोयाहाचोहा इसकानामचिहनमेंमूलि
पोनिकहेयाहै १ हिंडमूनीसमेंपालणावरचमलो इनोंका
बारुतामदिरमाथपानकरीकरके स्वेदवसमेकेनाशक
रणवास्तिहै २ औरआस्थापनकरेयवोवेरकुलथ और
पंचमूलसहज विलए आमेमथटसारण टेटर पाटल
कसीर इनोंकाकाथ औरसरेपोदानगदा और तेल
मिलाके आस्थापनविधिकरे ३॥

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰
टी॰
१५९

साल मोलसरी टापाटल पाटलभेद यओं इलतकडी इनोंको
जालके गोमूत्रसाथ चूर्ण करके और समूहलन है इ मिला
केसाथ मदिरा के साथ पान पीलेको देवे तो स्नेह रवने कोर
रना है ४ योवोड़ा आकुल होजाताहै अरुपीड़ होताहै जि
सकोंबडेको पाकरके मिलताहै अर्थात् दूरताहै सकद
और उभालो घोलताहै निर्बल मूल टेढ़ लिसा वासकोरया
हलाताहै ५ और आफरा वड़ा अरु अकड़े हैंन क्याहीअति
मन्यागलताहै जिसकी योनि सघोड़े को असाध्यविकार
याणे तिसकी चिकित्सा उलटीकरे ६ इति लहरवानीचिकि

द्रवाश्वकर्णमोचकपालाशपर्ववत्समुद्र
लवणानि गोमूत्रेण स्नावितानि हि शस्त्राणि सं
नेपाने ४ विड्लोपस्नेनोत्तरं कुष्ठादिभ्यो नि
नेभते ३ बलः मलगात्र अमेरामासपंचाभवे
त् ५ पोलनीवहताध्मान स्तम्भमन्याहिवालि
पिः असाध्यं तेविनानीयाहिपरीतमयक्रमे ९
स्वरवानिचिकित्सा साध्यासाध्यानकोपनके
इष्यलमदोषेन मनोनिषननेभ्मोनिषमे
वनिवनतः १ वानमूत्रपुरीषाणामग्रह
माविमुखेन निर्घोरनेनध्यामाणाविव
निवेदनारिताः ८ होहर ह्लानलेपोसंवा
मोत्रनानाभरूपा नेकृषेनेलेनाध्मकोनि
वृष्कवानलासयेन ९ लवणाध्मनमोदक
रेनवचामोचनिकणोभोलपाकूपवाः

स्ना समान और ध्यानकुपित होकरके हृदय विषमूलको
प्रकाशविस्तारण करनेहैन तिसनेवोड़ा पृथ्वीविषे गिर
ताहै और स्नायु भिन्न सहोताहै और वायु मलमूत्रको रोकता
है पीड़ाकरके दुःखितहै अरु वासमन हृदयानहिलगाना
ण और मोहनको मुकड़केवारंवारवैठताहै अरुविलटा
यावपेलनला होणतावोडा अवतान रणे तिसको कुर्वके
तेलसाथ मर्दनकरके नित्रहितकरावे फेरअनुवास
नदेवे ९ लाणपंसैयावित्रमोवलसमुद्रसांवर न्याला
मढकेला वदे मरिच सव विश्रा कलमा यों इनोंको

© Dharmartha Trust J&K. Digitized by eGangotri

मृद्दिसाथ पीनपान घोडेकोविवर्नकौं हरणेवालाकहे
याहै १० नलसी वासा मचो वावडिंग वणादालहरद्लक
रंजमफकेलण और समद्रलूण सेंधालूणपापकेसाम
दिरमेंघोलकेपानवास्तेहितकहेयाहै ११ अरुजिसघोडे
कामुखवहुतगर्महोवे आफराहोवे औरमन्यागलना
होअहिआलकास्थानजडहोजावे अरुमखतेजोभकालो
होवे ऐसेघोडेकोंमर्णेवालाकहेहेवे ॥ इतिविवर्नचिकित्सा
जिसघोडेकों पहलेंसहविधिकरिहै तिसताई सर्मेन्मूल
केमाथ अथवाऔरयवादिविधिनेविनाद्मेंहोवेमूर्छोने

घर्तेपानमिदंसुरयासहितंनरस्याविवर्न
हरंकथितं १० सरमातृषककणाविडंगा
निविंग्डेदारुनमाहेः माषदसेयवशुन
गलोलमुद्राहितायति ॥ अस्युसमखेमा
ध्मातेत्लव्यमन्याहिवालधिं श्यावासजि
ह्वाहेनमम्रपनेविनिर्दिशेत् १२ विवर्न
चिकित्सा अहिमात्समूलाःप्रागत्रि
गणवाजिनोयमे दीयनेवाप्रवुक्ताग्रा
सेमाघादपोनतुपेः १३ सैमोघनोविवेधी
भवेननसेनदारुणोवर्तेः नस्यचिकित्सा
कार्यासभिन्नवर्तनयाकथिता १४ कृष्णा
रसयसरमोधान्याम्लगुडसंयुतः माषगं
धिविनाशायदातव्योमधुनासह १५ अ
सिद्धेमहतेपानेपायोत्तिमाविवर्तनः वा
जिनस्यसहसामाषगंधविशोषपेन् १६

खाणेकों जिनांकरकेमाथजनामविवंपवटदूटाहैवड्डा
हलाकरडाजिसघोड्डेनाई तिसकोचिकित्साएसभिन्नावर्न
विषंकहिहैसोकरावे १४ पेटेकारस और धान्याम्लका
नीगुडसाथमिलायके अथवा मखीरसाथ देवे येमाहा
कोपगंडवेदीहोइहै जिसकेनासकरणेवास्ते देणेयोग्य
है १५ यदरनोंकरकेनासिद्धहोवे जो पाणी विषैंछलमि
लाके गुदामार्गमेंचलवेधपफकाविसहोवेतिसमेंघोडे
कीमाषगंधिसनाशी भुरहोजातीहै १८॥

© Dharmartha Trust J&K. Digitized by eGangotri

वसमेकेवीजगंधरसपालाशवीजस्वरसइनोंकोकोमीसाथ
देवे पद्रेमेदिदहेनगोरमूलकेनाशकरकेदेन १८ इतिमाध
विषचिकित्सा जिसकोरेकेखायेहारहासदाणाओरथो
भोजनविरुद्धतमानेउदरपनेऊपरलोपदेपकोदोनोंना
सोकरके अथवा मलकेसेलनिकसदालेव अरुमलीनहे
नवक्षनेअग्निसके तिसकोअजीर्णवमवालाजाणे १९ सोअसा
ध्यकहेयाहै इसकीचिकित्सानाकरे अरुयोयोउरमूर्छामो
हविहोसनाहोवेअरुछडाकफकावमनकरे २० सोअ
उपद्रवकरकेयुक्तहोवे तिसकीचिकित्साकरके राजी॰

बीजानिनीलिकायाश्वविषबीजंपलाशजं
विषामस्तुयुतं देयं मूलमेभेदनेस्मृतं १८ मा
धविषचिकित्सा अथाजीर्णमपवमस्वा
दनेभोजनानिवा वाह्यमुदर्यादेशान्त्मा
केननोर्ध्वमधीतिने १९ नवनेमानुमासाध्यानु
लाहालेप्रदेप्याने हयसर्ववत्सेग्यानस्याने
विद्याद्वर्ववतिने १९ अमाध्यःसर्वविरिदेहः
क्रियानस्थानकारयेत् मूर्छामोहविदीनो
ष्मःकेवलच्छर्दयेत्कफे २० सद्यपनविषुद्ध
नमवसिद्ध्यांतिकर्मणा त्रिहनोनरकेनेउ
शलकीनकमालयाः २१ नचाश्यपिष्टान
त्वापालरदतोरणामेसमेन प्रमवद्धनयु
केनरहितनालेनदापयेत् २२ पिष्टारसान
बीजानिशाकेनामलकैस्मरः आलोड्यनैल
नेमानिनमलःपानेप्रदापयेत् ॥२३ अनःपरं
प्रवेष्टनेक्रियामोभितिकीभवेत् नीलकाय

होमानाहे त्रिवीकूवल पालकीगनभवाहत पालमेदकरे
नमलकेलाणहनकरेज २१ इनोकेमिकउवराबरपीसके
मावीरामिसाकेवशवे मेधहरनालहनसाधरलामकेप्रम
इवावे २२ घोमकेवीनआमलपीदकेतेउसाघनेलनिवचो
लकेनसवारअरुपानविप्रेदवे २३ इसकेउपरांतइवनेमेपा
सभिहककाविषचिकित्सकरहैसोकरे वसमेदपत्रपाभरपो
-के मूत्रमाथउमावे २४

© Dharmartha Trust J&K. Digitized by eGangotri

अरु इसकी शुद्धि विषे गोमूत्र में यथपी णेको कहे या है वाव
ड़िंग इन्द्र और लूण मिलाके सराइ सनाइ देणे योग्य है ३६ व
मे के हरने वाला है और भोजन तिसको दूध के साथ स्निग्ध
करके वारंवार खुलावे इति ऊर्ध्ववमनचिकित्सा समाप्तं
वमन और अतिसार जिस चोड़े को होये होए तिसको वमना
तिसार कहते हैं तिस वमनातिसार वाले को आद विषे सो
भित रोग में यो चिकित्सा कही है सो करे और यो पूर्व प्रथम
न सवावर देवे जिनना विरवन न हिहटे या इसते उपरेत

गवां मूत्र गुनाचाम्य विल्वैपानमोक्षेत वि
डंगैसंधवैरगालवणानवैमिश्रिना २५ ह
या वासम्प्रदानध्या उर्ध्व वमनविनाशिनी भो
जनंगोमपिपान्नकंसमिनजनभाजने २६
इत्युर्ध्ववमनचिकित्सा वमनेश्वातिसारस्य
प्रसाध्यप्रनायने वमनातिसारिणांसम्य
पूर्वसोभिनिकोक्रिया २७ प्रथमपूर्वकास
वोयावजलेहिमसज्ञने अथातिसारेकर्मेट
केनेयोनरनेनरं २८ विल्वनगरविकस्यानि
भस्मनसोमदाडिमवताभि वाकोलसाद्दतैः
पानेदेयमतिसारोगहरं २९ मानलेगक
पित्थानलोरपेनामत्थले ननोवसंपादि
श्राव्यसाधयेन् दूनमात्रया ३० घाघिकानो
गणनामोदनेनेनभोजयेन् ततःसेवनेनव
ते ह्यतिसारहिमसज्ञने ३१॥ अतिसार के छूटाने वा

लि विधि कहणे योग्य है २८ वेल्ह नगर मेंडु म्हसीसिंधल
ण थोम हडनी फल के मिकडवा रुशिम दिरा साथ पट
पान अतिसार के नाश करणे वाला है २९ मोकडी कैथ
इनो हिनोंनो को इखल विषे कूट के तिनो का रस कढ़ के पूण
ले विनिस करके प्रमाण के अनुसार दे औषिज के रे तिसम
न साथ पण गाणी भटोका भन्न खुलावे तिस कर के वने के
सम होय पै अतिसार ने छूट जाना है ३१ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

अ
हृ
१४८

र्गनिवारणोचिकित्सा भोजन का सार पो रस है मंदाग्नि होने तें
कचार हया होया तिसको आम कहते है सो सब रोगों का
मूल कारण है २२ सो आहार चार तरह का है भक्ष्य भोज्य लेह्य
चोष्य भेद करके सो जिस दोष करके प्रेरित कीया हुआ आ
माशय विषे उदीर्ण होकर या हुओं नर वा नाहि पाक होय न २३ सो
आमहाके: सारे शरीर कौं जड़ करके फेर मल मूत्र कों रोक लेता है
तिसतें आहार और दम होता है अरु कि सो जो मा विषर मा
ग नहि लभता २४ आमाशय के विषे आम के स्थित होय

148

वर्नोचिकित्सा आहारस्य रसः शेषो यो नप
कोग्निलाघवात् मूलं हि सर्वरोगाणामाम
इत्यभिधीयते २२ चतुर्विधान्नपाहारो यद
दोषसमीरितः आमाशयगतो ह्येनस्सं
म्यक्परिपच्यते २३ विषूच्यलसके गात्राणि
शीर्कमं त्रेदयाति ह ततो ध्मानि ध्मोति च
स्थानतो लमते सदा २४ बुभाम्यमानि पानी
या दामो नामाशयाश्रिते पच्यमानाशये
मूर्छा तृड्भ्रमोपि जायते २५ विरस्प
लेददाहाश्च कुर्यो दाह स्याप्यतः आमा
शयगतो ह्येन यापक्काशयेगते २६ न
यापक्काशयगते नाहारमभिनंदति हृव
गौरवं मोपि विवर्णोपि च ल भवेत् २७ म
लानाहमदावनोत्त दूराग्यार्थगौरव पक्का
शयेस्थितामेन नयाशोनाभिलामवेन २८

ते पद है ल दण जाणे आमाशय विषे पवदोदोर्ई मूर्छो तृषा भ्रम वि
मकुलनीशय विदग्ध के खिपकी होवेना परमादाह पित्त ने कर
ते है अरु उदहार आमाशय विषे वायु का पाये मे शम दे ऐ वाय
है ल लगा होते हैन २६ जिस आम के आमाशय के विषे मास होय
है सो भोजन को नहि अग्न करता अरु लिए पन ली उर्गे वाली
और रोग विरोग वाली और पित्त वोशर विघा नी वाली ऐसी है २७
और मल और हार सभें दहे होण और मल मूत्रादि का कौ वि
परीत उलट है होण ददहो ला शिर भासा और मंदाग्नि यह लक्षण आ
माशय विषे आम के स्थित होय दे होन है न २८॥

© Dharmartha Trust J&K. Digitized by eGangotri

मरु आमकेसारेदेहविषेआमहोयतेसभनांनोउंविषेशो
ना गुरुभोजनतेकिरछानहीकरता देहभारयतीतहोता
है ४९ अरुवायुकेकोपतेमूत्रकृच्छ्रहोताहै अरुशिर३
वाकरकेरलीहोयाद्यास्यितहोताहै औररोगकरके
पीड़ितहै ५० अथवाअूलग्यामदेखीदेहै तिसचोडे
कोवैद्यआदविषेवनेकरावे ५१ वासपानिहारा
तेहदेराण इसकोलेचनकहतेहै इकदिन दोत्रपचा

सर्वगात्रगतेत्वामेशोफःसर्वेषुपर्वसु
नाभेरनिलवाहारंगुरुगात्रबलक्षये ४९
नष्टावानमकोपाद्वाकृच्छ्रमूत्रीभवन्नपि
शिरश्चोनमस्पदःस्वानेनिष्ठ्यापिनिपी
डितः ५० अथवाऊर्ध्वनेस्ल्लेष्मासेवा
प्यत्यदयपते नस्यलेचनमेवादौका
रयेन्मतिमान्भिषक् ५१ वामान्नपान
भोज्यानांवर्जनेलेचनेस्मृतं यकाहं
वाहयेवापित्र्यहं चनरहेनथा ५२
पंचाहंवापरेकुर्यान्तरंगस्यविशोधनं
शरद्ग्रीष्मेनवहोरात्रंकारयेन्मतिमान्
बुधाम् ५३ हेमंतेद्वावहोरात्रौत्रीणि
वसंतेमवार्षिका बलाबलेपरीक्षेत
नकुर्यादतिलेचने ५४ अतिलेचना
न्नरमाप्राणात्ययमवाप्नुयात् ॥

रयंजवाओरवीचोडेकोआमकेसकाणेकाले वनेदेवे
अरुशरदग्रीष्मऋतुविषेपकदिनरातकरके शोधण
होताहै ५३ अरुहेमंतऋतुविषेदोदिनारातकरके अरुवसं
तओरवर्षाऋतुमेंत्रयादिनलेचनकरे औरबलअरुनिर्बलको
परीक्षाकरलेवे अरुअतिलेचनवहुतनकाकेनादेवे ५४ ५५

अनिलंगन करके शेडेके प्राण नाश होजाने हैंन और उ
न्माद मूर्छा हिचकी मरण होता है और इसके शरीरकी
अग्निसांत होजाती है जिस कारणते जिसका पकाहोया
है मल और पक्काव अधोवात हचकीनरोंचलता है अ
रु हौल होया है देह गुरु मल जिसका अरु भोजनकी
इच्छा होइ अरु मेंताई थोडीलादोवे सो वासरवाणवास्ते
थोडा देवे ५७ ऐसे कार्छादिक मध्यनेसें निकसी होइ दी

उन्मादमथ मूर्छां चहिक्कां मरणमेव वा अ
नीव वास्य कायाग्निः असौ निधनमीगच्छति
तस्मात्पक्व शरीराय पक्षमूत्रानिलाय च ५६
लघुगात्र शरीराय नष्टाहाराभिलाषिणे
अर्तो पव संदद्यात्स्वल्प लघुच पथ्येन ५७
यथाविधुम्मो न ह्युधिः शिखिने मध्यनोधि
नः कार्पासस्य करीषशुष्केताम केसप्यने नवे
रणैः काष्ठैः अवहुभिः लोके लोके प्रबोधय
ने प्रवृत्तः सहसाग्निः का ष्टाणो न बहुनापि ५८
तथा नरान पस्नेहाणा महसः कोष्ठमाश्रिताः
एवं न्यासनोति विपानाराग्नेः संप्रदीपिनः ५
तस्मात्पाने दीपनीयैः स्वल्पैस्तैः सस्नस्या
शालिषष्टिकमूदैः सम्नात्मलैः रसकैः सखा ५१

अग्निथोडीनेसी लाटपकपमनेरहितानिसकौंजेसे क
पाहा गोहा टलीया रण लकडीयांकरकेथोडीथोडी
कौंजैमेमगाइदीहै सोनागीहोइबढनकाटकेसमहकौ
मनादी इत्यकरदनिहै मैमीरि पुरुपनेकमप्रवेकरट
पकेखिवैखिलनअग्निवढाइदी होरेकेनानाप्रकार
केहारकौंपकाएदेतीहै प्रकाशहोइदी ५८ निसनेअग्नि
केप्रकाशकरणवालेपानखेलप्रपमां सरसइनोक
रकेशालिवारलसासममीसहीमैंगी औरवनकेपती
येकेमांससमौकरके ५८॥

© Dharmartha Trust J&K. Digitized by eGangotri

औरहोलेहवे पटेत्तिनांकेग्रासोंकरकेघोडेकी चिकि
त्साकरे इतिवर्णनीसार मूलचिकित्सा आमचिकित्सा
अथवातकमूत्र घोडेयाकोंवातपेतकफसेंतिनपत्तनेंचा
रप्रकारकामूत्रविकारपंडितोंनेकहेहयाहेक्रमकरके ५२
आफराट्मअरूपिचलेसंवछेडदाहे अरूमूत्रकरनेकेस
मेवडेक्लेशकरके लिंगकोंविस्तरकेमूत्रकरणेकीइ
च्छाकरनाहे ५ पहेमूत्ररोगनिश्चयकरकेवातकामूत्र

लगुभिर्हरेन्नेग्रासैस्तुरेंगंसमपक्रमेत् ५२
एवंमूलचिकित्सा आमचिकित्सा ६
अथवातिकमूत्रवातानपित्तात्कफाद्व
मेलिपातास्त्ववातेनाक्रमशः एवंमूत्र
विकारास्त्वचतुर्विधःकीर्तितानेवुधैः ५२
आध्मानमेव्हमित्यमुष्याटोविलित्यपाश्वि
मैकक्लात तन्वांतमेहनोत्थःसमीरते
मूत्रकत्ते ५४ एवंलेलमूत्ररोगोमारु
तत्तस्याप्यवेमभ्यंगः स्वेदःसर्पिःपा
नेत्स्निमस्यातिरुहणोवस्ति ५५ कुष्मा
डानांवीजवीनानांवीकणस्यस्त्वंमेलुं
कर्णमात्स्यीन्मेलोगोक्तरकेवेवसंचूर्णं ५९
सुरयापानेदेयंमस्तुपानेवारनालमप्
के नरनास्यमूत्रमाशुप्रवर्ततेवातिकम
तेन ५७ एवंदग्धात्वाप्युमाडीवीजंत्तुःस्य
ग्रोमूलेहहनीदयंच॥

विकारविषेंपहिलेमा
लससेकटवेफेरचुनपानकरावे स्वेदकरके निरूहवस्ति
करावे ५५ पटेकेलोन औरवाकरणेटवीजतिकोंलाचीपा
वाइवडीलाचीभक्तु इनाकोंमहीनचूर्णकरे ५६ सम
मदिराकेसाथवाकांजीसाथ अथवाआरनालकोंजोमद
केसाथपीवेतोंघोडेकापफ्फावदवामवालकाअनातीवर
तेहजानाहै इसकरके ५७

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ टी॰ १५०

परणैसेसला हेडमें देवीज ज्वाखार दीपे अने कडेखारीक
डेखार पाषाणभेद भरवडे गुखरू ककडी के बीज सनावर
इटसिट इनको समभाग इनोके काथ में पवाग्नि सिद्ध करे
शिलाजीतको पिलावै अथवा इनो औषधीयोंका करके क्वाथ
काढके पर्दे पानकोइकी देणो योग्य है ५९ अरु अम्ल
कांजी छाछ वादपि मंडके साथ गुड नवा ग्र पिलावे
तो वातिक मूत्ररोगने वोजा छूटजाता है ६० इति वाति

पाषाणभिद्वोक्षुक शालिपर्ण्यः गोग्रोक्षुरी
नानिशालावरीच ५८ स्हैलिसहेना निग्रनवें
वाच पक्वोकषायेणापवेचवा शृं नोपाप
येदेभिरयोषहेवी सिद्धपयः पानमिदं प
देयं ५९ अम्लकांजिकतकेण दधिमंडेन
वाथवा पवानुपापयेत् गुडं नवानो रोगा
न्प्रमच्यते ६० वातकमूत्ररोगचिकि॰
त्सा अथपैत्तिकमूत्ररोगचि॰ पैत्तिक
मूत्रविकाराद्दाहः श्वासश्च जायते ह्यस
रक्तेहारिद्रेवापवर्तते मूत्रमल्पशः ६१
अनयोर्गोक्षुरकेपलाशोऽष्माणिशाके
गाद्येव नेरलनोपेन युतेपि ऐमधुमाक्ष
नेपानं ६२ पौरवोनिर्मलाब्धामनश्याम
श्याकंश्चयुते पिष्टं पानायमवेगारितेव
शान्तुकंप्रोइ वोनाश्यम् ६३ ॥

कमूत्ररोगचि॰ अथपैत्तिकमूत्रविकारमें दाह श्वास
होरे कीचमेहेन और लाल और पीला मूत्र
होता है बारंबार ६१ ताको मत्सेद बहुप खंडइनोको
वाउलेदनेलेकरके पीसके मरबीर पायके पानदेवे
६२ आदविषयोंकरे याद कफोंड बीजादि लाथी
दोनो प्रकारकीयों और अन्नपीलिना पानकेवा॰
सेरेव ६३

भवेहै दे क्वाथविषैं लाल चाउ सिद्ध करे फेर तिनों के सा
थ यवाग्र काढ़ के टंढा कर के अरु शीतल जल मिला के
पीवे पित्त मूत्ररोग वाला १४ इति पैत्तिक मूत्ररोगः अथ श्ले
ष्मकचि· कफ के मूत्रविकार विषै पकाव चिटंगके
चरणां विकरणा वा अथवा चउलैं देउ लोके समवडे खेट
कर के थाउ थोडा चलना है १५ तिस विषै पहिलें स
दसे ककरणा और यामवैं कहे पोग्रनिपान सो देवे अ
रु थोमवैं कहे नवा गहे नए पान विषै पान वाले दे है

गोक्षुरकषायपक्वं लोहितं शालिप
वेतनः सैन्धवं वा पिवेद्यवाग्रम्लनः
शीतलं तस्मृच्छा १४ इति पैत्तिकमू
त्ररोगः · अथ श्लैष्मिकमूत्ररोगचि · कफ
जे मूत्रविकारान्म्येते साद्रमपि बले वा
पि सेनाके मूत्रे वा मनेदु लोभ यवर्तने कक्का
न् १५ नम्नारोकम्मः खेदः प्रतिपानमे
व शर्वीकोपयवाग्रूपाने श्रेष्ठवको
लम्य १६ इति कफविशाविचकपाठाको·
म्पानस्थानमोदाच गोक्षुरकस्यव मूले
पाने वैतेतु लोवुनाशुनेवै १७ इति श्लेष्म
अथ संनिपातमूत्ररोग· सन्निपाते नरे
गाणां ज्ञानो यासन्निपातिको क्रियासा
धारणेन स्यमूत्ररोगस्यकारयेत् १८

वे अरु पष्ठ कुलथी का पान वा लेदे वे १६ कटं [illegible] वि
[illegible] वटल वेल मचोमाण वल भवहैं दोषां मूत्रा स्त्रा
का पान वा इलैं देने लके साथ पीणा को देवे १७ इति
श्लेष्मकः अथ संनिपात मूत्र की चिकित्सा कहते है स
न्निपात मूत्ररोगयाणा के पो सन्निपात की चिकित्सा है सो
साधारण क्रिया करे इति से १८ मूत्र दघनें [illegible]
पित्त के पकाव करणे वाला होता है अरु वल के लघे है

© Dharmartha Trust J&K. Digitized by eGangotri

शा
नि
१५१

151

णोनेनैलमेंहैनेलकेसमपछावकरनाहै अरुवीर्यके दोषतेथोडाशर्करामेंहिताईवालापछाहोनाहै १९ अरु वीर्यकेवेगकेरोकणेकरकेश्यपाककापछावकरना है औरगतिकेवेगकेविघातकारोकणेकरकेफेनवग वालापछावकरनाहै २० यहेपंचव्यापदामूत्ररोगकेउ त्पनकरणेवालियांकहियां हैन योथोडामूत्रहेउ अरु पीला अथवा मलसूत्रवज्ञाहोवे कारुकनावे रक्तांकेव णशुक्र उष्णताकीवालालालरंगकामूत्रकेरतांअसा

इतिमेनेण । मूत्रस्याक्षोराननमेहोष्म कैलमेहोवलस्यान् नायनेशर्करामेह शुक्रदोषणावहदयः १९ शुष्कमहानिशुक्र वक्कनेवेगधारणे गमवेगविघातेन मूत्रेणासनलेहूयः २० इत्येनान्याथापराणि पंच मूत्ररोगसमुद्भवाः यस्तुमूत्रेसोमरक्तं पीतंवहतिमूत्रः २१ उष्णाणकोनमित्रा निरंकेषुत्रेवयःकुरुने यस्यग्रीवाहहे त्रिकेवपादाश्ववाजिनस्तस्यः २२ अस्या होनितेस्थवनस्पमहासंभयुक्ताकः ग्री वाश्मार्थवानोयःस्तयोवाभिवोसनेनि षक २३ अस्मायनिनेशामंग्रहोनकामान वामोनि नोहैनायोवीनायाश्वोभयानेवनु मनिलतयम २४ तत्र्येवनमस्पमस्माल भसनिहिहः २५

यमाणा जिसवाइकीवाहीगिठ त्रिकऔरमंवमदहोमाणा २२ अरुगलनाडीपांहस्यादिसंभ होणोमहासंभयुक्तवोहनाणा अरुग्रीवाकापछीमहकेन रक्षाकरना वीहृयरलयनहिसकहाअरुग्रीवाउपरहेशअरुहोने वहीयांपाणेनहिनोहीजिसकीअरुमस्यानाडीरोकीगेरहेनानि सकैमसमंभकहेणाहे २५॥

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रन्यास्तंभ अवकपोतनिषादस्तंभ कहते हैं जिस घोड़े की
गोता में डोरीआ कडीना हो अरु फर के अरु मन्यास्तंभ जावे ति
सको मन्याचालिनाश्रो घोड़ा भोजन थोड़ा खावे ११ अ
रु पीड़ा करके पीड़ित वक्र की न्याई भ्रमे अरु पटों के भा
र गिरना है अरु लङ्गन दिन कदा अरु अगले सेबों के भा
र खेलार हिना है ११ अरु वक्र कीन रांफी र के विस्तार नहीं
धान आन वनों के भार गिरना है जिस कौ ऐसे इसन रों के

इति मन्यास्तंभः अथ कपोतनिषादस्तंभः
पंचेविधा थोड़ोत्रोवा थोत्स्ककरणोपश्यद्दृष्टपने
मन्यावालो निनेवे घोमदाहारेनरगमः १ ९
यो वेदना भिभूतोह्ययो भ्रमाति मंडलपतेत्
ग्रोत्पा उत्थानु नाहि शक्नोत्य थाधिमाम्पो
सिपतः पतत्रा ११ पार्श्वतते विसंस्तभ्रवक्र
वप्पौषित विनचनेन पंचविधेस्तालि
ये कपोतमादोसमाहितः १८ इति कपो
तनिषादस्तंभः अथ हृष्टग्रहस्तंभः
पत्काये न त हृष्टेन रूपेनाना यवतेने स्ते
भात् कुक्षपृष्ठांगा ख्यातिमेषा वा गा
निविधुमोजे १९ हृष्टे न विवैग्रहीतेका
ष्ठीभूतो न नाम्यतिन रगः उत्थामपि
रिक्तं हृष्टेन तस्मात् हृष्टग्रहं विधान् २०
इति हृष्टग्रहः अथ हत्ववहस्तंभः ॥

लक्षण होन ते नोइ ने को करके कपोत सा दीख के देखा है
इति कपोतनिषादस्तं अथ हृष्टग्रहस्तंभः जो घोड़ा पिट
के कक जाले करके स्तंभ नें थिमन हो करके गरिफिरता
अरु कुवा मैं होता नहीं निश्चय करके अरु अंगों को व्यथा
रिकमांटा है १९ हृष्टन लो करके ग्रहण करी कौई घो
ड़ा तो नहीं नमावे अरु शिर कौ उठा करके लौट रहे जि
स कौ पहेल सा लोहणानि स कौ हृष्टग्रह कहे जाते २०
इति श्री अथ हत्ववस्तंभ का॥

© Dharmartha Trust J&K. Digitized by eGangotri

152

[illegible]

[illegible]

[illegible]

© Dharmartha Trust J&K. Digitized by eGangotri

इतिस्नायुगतेभी अथस्नायुरोगकहतेहैं वातकुस्थाननैंकोप
कौप्राप्तहोयपा सरनकौंदरदेताहै जिसकौअरुप्रांतोंता
रसवादमाडिकोरोकलेताहै जिसकारणतैंसभइंदि
योंकेअर्थकर्मकोहाथिनरोनहिंजाणता ८९ सभ
नोंवोकोइनोराववनाहै अरुभ्रमदेहसारे परकिनेवी
सबनहिंलभदा अरुदोनोंस्तंवोंकरकेहथवोकौपु
टदाहै अरुक्लानि औरनेत्रजडहोपहैन औरमनतैवि

इतिस्नायुगतेभी अथस्नायुरोगाः कोपात्ख
लेतस्यानाडायुःसंज्ञाविमोहयेत्पुस प्रा
णोसिहरणाद्विनः सेंद्रियार्थेनबुध्यत ८९
सर्वेषामन्ताबोविभवेतिविभ्रमतिनल
भतेसौख्य पश्यांवेलयतिभ्रूमिलत्वो
दणतुरोविमनाः ८० अससमर्थोवा
स्याद्वेगेवेकोनिनेवयोवाजी उह्यतः
खिन्नस्नायुरेवप्रमितानोवेषमेन्यर्थे ९८
पक्षमगीवेकास्थितोनाचिकित्साकाचि
दस्याभिन्न ९९ स्नायुरोगाः अथआक्षेपकः
योवेदनाभिधमन्यः सर्वेकायेनसंस्थि
तेस्नायुः सक्रान्तिमपदेपच्छाद्याराक्षे
पकस्तथा ९१ आक्षेपकः ॥

मनहै ९० सोवोड्डारवड्डरोगकोंनहिंसमर्थ अरुबल
नाकाहेसमर्थहोवे अरुग्रादरेकीन्याईहोयग्राहै स्नग
हरणकीतरां अरुपरमासवहनऔरकेवदाहै येस्नायु
रोगवालेकेलक्षणहैन इसकीचिकित्साकिनेवीन
हिकरणीकहि ९९ इतिस्नायुः अथआक्षेपकइसपडिका
लक्षणकहतेहैं योसोवा बडीपीडाकरकेइसवीहोया
दा सगलेभागकरके रहताहै अरुपित्तलेवाम वारवारसं
कोकौबड्डदाहै जिसकौआक्षेपरोगजाणे ९० इतिआक्षेपकः

© Dharmartha Trust J&K. Digitized by eGangotri

अब आध्मान कहते हैं वायु करके पीडित है जिसका कंठ
दाह अरु परस करके अंगों को न हालता है अरु खाया अन्न थो
डा खाता है अरु भ्रम होता है अरु उलटे रस से पीडित होके वल
ता है ११ वायु करके जो देह को आध्मान नाम करके रोग क
हिया है जिसका पिचला है सो ढीला हो जाता है और त्रिक जि
सको वेधया होवे की नरी होता है तिसको आध्मान कहते हैं
इति आध्मान अब आटिन वात लक्षण वा केलह लक्षण कहते हैं जिस
को लाला वगण मंदाग्नि अरु नाशा वेशा भजना वनासा को

अथ आध्मान वातनाभि भूलकायः अवेपते
वैन्निषेवनेनवेग मेढ्रो हार आध्मानि गच्छ
त्यन्नां गमास्याय ११ वक्रपश्चिमकाय
मा विध्मन वपस्तिकवन्ने द्वापि नहे आध्मा
नमके नरोगाणमाकनेनेव १२ इति आध्मा
न अथ आटिन लालामंदाग्नि वेना
सावेशा श्रमस्यनेपश्य विहिष्येने वदन्व
ते वैनाटिनेविषान् इति आटिनः १३
कारणैः कुपितः प्राणः शरीरे मामुयात्
श्च नस्मात् दाके पने वानी उन्मार्गे वा प्रि
गच्छति १४ मेढ्रोहार सत्याश्यान्मुकु
मेरुः मवलनेमश्च विषगवानौ सवेले
योऽरे चिन्मन मोमन: १५ ॥

अउत्तीसी होजाती है और गलो प्रेत्तीयां होजाता तु रवे फिके
तो वेतिसको आटिन कहते हैं १३ इति आटिन वायु के
विकल्प होना के कारण करके कुपित हुआ प्राण वायु
सो निरंतर शरीर विषे प्राप्त होकर के इलटी गति को
प्राप्त होता है तिससे चोड़ा कें बंदा है अरु भोजन थोड़ा क
रता है अरु वार वार निरंतर डिगता है इनोल खाणा वाले
वो इकौ सिखरानी नाम रोग वाला नासे वेग पदहे वे उड़ा
लेकर के चिकित्सा है का कष्टसाध्य कहेया है १५

© Dharmartha Trust J&K. Digitized by eGangotri

इति विषगर्भतैलस्तंभनिदान॥ अव सामान्यस्तंभ कीचि
किकहतेहैं पहेसमप्रकारकेस्तंभकादेह आकनाण
वायुनेहोतेहैं निस्प्रकारके रुकजाणशरीरका शोषस्
कनाण वालखडेहोजाणे अरुकरडारुषाहोणा अंगो
काधारकेवृण होनाहोणा ९६ अंगभजने अरुधातवत्ती
णकेवणाऔरमदिरापीनेहोएकीनरांअमलहोणापी
डा अरुतिमविषनर्षनहिहोणा अंगटिलेहोजाणे औ

विषगर्भतैलमाम् इति स्तंभनिदानम्
अथ सामान्यस्तंभचिकित्सा यनेस्तं
भासमाख्याताः सापसोमारकनाम्नकः
स्तंभः शोषोरोमभेदः पारुष्यं वेपथुभ्रमः ९६
अंगोपाचानुतयः केपामार्यकरुक सानिशो
णेना सर्वेषामेवनिर्देशः सामान्यस्तम
लक्षणं ९७ येष्वस्मै तैलजाके विद्याप
यस्त्वनुलेपिनः अभ्यंगाः परिषेकाश्च
सेदाः श्वानमर्दनानि च ९८ यथा शस्तं
प्रयोज्याश्चनेषामपि वङ्गचूर्णैः भला
नकायममभ्यंगसैंधवायसमधायिवा ९ ९
नथायमसारिणीतैलं शतावर्यामसे
वच अभ्यंगेनावनेवस्तो पानेवैवय
योजयेत् १००

रसभप्रकारकेस्तंभकेलक्षणसामान्यस्तंभविषकहे
न ९७ येकोर औरवायुकरकेरोगकहेहैन तिनोंकों
मालसा औरथोणसेकदेणापरसेउआणा मईमलणा
९८ बहूषणासकेमानणेवालेयोने योषणासेमकरदेन
सोकरणेयोग्यहै भलानकादितेलसैंधवादितेलकीम
ले इनकरावे ९९ नेसैंहिप्रसारणितेल सतावरीआदितेल
मलमनमसाराप ह्कारि अरुपीणविषै योडेकावने १००

© Dharmartha Trust J&K. Digitized by eGangotri

ग्ररू योश्योनाकेठोरश्यादियोगलिकोफैसोपिलावे
सोसमस्तरोकेस्तंभकोनाशकरतीहै ग्ररू शुष्कसमूलादि
ग्रयपिलावेवैद्य १ ग्रोरमहास्नेहमिश्रकस्नेहसेवहनन
नरवावे फेरमलसकरायहोयकोपरसाशुश्चादैस्निग्ध
हनेनेलपिलायवोइकोस्निग्धपचकारीउत्रावे फेरवा
सककाथकीपचकारीवडावे २ यतेसामान्यस्तंभकीचि
किन्साकहिहै अवग्रोरविशेषचिकित्साकेपावेंयाकम

श्योनाकाग्निबिल्वेलेपानेसर्वैस्तंभविनाश
ने पयः शुष्कसमूलघ्नपानेस्याद्धितवत्
तः १ महास्नेहमिश्रकेचैवहननेवापिर
पयेत् अभ्यङ्गान्स्वेदनान्स्निग्धान्निरू
टाश्चानुवासयेत् २ इतिसामान्यमुदि
ष्टंसर्वस्तंभचिकित्सितं वैशेषिकमतो
वक्ष्येविदधुनाम्नराः ३ अथयकृ
त्तोकचिकित्सा उत्कारोकेनपूर्वंते
लेदयानस्यायवचाये उत्सादकेनसंशु
केसमांसेनवानसंशामने ४ अथवाकृं
चमस्तोस्नेनकुष्ठेनेलेनमर्दयेद्वने
स्तदः शाकरंत्रिशाकनत्रिफलाद्याश्चापि
केनेयः ५ पाकेचसराग्णेदीहिरुवनिविषप
वलवणाकलाभिः द्यासेपयोपिपाले
हनगुकेनकमानेव ६

नेसैकहनेहे ३ अथवाउक
रोकरोगकीचिकित्साकहनेहो तिसविषेपहलेनेलदेव
नेसहितमांसपानितसाधणोहोरारदेवेदयाहोजायोवानेदेनि
सकोसमनकरनाहै ५ औरकुष्टके तेलकोमर्दनकरैमल
दनकरेपांसाथुधावे और गोमूत्रकोरकेवात्रिफलाकेसा
त्यासकेदव औरमदिरा पुरहि इमीसपेनेलूणमसां १
नोकेसाथपिलावे औरसेंधालूणमकोकडेसाथपिला
वे अथवावकरीकादूधपरपिलावे ६

© Dharmartha Trust J&K. Digitized by eGangotri

नगेबेर कुलथ कशीर म्धे उ विलकथ ओर हम्मल विल
णक पीर अग्निमथ पत्तरण टांटर कंडआरी कंडआ
शम्भरकनीरथर भलुडे इनाहे क्वाथ्य विषे ७ घोडेअने
ल ओर मिउ विवपावे जीवक अरषभक ककडश्रृंगी मेदा
गलोअंड कुटमुलटी ज्वाहाम मूगपर्णी माषपर्णी का
कोली छीरकाकोली हरदल इनांको उदमाषपीवे २
काषमिलाकेकाडे पहूवे हम तेहकहेयाहे इसको ९

अथ नवकोलकुलत्थाः काश्मर्यो विल्व
दीपिका चेव हीबेर पंचमूलं क्वाथ्य वेषा
समाहाय ७ सौवीरतैलं च असोन त्रनखो
भाजीव कर्षभकौन्तु कर्कटश्रृंगी मेदा
छिन्नरुहा भद्रकावेव ९ कुष्ठं मधुक
सनैतास मुद्गपर्णी माषपर्णी च है
काकोली पारसनी पिप्पली दीपेण चैमानि २
क्वाथ्य विमिश्राणि पचेन्तैलं तेषु षष्ठको
तैनःस्नेहः पाने वस्तौ नस्ये वाभ्यंगे चे
व युंजीत १० वदराणि पंचमूलं यवाः
कुलत्थाः सानावरी चैव आढाप हैवव
लेमवीतिपनानि निः क्वाथ्य ११ क्वाथेना
नेन पके सर्पिस्तैलं विपाचयेत् मानिमान
पनमेप पाने वस्तौ वाभ्यंजने हितं १२
अतोणस्यन्नैव पाः शोषरवप्राप्यैकपांडुआ
मामिताः

पीनेथाले ओर पछकारी उटाणिविखने
सवाये ओर मलसके विषे घोडेवेध हैर पंचमूलवि
लाणहरारण टांटर पाटल कसीर ओर मडे कुलथ
शमावरीदमणी बडीपमणी इनांको बरावरघायकेका
थकरे ११ इसकाथकोवाट गुणापायके घेर अरुतेल
वैद्यपकावे इसतेलवा घृतकोनस बार पामपुरुकावि
मालसकोदेव १२ घोषोडेवलवालडोपनिसकोपम्ड

शा
टी
१५५

155

इषुडीग्रकटोड़ीउपरकीउपोंउकीनाड़ीवेपरकरे ग्रस
केरूपफकोरेउड़ाकेघरेरवकरेकालङ्कपीनेकोदेवे १३
त्राणकारसग्रोरमोकडीकेफलकारसकोमिलाकेदेवे
ग्रोरयोवऊंस्मानेनेलयोकरेयाहूसोदवे ग्रोरमदिराम
लीरमिलाकेपीणेकोदेवे १४ ग्रोरदशमूलकाकथको
रक्कीनरोकाउके सत्वोस्मसीलगर्भकोपढकारीउप्ल
वे सोवीदिनकरहै १५ येकरयोसर्वेउपायकहेनेनिरूह

ग्रास्थापनेचवस्तिः शोणितमानेचपाना
य १३ दीपकस्यरसनीव्रेमानलेगरसावि
ते कंदमानकनेलवलोहंचेवस्त्राग्रने १४
दशमूलकषायंवक्काथेनेनरोणहकने
स्तैलस्माकर्केमनुश्नेकार्यमास्थापने
हिते १५ यथेवेवत्तखीनस्यादग्निकर्म
ततःपरं यवमनकर्णकीवाहस्तस्मा
द्योगादिविच्यते १६ इतिउत्कर्णिकवि
किन्सा॥ ग्रथमहास्तंभः नाडीस्वेदम
हास्तंभकोर्णतेलेवदापयेत ग्रभ्यंगना
वनेपानेमहास्तंभेंरुपयोनयेत १७ नित्र
द्वबस्तिकर्मार्णमहास्तंभनकारयेत
कर्णयोर्दापयेत्स्वेदंनस्यकर्मचकारये
त १८ इतिमहास्तंभः ग्रथमन्यास्तंभः

माथमरदीकानिरोग्य नाड़ीस्वेदामवग्रग्निकर्मचराद
देवे इसप्रकारउत्कर्णरोगवालाहोउनिसरोगनेछुटजा
है इतिउत्कर्णिकाचिकित्सा ग्रबमहास्तंभकोउपायक
हनेहैं नाड़ीकरकेस्वेदपर्णमेंकरदेवे महास्तंभविषे
ग्रोर कानोंमें तेलडारे ग्रोरयोग्रादिविधेन हास्तंभकहे
याहै सोमानतमस्तबस्ति ग्रोरनसवारविधिनहास्तकरे
निसके १७ ग्रोरमहास्तंभनकरकेनिरूहबस्तिनवाले फाडे
वे ग्रोरदोनोंकर्णोंमेंपावेसकरनमसवाकरावे १८ इतिमहा

© Dharmartha Trust J&K. Digitized by eGangotri

स्तंभः अब मन्यास्तंभ वालों कू जाणीया जिसरोगविषे
घोड़ेकी देहीमलके स्वेदपर्शा श्वासावे फेरपरसायकस्थि
गपड़ेपघोड़ेकी काढीकी नाड़िविषे वेपकुपिरनिवासे १९
दिखावरूरदलदालरूरदलकोगड़कौड़गुड़ मर्गा खेम
इनोकोमभूनामयोमादेशाकसाथपीनेकौ घोड़ेकोदेवे
वेग २० अरुघोड़ोनेलसाथस्नेहकरकेघोड़ेकोफलक
रखा इत्यादि वस्तुकेसाथस्वेदसेकदेवे औरसरेपाघोआ
दियौतेलकेहूयाहै जिसकेसाथवेपनकरेलू एसेथाया

मन्यास्तंभेनवाकस्यमर्षिषाकस्यकारये
स्वेदं स्निग्धाभिमस्यनतोवङ्वामन्येयाः
श्वापाये १९ स्वरदारुसारोहेहेकुष्ठं नेनि
कंदोहणोस्तुटो मागधिकाचोशीरेम
धामवसेघृतपाने २० अश्वतैलमपिषाकां
श्वेदंघफलकादिभिःस्वेदः सिराधोधे
कुर्यादयानाहेस्नेहलवणसेयुक्ते २१
प्राणस्वबीनमनसोगोधूमयवमाषकु
लस्थानिलाः दध्याचसहसंधोनेनदेकरा
श्रोधितेननस्तेन २२ उपालिमूत्यास्वमन
फालस्वेदमकुर्वीत अभ्यंगपानवस्ति
स्तुदेयःस्याच्चेहनस्तनःस्नेहः २३ रसभो
ननेवमांसानिकोकटाम्नोकदकादीनि
नचैवमपिसस्याःस्यादम्लकमतनःपरे २४

धकरके २१ औरप्राणबीजनेहूअलसी कणक नदोम
हों कुलस्थतिल इनोंकौमहिसाथपीसकेरलावेपकरान
सेहूरखे फेरजिसकरके २२ जिसकेसाथलेपकीयेहो घ
बोड़ेको फालस्वेदयोग्य वेककेयाथाहै फालनुपायकरके
सेकदेवे और माल म औरपानवस्तिपक्षकारी इनोंवास्ते
वेहनस्नेहयाकरपावे सादेवे २३ औरखाणकोकुछड
और जेदकमन्यादिमांसोंकारमद्दवे नवइनोंकरके

© Dharmartha Trust J&K. Digitized by eGangotri

भा.
टी.
१५८

वोऊगराजीनाहोवेतो अग्निकर्मजैसेकहेपाहैतैसेकरे २४
अरुमन्यापोगलकीकेउपानाडीयो हैतिनोंकाउपरैरखो
कौनिकासअरुमोंडेपोंविषेचकुकीनरादाचदेवे और
वाहुओमेरखडीयोलेलेदाचदेवे और वाहीयोविषेवा
टकीनरा दग्धकरे २५ और अरुमानामयोमादेराहैसा
मंचोसाथदेवे औररुउरकेसाथनेलपीएकोदेवे २६ ॥
इतिमन्यास्तंभचिकित्सा अथकपोतनिषादसाध्यकी
चिकित्साकरे कुष्ठनैलसाथमालसकरे औरस्वेदसेक

मन्यापोगंडेलेपानचक्रं कुर्यान्मयोभयोः
अंसेपोगंडेनेस्वानन्माहोकबीनचागदे २५
अंसेनापिप्पलोगुकेगुडनैलेचपाययेत् २६
मन्यास्तंभचिकि: कपोतनिषाद्साध्यासा
ध्यमपिचकारयेत् अभ्यंगंकुष्ठतैले
नमर्देनस्वेदमेवच २७ वसामांसप्रसैनैल
वकषायदशमूलजै पक्कमभ्यंजनेच
लोनस्यपानेचदापयेत् २८ यद्येवंचस
लोनस्यादग्निकर्मततःपरे २९ इतिक
पोतनिषादचिकित्सा हृष्ठस्तंभचहनने
नेमेपवेसाकरोविसा अभ्यंगेनस्यपानेच
ह्रोमेमारुकेनैलके ३ मद्दानिलानाने
लचसलोमेलवगोकने आनपेनमका
हस्यपानमसमप्रदापयेत् ३१ ॥

देवे औरनिरुवेउनेलत्रुकटफसलका यसाध्यपकापहो
पहै तिनाकोंमलनमयरुवस्तिपरुकोरिबासे और नमवार
पानुकसनरवेवेघ २८ प्रहरनोंउपागोकेसाथसरवीनिरोग
मारेवनो अग्निकर्मकरे २९ इतिकपोतनिषादचिकित्सा
हृष्ठस्तंभकेविषेवोरैनेलसेथानुगा और सुरकीचवी नम
वारवासेओरपीलावासेलोरनवसागरमपागीनेलदेवे ३०
अकमरागिलयाकहेनेतिनोकानेलगर्मकरकेओरलगापा

© Dharmartha Trust J&K. Digitized by eGangotri

यकरके घृतके साथ नपेया होय वो चोडे न्हार पीनेवास्ते दे
वे १३ अरु घृत तेलके साथ सिमनमेकके फेर अनुवासन
नामवस्ति देसाकरावे यह दोनो करके रोग न हटे तो अग्नि
कर्मलीवठ अग्नावे १२ इतिहृद्स्तंभचिकित्सा अथ मृग
स्तंभचिकित्साकहते हैं मृगस्तंभी घोडेको सेरयांकाको
डानेल कुठ सेंधालूण मैनकडी कारसयायके
पकायलेके तिसको अंगमो लसवास्ते देवे फेर मर्दन
कीये हो पकोसेका स्वेद यो सवेक करे याहे मोसेके देवे १४

सिंनेच घृततैलेन नानिरूहं वानुवासवे
न् स्वेदोनैवंपदि भवेत्तन्नो भिमवनार
येत् १२ इतिहृद्स्तंभचिकि० अथयोग
गचि० मृगस्तंभी निदानो लोकः मोकल्ल
मकर्मसमारन् तिनसर्षपसतैलेकु
ष्टासाचसैंधवं १३ मालेमारसैवेव
पक्कमभ्यंजनेभवेत् तैलाकमर्दितेसे
दैःशोकरायेस्तवेदयेत् १४ प्रागेवाम
युकेतोइम्मेगा रककशोरकः विप्रा
मिवमरणलेवपयस्यापिप्पलीनया १५
प्राप्नेवपथमासाईकृप्रवोडूपायपेदूपे १६
इतिमृगस्तंभचिकित्सा० अथमृगरोगचि
कि० वायुग्रहइतिख्यातोमृगरोगस्तुवाजिनां
नवशांतिस्वकनेश्या ग्रहाणंवापिपाकिया १७
कालिवेलमलटमरवीरसंगग्रामयर विष्ठा--- वर्च
भयकमलनरहीरकाकोलीपिप्पलीमधो १५ इनो
कौवकरीकेदूधसाथ प्रातकालविषेघोडेकोपिला
वे १६ इतिमृगस्तंभचिकित्सा० अथवायुग्रहकीचि
कित्साकहते हैं घोडावायुग्रहनामरोगकरके
कौतिसकोमोहमरोगनामसोकरयोयोगपदै यो
ग्रहोंकी शांतिजिसमनरोहैतिसीतराकरावै १७ ॥

जिसवरमैंचवरखाचफेरआवरणकोटहोवेगरुयमि
जिसस्थानविषे संस्कारकरीहोयतिसमैंस्थितकरे शुद्ध
रनाकरेफेर गुग्गलतोलआधाटंक३ वर्णकोअ३ - और
सेनीसरस्या योगइनोवस्तूओंसाथरूपयनसिद्धकरे
तिसचेडेसाथमर्दनकरावे श्रकनसवारसलाई ति
सकेसाथकरावे ४९ येकोइशरीरकारोगहै येअंगको
रोकनवालाहै अरुज्वर अंगविषेछ्उफडीइनोंसव
नारोगोंनेमकहोताहै ५० औरश्रककीलकडीसाथ

सेहुंडेस्थापयेत्स्थाने तामिम्भानिमसंस्कृते
गुग्गुलं मरिचं हिंगु वचा कटुकरोहिणी ४९
सर्षपः सैनलशुनं सौवीरेण विपाचयेत्
तेनाभ्यंगश्च कर्तव्यो न स्यात्कम्पोऽज्वरोऽपि
च ४९ यकेचिद्बाह्यजारोगा ग्रहोपचा
गकारिणः ज्वराद्याते प्रकाशेषं सर्वे
प्यः पीडिमच्यते ५० अर्कस्य हकनाभ
मोहेनेन साहेनः पुनः नस्यपाययेच्चावि
हिनस्वीश्वमपुनामहः ५१ इतिग्रहा
रोगचिकित्सा सौविरभोगेपानेनवमे
पकंपायजयेत् शुद्धचीवीरकारेकमपु
कैःस्थानमणाकैरं ५२ नस्याभ्यंगपानरोषु
कवल्यःपानभोजने हीरहेदुव
नेटोनिसकरोहिणीगुडो ५३ ॥

योधूमकीयाहै अरफेरसूनमिलाकरभमहैसोनसुग्गार
स्रोपातुनेवालेहिमकरहै औरचीड़ीमकीरसाथदेवे ५१
इतिग्रहरोगचिकित्सा गलोइत्पकुरेरमलहीलडमा
धरनाकरकेसिद्धकीपायेंवनेहैसोमालसपानन
सवारडनोंलिखेंहैं ५२ नसवारमालसमेवनवस्नि
पान भोमनविषेदेवे और हरदलदालहरदल
टोटरभोनपाटाकोउडं ५३ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

इसको खेसरनांको आमलमदिराभेदनिसकेसाथखा
लपीनेकोदेवे औरसेंहुंहजवानेलखेड़साथखुलावे
औरसनुत्रोंकेसाथउपयापिलावे अथवाहुलनकेसाथ
पिलावे ५५ इत्यामामिनचिकित्सा अथएकांगरोगको
अलामकहतेहै जिसवोडेवाअंगआगमेंवापछेनेअथ
वासजेपासेनेवारवेपासेदा सकजावे वातपित्तकफ
रक्तादेकोपकोप्रामहोनेकरके सोएकांगविकारकहे
ताहै तिसकरकेदेहविषैकोइएकचरजेसाउलासहो

मार्गेषुकोष्ठोरेसमसेषु जनेपानीत
नेस्वेदहः सशाकैरक्षैवमसक्तभिःसीव
सर्पिषा ५५ इत्यामामिनचिकित्सा
अथैकांगरोगचिकित्सा सर्वमथ
पात्रिमेवादहाणमथवेनरंबरेगस्य
शुद्धस्येकेगात्रेपार्श्वकाण्डेनेवोनेपिन
कफैः ५५ एकांगमसविकारः कार्यके
हानिनेनजापेन भिषग्नेवसवेलेव
सर्वेषान्नसर्वविस्रावः ५६ एकांगावि
कारहूतेजोष्यामोमास्पेणहून्यनेवाजी प
वमनाध्याध्यापिः सदाहणश्चैवनिरुहै
हः ५७ अहीनाध्यानमादावेकोगवि
कारनः पारिमाथः स्नानोमोर्ण्याभ्या
दमध्यजन सर्पिषावेन ५८

मानहै सोभेदकोप्रामहोयातावगदाहैसोवेदयादानि
सनैस्कवराहै ५६ एकांगरोगकरकेयुक्तवाड़होए
सो निसपकरवेमरनाहै इसकारणतेपहेविकार
साध्यकरनकरेयाहै अथवामासकोजनतोशालेपीने ५७
एवघोड़ालीणक्रपशानाहोवेलहाएकांगविकारबोले
कारुधिरपरनेहिानिकालदेवे फेरस्नानकराकेल
हारैकेनरगनिसकोमैमेमाथ लेपकरतेहैवेसरे ५८

© Dharmartha Trust J&K. Digitized by eGangotri

मदिरा समान कूठ खेर मरव मवा ग्रंड और बाङ्लिमदि
रसाय वैद्यपीयेवासे देवे इसकरके वोहारजो होजाता
है ४९ ग्रहगलोके काथमांथत्रिफला हरीडवहेडे आम
लेकोडखेड मिलायके बुद्धिमान नेपिलावे और निरु
हवस्तिकरावे ५० वलसीमालतीवटलवेलकरे आरा
कृमरकुटैसनगंडकार्दमाणविआइटसिटकाथको
हो मेढसिंगी कसेर कुमदनापैके फूलहिङ.पाटला
और बडहनपंचमूलवडापंचमूलकरके औरमदाइना

शालाहरेणुकुष्ठानि शार्कराणां घवाहलि
पुनर्नवापानेरथाश्मानिमानेवाहिम्लोभ
वेदष्टः ४९ यमनाकाथोविमंत्रोत्रिफला
कटुकामपार्कराबैव दद्यान्मांनेमानि
मानिबूहेनेबस्तिकर्माणि ५० सुरसाद्व
मनापाटाहरलीकर्वरकुष्टरासाभिः
शृंगरोरोगजोरिवकपुनर्नवाककमाजो
भिः ५१ मनस्योगीश्रोपर्णीकुमदच्छद
हिं गुपाटलाभिश्च ब्रहत्पंचमूलेनव
दयाम्यानैनेलंचूर्नवेननः ५२ यष्टयंगे
मानैनेपानेश्रेष्ठःप्रोयत्रुणापहः अ
मांनावहिकर्माणि यकेमेदनमीखेत ५३
इतियकोगरोगचिकित्सा एवंवा
तरोगचिकित्साध्यायसमाप्तः ॥

केसाथ चूनवानेल मिलकरके पानविषे और
मर्दनमें खाणेवाले श्रेष्ठगणहे शोषकरके वा
यकोहरकरनाहे इनोंकरके मानना होवेन बसुभि
कमेदागरहे पेपकमावेनो मेद चीरादेनाक हेयाहे
५३ इतियकोगरोगचिकित्सा ॥ इतिवातरोगचि
किल्साध्यायसमाप्तः ॥

© Dharmartha Trust J&K. Digitized by eGangotri

अथ सामान्यरोगचिकित्सा। ये रोग घोड़े को मुख गल
विषैं निदानस्थान मैं कहे हैं तिनाके स्वरूप अरु भिन्न भि
न्न तिनाके उपाय अब कहूंगा हों ५४ जिस घोड़े के मुख ते
दुर्गंधि सहित कफ आवे और लाला वगन अरु ताल मैं शोथ हो
अरु निद्रा निद्रा होवे बहुत अरु शिर बारंबार मारे उवाक
रके ५५ यो घास का ग्रस ग्रहण करता है अरु दांत पीला
ता है तिसको उगल देता है इनाल त्याग करके पुरु होवे
तो वालके नीरोग कफ करके कर पीड़ित घोड़े को होता है ५६

अथ सामान्यरोगचिकित्सा। येषां पर्यायो
निदाने कथितानामश्ववके त्वास्यरोगाणां
तेषां रूपाण्यपनामानि क्रमेण च प्रवक्ष्यामि ५४
यस्य मुखाद्दुर्गंधिः स्रवेल्लालावस्थाने
तालुनि शोथो वैवास्यर्थं मुहुर्मुहुः हन्ति पनाशि
रश्चैव ५५ यवसं त्यज्य मञ्जरीनामसृक्छिरे
त्यादने च दन्तवालाकिं निर्विघ्ना
कफरोगेण पीडितं तुरगं ५६ तालेष्व
यस्य शोथो गङ्गपदस्मानि भेषजस्य पाने तालु
वरकाध्माने मुहुर्मुहुः प्रोथते यास्यः ५७
कफलालाविलवदनः समग्रिरे दर्दरे भ
क्षितेषामे रूपमवालाकिशोटशोपस्य भ
वेदवाने कौ ५८ जिह्वाक्लिमास्वनाड
गैष्यानपवर्तने वदनात् ॥ ॥
जिस घोड़े के ताल की पांना डी यांगे रूप दग डोय बिक्ष
कुल वो गुरल स्रवण ताल लाल अरु फुला द्दा होवे ५७
कफ कोजा बारंबार डोरी को मारे ५७ कफ और लाला क
रके गेर मुख तिसका अरु दर्द होया अपर बोदा ग्रास
उगल देता है अरु त्रभत लक्षण स्वरूप अबालकी रोग के
हलाई है सो अबां ने कना म रोग कहे या है ५८ ॥

श्रा
हो
१५९

159

जिसकोनीभीरोनीहोवेग्ररुसनीदहोवेग्ररुमुखनेमा
डीगंधी श्रावेश्रोरमुखनेवारनाश्रावेश्रोरनीलवर्णकीहो
वे श्ररुलहूकेरंगकेफोड़ेयोंकरकेयुक्तहोवे श्रोरजल
वेगमुखनें ५९ वोजालिमावकूनहोनानाहै ग्ररुमुखजो
भाकरकेभरेपानानहै श्ररुदीन गरीबविमनहोनानाहै
श्ररुयासश्रोन गुहन मदिकरदा इनालहृणाकरकेयु
क्तमिहासलभीयोडाकइयाहै ६० जिसवोडकेउदकाले
भडेहोवें गभ्यवालालहोवे श्ररुंददोकेमांसलमवपावें

नीलायकृत्स्नवर्णास्फोटहनाचजलसा
वा ५९ हामसूरनसंस्थानेयोनिह्लाप्राणंनतो
ऽरोदोनानवरवाटनमादृशेनिह्लास्ते
भीमानिरिदिष्टः ६० श्रोष्ठेणपावौरक्तौदे
नामोमालिपयम्योशिये नेला लामेदाम्भि
वेमल्लनरनेनमप्रानिरिदिष्टः ६१ हन्वो
रपोनिगालेकंटेवापय्नायनेप्राधः
मेदग्रामनरगंनेविंघनकंटमालाकेन ६२
स्कंधोप्रोनालनयापमहाणामंप्रुता
विवर्णाःस्युः ग्रकृष्ममनवर्णाम
लिपाकेनमप्नानोयान ६३॥

श्रोरलालांवर्णग्ररुमंदाग्निहोवै जिसको पहेलहम
णहोवै नोपल्लनजामरोगकहे ६१ हनुमुखगलको
संधिविषे श्रपवाकेश्वविषे जिसचोडकेरोजाहोजावे
श्ररुग्राहारकफनरं खादानामावेनिसकोकंटशालुक
रोगयुक्तपाणवेद्य ६२ लोखोउटनालेनिसचोडके
फुटटेद्यापवालेहोणवाकीगुणीपावालेहोवे श्ररुव
रोगेन विगड़ेयाहामाडाश्रोहोवे श्रोर लामेकेसमवं
होवेनिसकोवेघमखापाकेवागनाशो ६३

जिसको रोडके जीभ्या के मूल विषें कंठ में गलविषें शोजा
होवे वाहन वाला देहट शोथ होवे तोतिसको हनग्र
हवे घनाजाणलेवे १४ जिसको वमन वारंवार श्लेष्मा के
उग फेन चिपचिपानी वाले नेवने अरु कंठ विषे लगी
विहृत होवे तवतिचारेको छर्दिरोग जाणे १५ जो भो
जन खाया है अरु आमाशय विषें पड्या पाहे तिसको यो
डो कवमन करके देता है पका होयावाक वार हैयाद ६६
उपरे स्पष्टदा है तिसकी चिकित्सा उ हिमानवैघनाकरे

जिह्वामूले कंठे गले च शोथ प्रजायते येन
स्य ह्रुव मूलाष्ठाय स्ला हल गृहेन स्यज्ञा
नीयान् १४ छर्दयति यस्य मन्ननं श्लेष्मा
णं फेनापिच्छलेसाह्र नचैव हृन्यकंठे
नस्य छर्दिर्विज्ञानीयान् १५ आमाश
यस्थश्लेष्माभयोभ कंठे छर्दयति रोगो वै
ग्रविपकोपकंवानस्य चिकित्सा न क्री
वीन् १६ स्पपथुः प्रलंबमानः सोपि स्या
त्तालकंठयोर्यस्य रोहिणीका सा क
थिना गलशुंडी वा छिन्ननंते: १७ जि
ह्वापाश्चाथस्ता शोथस्तैवोपजिह्वक:
कथित: अधिजिह्वा या नीयादेवैवेवो
पजिह्वान: १८ मूलेभ्यो दंतमांसभ्या
यस्यानिर्याति शोणितम् ॥

जिसको रोडके तालु अरु गलकी संधी विषे शोजा लंबकप
या होवे सो रोहिणीका नाम है अरु थोडे के सासके जान
णवाले गलशुंडीकी कहते हैं १७ जिसको रोको जीभा
के हेठ शोजा होवे सो उपजिह्वक नाम रोग कहा है अरु यो
शोथ जीभा के ऊपर होवे सो अधिजिह्वा जाणलेवे १८
जिसके दंदां के मूल के मासतें लहू निकसे अरु दंत हलवे

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ प्र॰ ९८

होणातेउपदेनबुद्धिमानवैद्यजाणे ११ अरुजिसकोउ
केदांतोंविच पकवडादंदमहोन अगलेपासे अधिक
लेमाद्देवीदाहै सोअधिदंनवाउमनासिरहड्डीनेउत्प
नकहेयाहै १० जिसकरकेवोगदीनलिसाहोजानाहै
अरुखाणापीणाथोडाग्रहणकरदाहै अरुखेगहेदी
हैलालावगदीयांहेन अरु बहुनचटदावटयांदाहै १८
पहेसबकेणारक अरुकफकरकेहोनेहैन इनाके
विषेसर्वहिनाल अरु शुद्धबुद्धीयोंकीयांनाडीयांविषेवेध

वलंवेनसवाहस्याविंयाउपदेशोबुपये
व ११ दंतस्वपिकःस्मृतोदंतस्याना
समाश्रितः शुष्कःयोदशपनेपिदंतःस
वालमनाश्रितःकथितः १० नेननवंरोग
दीनोभेदंवैप्यवनिमंदमादंनेकामो
लालाचभवेद्दीनापारिद्दीपनेसतने
११ पनेसलजारोगाःकफशोणितसं
भवासमादिष्टाः पषोनोथरेप्रवंना
लवेयशोलमेवेध्य १२ अयापिकेदकः
स्वपशुवोवनकेस्योसंम्पःकोप निरुतं
नेशाद्धेणास्तीलोनमवंमपकंपंपेशोमा
न १३ जिव्हानिकषायाणोकदकानिवदीप
पेशयांज्ञा निपानानिपश्याशास्नेप्रदापानिसहुदास
मवयोसनपमानिनस्यानिवकारपपघ्याकानि गोमूत्र
समाधुकेकटुचूर्णादापयेन्मतिमान् १४॥

कराबेबुधिमानवैद्य १२ जिसकेदांतकेमसूडेविचिपीड़होणेयांअथ
वासोजाअथवापीड़ाकरे तिसकोबुद्धिमानवैद्यनीताश्मकेसा
थकहकेवाहरनिकलाहेवे १३ अरुपाणिनकाथकरेहे न
योंरोगनमो दवे अरुमृगीरवे शुरुतुकेपानेकिधोपाशलेकर
देनमोधावे प्रयमानकराएवपसेशकदेन अवरुतेर
मानवैद्यगोमूत्रकेसाथकटुकचूर्णदेवे १४॥

© Dharmartha Trust J&K. Digitized by eGangotri

औरमरिचादिपिंडमाहै केसाथ देतकरके देणा है अरु
पानकेवास्ते द्वात्रिंशकापिंडगोत्रकेसाथ देवे ७५ एहसा
मान्यचाईकेमुखरोगकीचिकित्साप्रतिपादनकहेणा है
अबकैकरोगांकीविशेषउपायकहतेहै ७६ इतिसामा
न्यमुखरोगचिकित्सा॥ अबबालकोरोगकी चिकित्सा
कहते हैं पहलैबालकीरोगविषे नालकोयानाडी॰
योविषेवेधकाराखेफेरलूणकेलायमलैमलकरकैपि

अथमरीचाद्यैःपिंडैर्मुखपामहसंयुतैर्दे
यपानै द्वात्रिंशकैश्चापिंडैर्दद्यागोमूत्र
संयुक्तैः ७५ इतिसामान्यंकथितं मुख
रोगचिकित्सितंनृणां अथ एवपुना
केषांचित्प्रतिकर्मान्यद्विशेषेण ७६
इतिसामान्यमुखरोगचिकित्सा अ
थअबालकिचिकित्सा॥ सर्वमथ
वाबालकिनस्तालमूर्वेदपयोशिरेवा
स्य लवणेनतंविमर्द्यापथ्यप्रयेमाय
येत्प्रयत् ७७ कुस्ताम्बुपथ्यलिमूलेन सो
मनेगौरसर्षपावद्धः पश्चिमत्तेनोवरस्या
सरक्तुर्यान्मर्दनेच ७८ अभयावचापटो
लैनिंबलवणानि त्रिमकेस्ठीयलिपा
नेवाकल्पादयंतोहेणासंयुक्तैः ७९ सम
नाहृदानिवानोमरमानिर्गुडिनकमाला
ना

स्कोथमै निमलेउपरंत मथा पिप्पलामल रसोंन
सेतो सरेपा विग मालाकेगुणां इनासाधनकरे ७७
हरीडवचपटोलपमलनिवलूणपंच विशांगुड इनांकों
वारुणी मदिराविचमालीवपाध करके पीएं कोईके ७८
मालती बुमानिंवा इनोंका और तुलसी बणाकरने
मधुकेलेकेपत्र इनोंका क्वाथ पहेमुखधोणबालेविर
नकरकेदेणा है ८०॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
टी॰
१६१

181

मद्यांवाविडंगमरिच हरीतकीइनोंकापिसकेनायकरके शमभानामभद्रिगाभेहतिसकेसाथपानुनिषेदेवे २० गोमू त्रसाथपीनेकोदेवेतोवालसुखीहोताहै २१ इतिअवा लकौचि॰ अवअवानेकरोगकीचिकित्साकहतेहैं अ वानेकरोगविषेनालकीयानाडीपाहल्लीनशानाणकर केवेषेटके फेरतिसनालविषैदारकरके अथवा अग्नि करकेस्थिरकरैतिसकों २२ तिसकीपीछेविताहैहै॰

कोलाबिडंगामरिचंहरीतकीभ्रंगवेरम
युक्तं पलंकिंडंसपाटसुपानेवैअसंताव २१
गोमूत्रेणाचसिद्धंपावकमथाविस्मपि
पलीपके तेलघृतगोमूत्रपानेदया
सुखोभवति २२ इतिअवालकौचि॰
अथावामकोचिकित्सा आवर्तकेतना
लेछोशिरवेधेसलाहिने तेनोसपनाल
तोरणाग्निनावानुवासपेत २३ विड
कहिंगमहौषधकरंनणंसुमदापिप्प
लीलवणैः अभयावचाविडंगैःमाते
विषेवांकरगोपान २४ कापोमसमाग
पिकोननोवनोलाप्रोचनामक्ते मेमाही
हवानेपाकसामूलेववानेविषा २५ पमिं
श्रियंगुमहिनैःमलैनःलोहानिनेमलम
न शुष्कपावेनेचकृपांनरेनेवासमग्रोन २६

शुंदकारंभूनिंवमद्यांवरनमभहरीतकेरणां नालहिंग पनी कासिपसार मद्यो मालकेगुणी लोथरगोरोचनमासिव लामल बंसमलीगालिपेगरनोकोगहीलहल दाल हरदल पिप्प मालीर मिलाके मालके ऊपर मदैन करे पकरमाद प्रांकरके मलकोभमावे २५

अरुकौड़पखलहिंड़दालचीनी मचांमुड़इनोकाचूर्णवा
नायकरके सुरामदिराकेसाथपानकौदेवे स्वरभंगव्यो
नेह्लोपकें ९७ मरिचमुंडपवलुणाकेपुक्कमचांसरेया
माहो पहेसमपलासकेक्षारमिलाकेकाढेहोयणाको
मतेवारमिलायकरकेभोजनकरावे औरनसबार सैधा
लूणनेवेनेकोदेवे ९९ इतिस्वरभानकाचिकित्सा अवजिह्वा
स्तंभकीचिकित्सा अकहतेहां जीभास्तंभविषैयोफोडेपी

कटुकापटोलहिंगुवचकणपिप्पलीविषभे
षजचूर्णं स्वरपासहितेपानेदेयस्नाले
नेवटेन ९७ मरिचंशृंगवेरंचपंचभिलेव
णैर्युतं पिप्पलीसर्षपामाषान्मलाशला
रणाविनान् ९८ भोजयेन्मधुसंसृष्टान्स्व
रेहृतसैंधवं ९९ इतिस्वरभेदचि० अथ
जिह्वास्तंभचि० जिह्वास्तंभेपिहासको
जिह्वायाःपार्श्वयोरपस्नाव शस्त्रेणभे
दयेनासभेदयेद्धपारेजिह्वायाः ९० ओ
तिष्मनीहरिद्रेपाटाकटुरोहणीनया
निविषा कुष्ठमूर्वामूलंपिप्पल्यःशृंग
वेरंच ९१ तेषोवानिविड्गंसचूर्णगुडे
नसंयुतेमवं दोष्ठाविनेचनालनिजि
ह्वायांघर्षणंकुर्यान् ९२

तेगयेहैनतिनोंकोशस्त्रकेसाथकरदेवेपेडेवद्वीअरु
हैटकीनेनोकोटकेअरुपानीडाकेऊपरहै तिनोकोना
भेदकरावे ९० मालकंगुणीहरदल दालहरदल वट
लेवेलकोर अमीसकुटगलोटपिप्पलामूलमचांमु
ड ९१ मालकंगुणीवायवडिंगइनाकीमहिनपीसके
गुड़विषेमिलकेअभनाकोमिदवीरसायनालयकजी
भाकेविषेमलेहकीनरो ९२

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
टी॰
१६२

और नालकी यंत्रकोवेधकरावे अरुबलकोदेषकरके म
न्याकंटकी यांवो वेधनेयोग्य है लहूकोनिकलदेयिछो
बुद्धिमान वेधमात्र अस्मावे ९३ हरीदमतीसाने व विल
लाचीयो कुष्टचित्र पराण बटलेवलवच परवल मनका
रनाकोआसवकेसाथ्यानवासलदेवे ९४ औरदेहोकेमूल
विषै मोहामेखाखोनालरनाके ऊपर मछ्रामरिचपुड
सैंधालूणाकुटमरखीरकरके पुरुमर्दनकरे ९५ गंभ

वेध्येचनालंनिशिरेयथावलेमन्याशिरा
वेधबे मन्नरक्तस्रवनपश्चात्कुर्यान्मृदे
यावनमतिमान् ९३ अभयानिविषानि
वैविलेलाकुष्ठचित्रकैरेडेः पाठावचा
पटोलैः नेहासवंसंयुतंनेपाने ९४ हृत
मलानिनिद्राचरकेनालनंयोमरो श्रा
वैः सैंधकक्रोषणमधुश्रमैर्विमर्दयेत् ९५
स्वेदकेनपंचालमर्दयेत्मधुमसंप्रा
सैंधवमश्रनेनशीलागमाषाशुभानयेत् ५९
रपवेसमप्रकनेवानोनिद्रामभादिम
चयते ९७ इतिनिद्रालंभचि अथगलग
दचि मर्दनः काटिनोग्रंथिनिगलस्थानि
शकलाः हेमानिमर्दनः केटवद्धेतमलः
माश्रितः ९८

नलकेसाथपीवे अरुमरवीरकुनसाथ
मर्दनकरे अरुसैंधालूणाकूनकेसाथ
गोमिठमरुभाननकेसाथनमवारदेवे अरुहा
करकेचिकित्साकरेनवनिद्राकोसंभनेदेवे ९६ इसतरहभलीप्रकार
निनिद्रालंभचिकित्सा अवगलमभनेछूटजाताहै ९७ इ
हीयोगमपासनेकाठिनकररोगचिकित्साकहते
है सोवरीदारुणअबदायकहै निगालकंटकेपास
कोरोगकलेनीहै अरु गल सामभणोवासमैं गल
विषै स्थितहोरवपडीहै
निम ९८॥

© Dharmartha Trust J&K. Digitized by eGangotri

कर्णके पीछे और कर्णमूलों विषे और गलकी संधीवि
षे पीड़ा होवै और जो दाह कंठको नाड़ीविषे शोभा तिना
को होय कोलता है अरु अन्नपानीयं ग्रहणपान ग्रहे होवे अरु
दीननिर्बला होजाता है अरु प्राण पीनवी वद्धकमक
रसकदा है लालावगनीयां है नेगे नलनिकसदा है
और नाशांके रस्ते लहू निकलदा है १० एनेगलग्रह
वहन उपद्रवोंकरके युक्त होवै सो नवसिद्ध नहि हो
ना अरु इनाउपद्रवोंनेरहित गलग्रह होवे ना सिद्ध

विदूवकर्णमूलेचनिगालेवाथपीड
नेरसनोकटनाडीवषयपउनेरुण
द्धिवै ११ अभुसुनालोदोनम्नमदायव
निखोदान लालास्याववितलरकेना
साभ्यापवनेने १० वद्धलेष्मपवेन्ने
नसिद्ध्यतिगलग्रहः एतैर्विरहितश्चा
पमल्पदोषश्च सिद्ध्यति १ संधवांवित्रके
युटोमागधिकागोरसर्षपसैनैः वा
तोकुवचाहिंगुभिरिदूपवैदोयथेनसं २
एनेनेवहननेपक्कनस्वेनस्याननयोनयेत
खोदेनवयवाहेयामस्नानगोमूत्रसाधितां ३
पिध्यालिविस्वमसंयुक्तां भोजनयेमधुसर्पिषा
होनेनाभ्यस्यालितनस्यमस्यनेवपयोतसे ४

काहेनानाहै १ सैंधालूण चित्राकं द्रुमचांमेतीसरे
यां श्याम भटे वचहिंग इन्होंको दंनांकी मटीनपीस
करके नसबार देवे २ गुग्गुवाइनोंवस्तूके साथ वहन
सिद्धकरके नसवार देवा ले देवे अरु लोणवाले न
ड़ीओं वन्नेणीगोमूत्रके साथ सिद्धकारकरके देवै ३ अ
रुमवोगड मांतीर ओरेवड़ीके साथ भोजन करावणाके दे
वे और शहदके साथ मालस करे अरु सदद वृ घर तिस
के पीछे ने मस्याकेट की नीयांकी वेध करावे वेद ४

मा
नि
१६३

163

अरु जिस विषैं कटक अंतिपान विषैं देखोक ह्है पावै है अ
रु पोशोनेके इदगोणकायक है इन सो समभावि पीकरै
अरु मस्या विषैं वेपन करे ग्रोम वक है इन सोसमझिन
करक है इन ५ इनोकरके पवमरवोनाहोवैं नवश
निकसेदावदेव पदश्मकारके वीशमनाहिहोवेन
व उसकोपाइ करके रुधिरनिकाशके दारकमेबार
पाननकरावै ममस्थानकोनाडीकोछोडकरके बार
पावे ७ इतिगलगरहवि० इनश्रीकेमध्यस्थानविषैं शो

कटकेकंपितितपाणे स्पाससोथ ग्रंसवेमाव
रेत मन्त्रोपनाहयेवोकालेषोपनाह
नोइने ५ सवोंपदिमवे मेवमस्मिक
मेननःपरे पयवेनशमेपानिपाडये
मानतस्रवे ६ तारकमेगोग्रकृवीन
ममस्वापुविवधयेत ७ इतिगलगह
वि इन्ननरस्याः स्फोटाः सपीडके टवि
डालिका निर्भेदाद्याः पैत्य केकछाये
रोपयेत्ततः ८ इतिकेटविडाले अ
थश्रुपिदनवि० अथकास्मोपमकर्प
घर्देनापकर्षणं यरास्थिमूलेपकर
नेवदेवेमहारश्यगले ९ अतश्चोत्रयदा
कारकारयेस्ता कोविदाः नेनापिदंनमा
स्रापनाश्यदेशमनाभेषक १

विडालिकाकहिऐ जिसकोपकायकरके नदेहोवेसोके उ
जिसके उपरैनकाथयोकरनमिनोकरके भेदकरावै अरु
ग्रावे ८ इतिविडालिकाचि [illegible] करके रोपनप्रगरनु
कालतोदेककापशवालस्याके पोरनेके [illegible] चिकिकरनेहा
स्थिकामलहोवे अरुपकारहोवेगिदहोवे अरुश्र
ग्रलियोकाहोवे ८ ओग्रास्ववनायोवालेयोकिवैवनरश्यत्ते
अपपरविसंगगावनावे जिसकरकेग्रीरिइनवोरहदकोपक
इकरके श्रोडनाउपचारकेसाथ मेकेजिसपेशकों १०

© Dharmartha Trust J&K. Digitized by eGangotri

अरुमासकेस्पर्शगंधिविनाहै इसकोमंनेयेकरस्पर्शरू
पिकाहोनावेतोसनावीपकनाना हैमास तिसकारण
करके पहलेहीपंजलेवेवैद फेर सेपेलूणकेरकेउस
सपानविषेमर्दनकरावे ११ तिसकेउपरंतमस्वांसेपाल्
णकोनसवारदेणकाहैहै येकरकछशनववलगारहै
धारैषितिसकौ पोटवाणवालाशस्त्र हैतिसकेसाथ
ट्वाकेवारकरदेवे १२ अरुवरेउस्वदापक मवलकम
योनेदेनमलकामांसकौंखानेहारांको रसीनरांतिसकौ

भग्नेमांसेविनास्पर्शात्प्रपाकेप्रपाणिव
नमारोगोत्कृपेत्रोमांसेपचेनाविमर्दयेत् ११
ततोऽनसंप्रदानंपिष्पल्यासैंधवेनव
ललेनवपादैनतलंमर्दयेनापकारयेत् १२
भग्नेनेदेनमूलेवाप्रबलेःकृमिभिर्भृशो
नेत्वायेनेनकल्केनांतेप्रमेवापकर्षयेत् १३
उद्धृतैर्लिविशल्पेश्रमसलीनरोगोभवेत्
प्रपिदेनस्त्वर्बाणांनेमादोपंचवातिनो १४
कोषात्नीतुमनलोमान्यास्पावननःपरे १५
इतिश्रीपिदेनाच॰ इतिमूलरोगचिकित्सा
ध्यायः अथकामलाचि॰ वातानपित्तश्ले
ष्मकफावसन्निपातात्ससनानतथैव सप्त
कामलानिर्दिष्टामाकलमूलाद्भवेत्तथाः १६

तीसनाबीवाद्दरनिकसदेवे १३ उनांमालोकेपुट्टे हाथां
बोउसरवीहोमाहै पोथपिदेनचोरदेनहैसो घोडेकौंम
सनैलकेपेनवपेलगवहूनपीडाकरनाहै अरुतिसके
उपरंतसन्यकादेहकेस्वभावकेसाथमिलजाताहै उस
नहिदेनाहै १५ इतिमूलरोगचिकित्साध्यायः ॥ अब
कामलरोगकेचिकित्साविधानभेदकहतेहैं कामल
सातप्रकारकीहै वातपित्तकफ सन्निपात ललनवप्रमेहतेने
हैन अरुसमनौमेवातमलप्रधानहै १६

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
१६४
164

अवरोधके कोंमलवेनें श्लेष्मनिकसदादेतीहे अथवाके
नेनगानेकेसे सेवागुकारके सोकासकहि है १७ जिस
बोडेके श्लेष्मपीला थाडहृदबलीके रोगका होवे तो
पित्तकरकासनामसे कफकी कासरोग है जिसुविषे
श्लेष्मबहुता अरु सुनो बनाहोना है १८ जिसरोगविषे
सभदोषोंकेलक्षणहोनेसो विसोत्रिदोषयोनेत्रि
दोजकासकहिहै जिसविषेश्लेष्मकसेलक्षणहा

अथकासमनस्वमननेश्लेष्मणावाम्येनह
ष्यतेयस्य फेनः पक्वेनेवानस्पन्दवातो
द्भवः कासः १७ ननुह्रासोऽस्त्रवर्णः श्ले
ष्मानुगामस्यपित्तनेकासे श्लेष्मावङ्क
वामयंचनस्यकासेभवेत्कफने १८
कासस्तुसर्वरूपः त्रिदोषजनः कौ निनो
महामतिभिः सकफपापायसरक्तः
श्लेष्मकासेस्पन्दनः तनने १९ उरांपप्र
यतिभृश्लेष्माणावमानेपिच्छलेपायः
तामेमदाहारः तपोउवलस्यकास
स्तु २० सर्पिपयोविमिश्रपुक्तेस्नाथे
नेपवमलस्य शुष्कादिरामभिस्मपके
स्याहानकासरराम २१ ॥

शुष्कहोवे सोबातजनकासकहि है १९ थोचोडाश्ले
ष्मउगेथियबालापाकके समरूपवाला अरुत्तिपानी
वाला कफवमनकरे अरुलिसाहोवे अरुभुलेथो
लकहनके कायकों हनमोरनगपवोमिलाप
वालाकदेयाहै २१ ॥

मवांमेंउपायकेववरीदाजन्मकाडेमलटरवेंउपायक
रकेपीनाहोया सोबानकासस्त्रकोहूरमाहै कडेपारिक
देपारागलधूपगुगलवामवांमेंडेमलट रखोकेसा
घनेलकाभूमदेवेनोसनावीवायकोरवेगकोंदूरना
है २२ निंबादिपटोलादि अरुमेंद्यागेंलेरहबटणोदे
वे इसचिकित्साकरकेबानकासस्त्रहोतिहै २३ इति
बानचिकित्सा अथपित्तरवेगकाउपायकहतेहै नव

आनेतोरेंकाथयेनेमागधिकामेंगवीरस
पके पोनेमधुकशर्करपाविमिश्रितेवा
नकासस्त्रं हरतोहृपानियोंसेमागधि
कातिस्वमधुकसेपकें तेलपभ्रपिने
बानमापकामेतेवारयति २२ पित्त
मेंदपटोलामेंमुस्तोपवामदोपपेलेहे
अनपाकियपानरमस्वानकासस
मेपाति २३ इतिबानकासचिकित्सा
अथपित्तकासवि० लद्राटिमद्राक्ष
लेपाकोदयाकामेनयेतिके चूर्णमाम
लेकानोनपिप्पलीचूर्णमेवच २४ हि
गणवनमोवीरंमोिवासस्त्रसाचपेत
नमस्मिदापयेलेहे शर्करामधुमिश्रिते २५
बानकामेनपन्चवेनदानेपायेसपः २६

पित्तकीकासहोवेनव द्राक्षादि पोसहमेंगीकरपाम्मा
नविधैकरिहै सोपित्तकासविधंहोवे अरुआमलेका
चूर्णओर मसांकाचूर्ण २४ तिनोनेइणीमेंशलोवन है
नकरके रलावैफेरतिसविधिंमरवीरंलइरलापकेपित्त
कासकासेचोडेतार्ह इमावे बटणी २५ औरपोककेरी
काइणपमवे बानकासमेकहेपाहै सोवीपितकास
विधैरेवीपीणकें २६

भा
टी
१६५
165

इतिपित्तचि॰ श्लेष्मकासचिकित्सा स्वरीहैदलदाणे
कोजडहूरदलदालहूरदलसाठीकदेश्रारीकेफल इनोंको
देउकाचामेंडुपरकाफुलनिमकेसाथभूमपिलावेक
फकीकासविषे २७ मुलठलावचा साहूरीडमनुकासवा
गेउ आंवले लोथर लोहचूर्ण इनोंकोसमहोनयोसकर
के २८ मखीर इनरस्लाके पहेचटणी बौडेचांतोरेद
आवे और मखीरकेसाथकटु चूर्ण श्लेष्मकासहर

इतिपित्तचि॰ अथश्लेष्मकासचि॰ सैन्धवंवी
ह्रीवेहूहेरगदोहहनोफल ह्मनमडेन
मधुनक्षमकासेकफोद्भवे २७ मधुर
केलाबावासाहरीतकोमधुरसाक
णांस्तुटो आमलकाविलोयलोहर
जसैवसंचूर्णं २८ मधुमाध्विभ्यां गुंक
लोहंभिमंदापयेन्नरोभ्यः हौडूत्रतं
कटुचूर्णंप्रदापयेत्श्लेष्मकासहरं २९
त्रिफलात्रिकटुचित्रकमस्तै: दौ:हण
मधुनलेह्यः कटुभाननंचदंषकल्या
केश्लेष्मकासहरं ३॰ यद्वैपनिकं
कासहिमकासपित्तहिंत यथाकेःवी
रपानेश्वपवचूर्णंप्रदापयेत् ३१

करणोबालादेवे २९ हरीतकहेडमामलेमधोमरचकं
इनिवासमुथर मखीर साथ लेहदेवे अरुकटु भोजन यो
कुलस्थानविषेकरणादे सोकफकासकेदरणेवाला
सादेवे ३॰ यद्वैवपित्तकासविषेकहिदेसोसमभोषध
सनमकासविषेद्यातिनकरकहियाहेन औरपेडूगयपान
कहेसोपिलावेअरुनवीके चूर्णसाथपिलावे ३१ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

अरु जो गलग्रह वाली यों के मांस रस साथ भोजन खु
लावै पहिले विधि करि योग्य स्नेहन हो पेछ कफ वेगा विषै
वो देयो ग्या ॥१२॥ अरु स्नेहनिपान की कास विषै साधारण
क्रिया चिकित्सा करावे धूमपान शिरोविरेचन नस वा
रो लेह पान यो कहे है ते सो सब करावे ॥१३॥ और स्निग्ध भक्त
भोजन इस कास विषै वहन्न हितकारक कहे है ॥१४॥ इति
कासाध्यायः अथ स्नेहव्यापत् कास्नेहपान विषै यो वि

गेगलानां च मांसेन भोजयेद्रस भोजनं
पनस्नेहेन कर्तव्येच्छेहपकासे पिवानिना ॥१२
स्नेहपानसमस्येन कुर्यात्साधारणीं क्रि
या धूमशीर्षविरेकौ च मलेहः पानमेव
च ॥१३॥ स्निग्धभक्तानि चैतेषां कासे शुप
रिमौषधं ॥१४॥ इति कासाध्यायः ॥ अथ
स्नेहव्यापत् लवणाधान्यस्नेहात्तीवोदः
कनादिभिश्चयाः समः स्नुः व्यापदः प्र
वक्ष्यामा सांत्र्य चिकित्सां च ॥१५॥ अतिमा
त्रमयोगात्सायभ्यः स्नेहप्रयुक्तानि हृदयभ्यः
तेषां स्नेहव्यापत् वेत्समः स्नेहवतेसम ॥१६॥
दिङ्गुवचालवणोनि वपंचानिविपाकण
वमेषूणां पानाय स्नातासाहिते स्नेहव्यापत्
नाशाके ॥१७॥

हलिहोनालि ये व्यापन स्नेह लव
ण पान्यसहाहीर उदकनादि ये स्नेहव्यापन कारने
विषै यो उलटा विकार है जाण इनां के सम रूपमसण
महाउपाय करना है ॥१५॥ स्नेह रूप तेलादिक रहि
नाग पावा मर्यादके नहि जानने वाले ने वो इकोस्नेह
दीयाहै तिनांको स्नेहव्यापन होताहै सो स्नेहरूप वनेग
गकेसमहोताहै ॥१६॥ हिंगु वचू पंचलवण पनीसमवा
इनांकोपीस केन्नगाम रमा वास्नेहव्यापमनोहरमाहै ॥१७॥

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा
हे
१६८

168

इसकरके उदावर्तरोग शूल टेमा गोमलादिनि कलें औरव
नेवट अनाह वेदहीगसवहार इनांकोसमकरहै अरु ८
काष्ठअग्निगनस्वेदकोलिटसाथवाइयनिवासदेताहै
वोइका १८ पंचलवणकोउदीपकरदलोहिउस्तहांजण
वटलवल पंचर प्रतीस नजोहार इनांको मदिराकेसाथ
पानकोदेवे १९ औरयावेदावर्तविषेया ऊषधकोहै
है सोसभ इसमें याउ ५० इति स्वेदस्थापन अवलाणा

पटेनोदावर्तावर्तीवानाहपववसमे
नकाष्ठाग्निमोनिरस्यानिसवाणेघावा
मिनो स्वेदः १८ लवणानिपंचकट
काहेचनिशोहिंगुशीरकेपाठा विष्णा
त्रिवत्तिविषाहारेवस्याष्ठनेपाने १९
स्वेदावर्तनयायोकाक्रियानां संप्रयोजये
त ५० इति स्वेदस्थापन अथ लवणस्था
पन लवणपदानिमात्रं प्रदीपनेयानि
नामकालेवा अन्नस्थवामप्रकेविदह
नधकाश्व ५१ पंचलवणकोप्राप
मेशाणिनाचपिबेच रूपणनिनोवलवा
नदीनाथनेप्स ५२ भवनिमलिला
भिहीनेदीगधक्षमपुरवः स्रोमेनिपिनताया
नेः इच्छानिसननेपानेकापेसटसमानेव ५२

सकहनेहां लागवृहनअथवाअकालविषेदेइपअथ
वाघकेसपकोदेवे सोलवणअगपचयाकोहस्थान
विषेस्थितहोताहै ५१ समनंरलवणकोहविषेविरूत
होके कोपर अरुपिसकों अरुवातरनाकोटि
पिसकरताहै ५२ जिसनेसोरनलनकेसहभाहोताता
है हीनमंदाहोजानाहै अरुगुल्मकजानाहै अरुरमक
रताहै अरुपिलकेलापकरकेपीरनहोताहै अरुगीर
केहष्यहोनेयानिरनरनलपीसकोइस्थाकरताहै ५ १

जिसको हैडे जल करके सेवन करे नुहाले वारंवार अ
र्गविकडूके साथ लेप करावे अरु पीलोंको हैडुखेड़का
सेवन देवे ४४ अरु ठंडपाणीविषें नाहिडावे अरु पा
न करावके नाउहाले छोडेको और शीतल इमध हुत म
खीर साथ देवे ४५ मनका फालसे पीलू के फल खांड इना
का महीन चूर्ण करके मखीर विषें मल के पीने को वना
यके तुरिन रखावि - ४६ इसका मूल यो मूवें केकणा ड़ेनि

तैः शीतलतोयमिश्रैः सद्भुरर्धेःकदंबैर्नवै
र्लिंपेत् दंपपानापनं सशोणितशर्क
रा तेषां ४४ शीतसलिलावगाहः प्रश
स्यते पानं वर्तिं तथा स्तु शीतं भक्षं पय
सा माषिमधु सेव्यं देयं ४५ द्राक्षापर्व
षकाणि च पीलुफलं शर्करां च मधूकं
तोहेणलोम्सनन मूषिकाद्यापथेन स
सिमान् ४६ द्रावितमस्यकाथं मनेशी
तो कृतं पयोभिश्च मधुमधुकसमायुक्ते
कुर्याद्वास्थापनं तस्य ४७ वमनं मुद्गपरो
लाभ्यां च वयोहिमकुकुरदाः प्रलेपचन
लेपाः स्युः स्वर्णवपवमहिमा ४८ नीरागा
के वपा ये क्रमा तो कि याः सप्रयोजयेत् ४९

सका काथ वणा के फल के हेडा करके उसमें मीठा र
मलट रस के साथ आस्थापन वस्ति करे जिसको ४७
तिसको वमन और सक्षौद्र चूर्णादि मोरु कुकड़ले
वे अरु वामवाला सवस्थान विषें स्थित करावे अ
रु खाण को रवो देवे हिम करे ४८ और नीरोगण
कौराग विषें पो क्रिया चिकित्सा कहि है सो सब भाम
विषें करावे ४९॥

© Dharmartha Trust J&K. Digitized by eGangotri

धा०
ह्रो०
१८७

इति लवणपानम् अथ यवक्षारपानम् विकृते देहे सो कह
ते है पक्कादोषापानग्रथवाकफवायोवृद्धत खायेपावडे
वीर्यकरक्षाराशोरकरपचनेबालग्रथवाविषियैवि
नाशकादाहोप अथवासमकाबालवानीवैकाखादा
दाहोवै ५० इत्यादिकदोषोंकेसंयोगनैचोड़ेकोदुर
याग्निसमको नहिंयदपचावे नवसोभोजनचोड़के
भाकरऔर विदाहसकरदेना ५१ अरुइसनेचोड़ोबल

इतिलवणपानम् अथधान्याम्लपानम्
अविपक्वे पक्वे वा वादम्यतिमात्रपाय
दायाम्ले कृतवीर्यमयुक्ता वा मतेस्म अ
वायकमिलवा ५० पतेदोषान्ययथा
गाङ्कायाग्निसाम्येनेनरोगम्य नृपेचय
दिन्नुकेननोहृयोघ्याविगानेस्मतः ५१
पोरवर्नैनप्रहिनोधान्याम्लपानिनप्रक्क
कृतन जीवनिकदाचिद्धानेवहि
मूलाभिन्नाघ्यानेः ५२ और स्पेनस्प
शिरेवपकेकोहाशिनेववाहस्य विशा
विभ्यस्यकार्याङ्कियानसोभिहकोक
न्या ५३ इतिधान्याम्लपानम् अथम
राण्यापानम् ॥ ॥

मदाहै और परसा होनाहै सोधान्याम्लपानतनै चो
ड़ा बड़े कृपाकरकेद्विजीवनाहै अरुकोइसमूल
नै करैकोइ जीवनाहै अरुमरजानहिं मूलकरड़े
लिनदोपाद्दा ५२ इसरोगमैंजानीकीपानाड़ीयोंके
भेदकरावे पचकोइस्थानविषैस्थितहै चोड़के अरु
लघिकरैमेंपर सोभिदकीरागविषै योगिकिमाक
हिहैसोसमरसमेंकरावे ५३ इतिधान्याम्लपानम् ॥

© Dharmartha Trust J&K. Digitized by eGangotri

अवसरव्यापनकरनेहारा मदेराजिसकोंवर्तनवर
मानदियाहै अथवाश्माउंगंहोवालाचिपानीवाला
अथवाविदग्धकचापकाअथवापिनरोगविषैरिज्ञा
गयाहै वातसेविषेचलदेकोंदीपाहोवेयकेनाप
कोंदियादा सोकोहस्थानमेपिल्लकोस्पर्शनकरके
फेरसोपिल्लकपिनहोकेसभपानेकोविगडदेताहै
जिसउपनापनेवाडेकीस्तरनसभदरहोजातिहै अ

अतिमात्रेयस्यमसाडगेणायपिल्ला
विदग्धया वा श्लेष्मविकारैरथवाप्रदी
पनेधागनेऽधीने ५४ साकोहस्याणि
नेभकोपयेरहथेचधानगणा उपनारे
नैगसंनेनसंज्ञाञ्जयाम्येन ५५ पार
दलमानपवंमूर्छान: स्वसिनिवपने
श्लिष्म: रक्तेमत्रेक्रुकनेरस्पेनचलीस्नि
वास्य ५६ नस्पस्तशोनेस्यानेशोनेलै
नेभेदहनेवेव अनेनेश्रवोजनेस्यारेवृ
संज्ञाभवेनस्य ५७ इलक्ष्मलप्रतीष
नेलमूलामूस्लानि मेनिष्टातोरी
लमपोंस्तरोकेवमधकेव ५८ पञ्चक
वेरनतिलमकस्पनेवेवशारिवाद्याः

रूपसंदरपहोवेजिसकीन्याईमूर्छोदमकंच परसोरना
करकेप्रकरहोताहै अरूपक्षावलहकाकरताहै अरू
शोतिजिसकोघालालहोताजानीयाहैन ५६ जिसकोइको
वेस्थान अरूपोनलेलेपमालसोअरूपतेयोमायरो
लगता हनो उपायोंकरकेसपमावतीहैजिसकों ५७
स्यालिकेमूलका मुगदा नइकीजड कमलपत्र मजी
ट अरूहीरहलवदीकेबल पलासवडवेनस्थलकमलका
ममीरामूलर ५८

© Dharmartha Trust J&K. Digitized by eGangotri

मा. को. १६६ पद्मकाष्ठ चंदन निलसिकी कालीबेल इनोंको हंडे जल
168 लसाथ बारंबार लेपकरावे चोडेको ५९ पानमखीर खं
डके साथ देवे अरु नपंण देवे सो हितकर है लूणसमजी
रानारदाणमचोमरिवधंड इनो साम्यसराम दिरापान
विषैहितहै ६० अरु भोजन वास्ते सटीधेनदेवे अरु ले
डानि नरकुकड इनोका मांसरस लूणपायके मिठकर
केदेवे ६१ इति मदात्यान् उपयको आपन यो वो ३३८

पैनैष्टिकेदशेमद्यमेहः पौनवामेघु
नैः ५९ पानेमधुशर्करायामेअभ्युक्तंतर्प
णंहितेवास्य लवणानमजानिदाडिमि
चिकटुकसहितासुरापाने ६० भोजने
चाष्टिकामेचुलावानिनरविष्किरैः मद्मा
मलवणोदेयरसैष्मधुपरिप्लुतैः ६१
इतिमदात्यापन् अथलीरअापन् १
लीरंयदातिमात्रेपीनावाजीननःस्वरो
पिबति लीरंपीनापरामात्यायामेचाक
रोत्यथः ६२ नस्यलीरअापदवेन गु
रोष्ठनपामभिघात् कुलीवेवाधाने
शिरोगुरुकंवेवरोमेनस्यैव ६३ मेनाव
लोपनकणाकृमानिविद्योत्यपिर्देकोत
स्य पर्वंमलेनरूनापस्मात्मानेसरादयान् १४

बहुतपीकरकेफेरसरामदिरा न पीवे अथवाउदरको के
आयास आयामसे वलकरे ६२ जिसकै लीरआपन
विकारहोते है जिसकरकेलिए भेदका आपनलो होजा
तिहै अरुकुतिलिसे आपन रोगसिरभारी मलिनोविमन
होजाना है ६३ मालकंगुणीगजापप्पल मवो योत
पारसकी पिनीपरलेंमर वांधेरके पीछे नेमदि
रापीनेकोदेवे ६४

© Dharmartha Trust J&K. Digitized by eGangotri

कांजनेकेपत्रविज्ञा गजपिपलमवोइनोंकों पीसकरमः
खीरकरकेदेके फेरपानदेवेनिसनारि १५ यदपोडाह
ठनावेतववासमनीकेचावलनिलोकरकसाथसिद्ध
करघीरखंडमचामरवीरकरके साथ भोजनरवाणेकों
देवे १६ त्रिफलाकेकाथविषे सिद्धकरके मुंगो मसीर
खलायकरके भोजनखुलावे अरु मनस्यमेंमेलठपाय
करकेखाणकासनेदेवे फेरनिसकोंचापदेवेखाणकों १७

पञ्चाणिकरंजानांवाहिगजपिप्पलीक
णांचैव पिष्ट्वातोद्धेणाउनेपानेदयंनन
नस्यै १५ मकस्पनवेदनयाश्वोहिताणी
मादलानिलेःसिद्धं विघ्नकर्णीतोद्वेण
वमेस्पइमोजनेदये १६ मद्वाम्नात्रिफ
लासिद्धंभोजयेत्ताइसंयुतान् मनस्या
स्यकेलीनकेचयवसंवास्यदापयेत् १७
इतिलीरव्यापत् अथोदकव्यापत् दी
वोधनेसगुकंवमेमाराभियोजनाद्या
ने स्नानेविमशरीरेपिपासितेनवलेको
छेच १८ नेपाययेनिमूढायेतत्त्वनस्तत
निरूह्णामे सलिलेपिवतः सृणांतको
छादयितैभवेत्तस्य १९ ॥

इतिदीरव्यापत् अथजलकरव्यापत् योवोउवहुते
मार्गकरेआवे औरभूमकेविषेवहुतभारउठकेआवाते
थकेहोयके अरुपसीने युक्त शरीरहोवे अरुवहुतलगीहोवे
कोष्टजिसका खलहोवे १८ निसकोंयोमूर्खनिलम्-
ताकोपिलावे निसकोंउवेष्टासनेमानलपीनेहोयेकों
कोष्ठमगानवहुतभरजाणेहै १९ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ ह॰
१६९
169

नवउष्णे ष्वासवदेपाहोपानिसनेवागुकरकेप्रेतिनकोप
दोयानसना डीहाराधोनलवाहानाही हैन ज्निसहोनेसा
गवोडेकाकोहाभरेपापानाहै १० शरीरवदननाहै अरु
उदरनलकरकेक्रमने मागजानाहै नवहोइगनिवल
होजानाहै देहभागमरुवउखदकरअटदाहै अरुलिसा
होताहै ११ नखलगमीहैगमखेउहोनेहै अरुलिदपक्ष
ववडेलैपाकरकेहोनाहै टीउशवदकरनाहै अरुचासदा

नखोष्णमोऽप्तेनवाग्नेनोदीर्घेनेसिताभि
प्र कोष्ठवासिवदाभिःकनस्त्रमविमूर्पने
ष्पप्प ११ गात्राण्यथमूर्धनेविवर्णेनेवार
रेजलेक्रमशः हीनवलोगुरुगात्रः
कुक्षौप्याप्नोकृपेणभवति ११ स्वमोरो
मवदर्षः कुक्षौमूत्रेभवेन्मुरोषेव को
ष्ठवपनिक्रमनोतिनादमेग्रामसमर्थं १२
ष्वासोम्तृक्षौभवेद्धाप्यानोटशपनेहये
टनिवन १३ पक्षामलिलमापन्ना
नाकुर्यान्नकिंपावेना नेकुष्ठापेसनेलर
ध्यकेस्वेदपतनःपश्चात् प्रवोहपानमि
देनक्रोणमममागुनेदेये १४ लवणानि
पवमममनाकरवीरनटाद्रुमकेनिवे
पिष्टाचमीमवलोमपादलावाजिनोदपा ११

एणनहिगुहणकरदा १२ ष्वासमलछीग्रामूराद्मवलोपी
देकीमरोकेनाहै १३ इतिविमलिलहोपन कनि ---- नाकी
हाडमगजानेकपहलेविकिन्साकरावे चाइकोकुषटिनल
इष्यादिकनेलमाप्यमालमकरकेसदकरावे पिछेफेराप
हपानकुकरकेसाष्पञानकानाविधुदेवे १४ पंचलवणमा
लनी करीरकीजरवासानिवरनाकोपीसके लवलेकी
दुधीपाटलाकेसाथ बोरकी इलोपायपहै ११

© Dharmartha Trust J&K. Digitized by eGangotri

सोसोहंडलमें होताणसोजानाप्रकरवतीयोविषे औरउदरवि
षैंजहांजलहोवेसोसमस्त जुजानतेहैंन और बल रंगने
जकेसप्रभवपतेहैंन ७६ केगुणी नख वेन वेन नाण
वचेवा खस्स नाति जलवडी इनोकेमूलोंकाकाथल्हण
केसाथ थोडेकोंपिलावे ७७ पहेवारेवारएकदिनवि
श्राटेकरकेनोसरेदिनपिलावे यरेदरनाकरकेगानी
नाहोवेदन तिसका जलबाहरनिकाले ७८ तिसको
हधिनरोवमके नमीकेअगेचारअंगुलीप्रकरोमरागी

लोहकंसेभकंशेफेकुलेपग्रेदंसजले
ग्राम्येनवलवणेनवर्द्धनेनमासह ७७
फलिनिकरवेणकवद्धोलाग्रानलहना
निम्नलेम्न पुनःपुनःसमालस्थ्येद्यमेन
प्रहातरं यघवेनमुखोमस्यानतोनिवा
हयेज्जलं ७८ सप्रोत्रिनमनाभेनवरतस
मंगुले अर्द्धांगुलेरोमराज्यावामप
क्षेनवेधयेत् ७९ अर्द्धांगुलप्रोहिमवे
मुपनीयाथ्यप्रशस्तके ततःशस्त्रेपदेन
स्मिनग्रमनाडींसवेधयेत् ८० स्नुह्या
श्रवित्रफलामिर्जाभानयेत्तोदरसंपु
नान् मत्स्यास्थ्यकेलीनकेवयवस
वाम्यटापयेत् ८३ वर्द्धांगुलमाने
नतयानिर्वाहयेज्जलं म्लाने थोदरे
दक्षावर्द्धनमानिबंधयेत् ८१॥

केअपिअंगुलजलवेणासेवेधकरावे ७९ अधिअंगुलप्रमाण
जडोकेबराबरघायकरावे फेरमासकोंकाडकेउसस्थान
विषेरलकेपरकीनाडीलापदेवे ८० सेनाडेचारअंगुर
लीप्रमाणतिसद्वारमेंजलबाहरनिकासे जबनाडीका
मुखमलिनहोजावे तबजलकोंबंदकरादेवे ८१

© Dharmartha Trust J&K. Digitized by eGangotri

श्रा॰
क्रि॰
१८०

180

फेर नाडी उसने कहे कें तिस गाय कों मखीर वोडी के सा
थ भर देवे फेर तिस कों हस्तिन रांघी इ करके फेर मखी
र साथ असव पिलावे १२ अथ रस वा स्तिक कूट ह व कर
मूत्र रना कामा सयो इ १३ इति उदकव्यापत् अथ ना
डी व्यापन कहते हैं उग्र वा मंदिरा हून मैल दियो ड्रा
न हि नान ए वा ला नाली माथ पिलावे नालो वहन
भरी होई अथवा बडे वेग करके सनाकी उपर उपर दे

अपानस्थ नाडी व्रणेन स्रवयेन्मधु सर्पिषा
पाययेद्वा हस्तिमूत्रो ऽथवा मधुसंयुतं
१२ कुष्ठ कुटज नव राहोश्च रसार्थे स्तु पयेया
नेपेन १३ इति उदकव्यापत् अथ ना
डी व्यापत् नीर यदा स्त्रावास्ते हं वा
पाययेत्सम्यक् सिक्ता: नाड्या प्रस्तूत पा
वैपायेत्स्यथ वेगत: सहसा १४ रसनां
वके ढनाडी समनि मात्र प्रस्यन्स्य योगेन
कासेन नोस्यान नेपन् स्वामानि रुजो यु
दानम्ब १५ नस्यन न्कार समानस्य कंठ
स्थोपयम् रंगे उदान वेगा उत्तुं ने शिर:
सम्यपयने १६ मेनास्याश्च गात्र वनं
नेत्रकस्यारयने शिर: अपानस्य जि
ह्वा भवति भूमौ पन निवेपने १७

नाना वेग उक्ति विना दोषा होय जी भयरु कंठ की नाडि वहु
न भरी जानिये सो कास पदे कस नी रे अरु दान वायु स्वास कों
रोक लेना रे तिस के लगे टया कंट हिये स्थिन पाप पर व्या
नेहे सो ऊपर उदान वायु केवल सो शिर: विशेष प्रम होना है १६
तिस कारण करके अरु पान चलने हे शिर वडे आसा अरु
काले परे मुख जीभ हो जानिये सि ... हू ... नो ... ना
है कें वहा है १७

© Dharmartha Trust J&K. Digitized by eGangotri

नाडीव्यापनतें जीवनाव उपस्पर्श है इसकारणतें थोडे
कौं दूरयादि नाडीव हुत भरी होर कर केना देवै ८८ जिस
कौं पीनलपारे है कस्नान और वेजे के साथ मालस क
मैं व और योकल्प स्थानविषे धूमपानक देनसो करावे ८९
इतिनाड्याव्यापदः समाप्तः जिसबोडेके कोष्ठविषे ला
म है न ऐसो कोड़का मासनें वीरहिन है तिसकोलिदपन
लीक्रमोके ग्रस होती है तिसकारणतें सोवहन मलपी

नाडीव्यापन्निनो लेवमाश्चर्येपादिनीवनि ८८
नाख्यानेद्यमस्य स्नेहोराघेनन प्रलेपया
नस्यशोतानपानेले कान्हृनाभ्यकस
कारयेत् धूमपानविधानेच कल्पस्थे
प्रकीर्तितं ८९ इतिनाडीव्यापत् पवं
नाड्याव्यापदः समाप्ताः क्रमिकोष्ठिन
स्तंगस्यमांसहीनस्यनेत्रभिः सर्दितं
भिनेभवनिपुरीषंननस्वबहूपिवनिभृके
च ९० हीनवलाय्याल्पाल्पं पुरीषमाति
मार्थनेमहद्वंगुरुशः घषभवेनक्रमि
कोष्ठिकफकोष्ठीवनिनेवपुना ९१ मे
दोभ्रिनाहीनयातेदोषेवापजायतेयस्य
गात्राणांवगुरुतेदोषेल्पेरामसभेदश ९२
कफसंहतंपुरीषंस्थिरंवमूत्रेभवेनथा
स्वल्पं

नाहै मूरुवहूभोगनवीकरतनाहै ९० वलुव
टमानाहै मस्रूपुरीषलिर वहूनगारपोडीकरदाहै व
हूम पदेलनहलणक्रामकोष्ठवालेकेयकहै न ग्रवकफको
ष्ठीकेलवकहलेहो ९१ मेदाग्रिनिद्रावहून ग्रकदेहभाग
रेण हेष्पेवलतामसभरेरोमसखेहोनेहै ९२ मललिरकफ

© Dharmartha Trust J&K. Digitized by eGangotri

भा०
टी०
१२१
181

मललित्कफकर केलपटी टोकरे अरु मूत्रस्थिर होके
थोड़ा होता है सो श्लेष्म को छीका लक्षण है पहलेके श्लेष्मि
को छीका मलजनक होता है २१ जिसको बकरेकामास
रुदके साथ तिनके देवे बुद्धिवाला अरु शाली का भत
मटे विषेलणपाचके भोजनको देवे २४ अथवा गुड़द
धिविषेरलाके तिसके साथ खाणाकोदेवे यहश्लेष्मियो
कोकिठेकरनेहै अबवह्निनाशक उपाय सुण २६

मश्लेष्मकोष्ठकीनादीकामिकोष्ठिकेयं
प्रवक्ष्यामि २२ आनन्नस्नेममांसस्तोरविनेम
दाणपेन्मानिमान् दध्यालवणामिश्रभो
जनेनमथपष्ठिकामेव २४ गुडमेगुणेन
दधामिश्रंवादाणपेन्मानिमान् संकोच
नेकमीणामेतन्मध्यनाशानेभेषा २६
केपिलकामिटमोवेनमकमिघातुनी
लिकानहूमापवानिमेकगवातिकु
सुमभथनिनिद्रीकेब २७ मूषकपर्णि
वैमानिमाथपेन्ती सेकोपवपानीपा
क्राथमिमेस्वपारमन्नमपि अपेवापिघनर
यो २८ सोमिश्रमाथपेनन्मार्षीभेकेपिल
केभवेन् मिश्रोवि डंगचूर्णोनन्नदेयमानिप
रोपन् २९
कमीलाविडगनुमालगोटेकीनर वैतबोल
डंगबसमानलेनेवालिकानमाकृष्णवाणिनशी २७ इटन
दाणकोनर डंगोकेसाथ इसकाहे वापानोमिडकेर प
रेकापपुणाके केरवाबुऊपर वाइटबे २८ तिसकोबकमी
लाडेरोमिनाके[illegible]मापविडंगकाबीणपाकपा
नवालमिलावे तिसकरके कमिसमहोजानेहैन आर
श्लेष्मकोष्ठकी शुद्धहोजानाहै चोरयोका २९

© Dharmartha Trust J&K. Digitized by eGangotri

निंबपत्रपटोलपत्रशुंठ हरडदल दालहरडदल विडलूण
वटलवेल सैंधवलूणमरिचविस्मा वायविडंग १० इनोंको
महीन पीसके और हमद भेद तिसके साथ चोडेकोदेवे
कोष्ठविषें स्थितयाक्रमिरूंन कफमंदाग्नि और रुदेकू
रोग इनोंकोनाश करता है २ वटवेल वेलगिरा सुंठ
वचमहातृणहरडदल दालहरडदल कमीलाकूट मरि
चमचांदनिसवाड कौड पनिसवावडिंग सेरयो महीन

कृमयस्तेन मासंति श्लेष्मकोष्ठेचवासि
नो निंबस्यपटोलस्यचपत्राणि महौषधं
हरीतकी ९ विडपाढासैंधवकल्माहूनम
कविडंगानि १ पलानिसर्वाणिसचूर्णा
नानिदद्याद्धरीतकीन् नरोगमसा हमान्क
मोकोष्ठगनाकफंचमंदाग्नितासद्भत
मामयेत २ पाठाविश्वकृविषमेषनव
वासौभंजनं देनिशाकंपिले चकुष्ठम
चमोरचकल्माखुपर्णीनव निकावानि
विषाविडंगमहीनाम्निजार्थकैसपुना
सतेमचूर्णामिदं हनेन मधुनालीरेणपि
बेत्केने ३ बिलासाद्गेसिदंपिरेगदाम्बे
णदापयेत् पतेनाशुपशाम्यंतेक्रिमयः
कोष्ठसंस्थिताः ४ मंदाग्निजाश्चये रोगाः
श्लेष्मकोष्ठश्चवासिनो ॥ चूर्णकरके महीर और

रसके साथ पिडीबनाकर के वेध ३ साबुनानके पहे
पिंडुगोमूत्रसाथदेवे इसकरके कोष्ठविषें स्थितया क्र
मिरूंनसो नसहोजाते हैं ४ और मंदाग्निसेरोगश्ले
ष्मकोष्ठ कोडेका रसहोजाते हैं ग्रह इसलिए चूर्णकर
के मिलायके रसभोजन नानिस्वाडोकोदेवे ५ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

भा
टी
१८२

182

और कटुपिंडी बनेलवण और कटुचूर्ण और कटुकयोगअ
न कटुकभोजन और हृदयको भेद अग्निको प्रकाश करणे
वाले यवनिपान ७ पाचनाग्निके प्रकरणेवाले इन्द्र अल्हो
लेमन्ल और तोणकोयघे देवे और शमके वालेस्व
वलकीयो हर्वाहिनकाहियाहैन ८ इनिक्रमिकोष्ठ
श्लेष्मकोपचिकित्सा सब त्रयदोष रक्तके सहित कुपि
तहोके विरुद्धरुग्रहरोग करते हैं निसविधि कफने अग

यनेषामेव चूर्णानि संस्कृते रसभोजने ५
भोजने पेन रोगानिद्रं यथ्याकटुकपिंडिका
नद्येवव नेलवणा चूर्णानि कटुकानि च ६
विविधाः कटुकायोगाः कटुभोजनमेव
च अग्निदीपनीयं च यवनिपानानि पाने
च ७ मेदाग्निभ्यः प्रशाम्यते लघुनो यं न
शैवच खारने च पवादेग्या हवीचयवसे
हिना ८ इति क्रमिकोष्ठश्लेष्मकोपचि -
दोषाः स्वपः सरक्ताः कुपिता विग्रहस्त्रकु
वैति नवकफालनागामरहने रक्तापि
तेन ९ मारुतकोपाद्गानिभ्रमसल्लगि
तेमऽगादीनः गात्रशुग्रहोनेषिवकर्षानि
रुक्ता रूपाणि ९ मेरुवापिवनिसारेत
रक्तं मूत्रेमसंद्भूतिगतो मांसः दोषाभिताविता
वेलीयं पावकस्यासः ८

वलन और नलते है न रक्त
विसकरके ९ और वायुके कोपनेसे डालने गाहोता है और गन
गरेकाम्रैरे निसैन वहमलिसानि बलहोता है और शरीरके
गोके होयाकोडासरे हैगाने अंगासुवलाना है १० खारणा
दीणक्षयाप्रकारदा और खलाहुके समकरता है शुकडो
नपगाकसकरहोमाना है और दोषोकरके नया रंयाहोता

© Dharmartha Trust J&K. Digitized by eGangotri

पाने हीण होजाति यांहैन चोडे कीयां ११ अरु ......
डपोडुकी यांनाही यां विषेवे पकरे औषधरानि कालेअरु
कोषकी यां वेधे फेर मुडमचां कडेआरि खसखसोना
पाटांटोटहरनांको हराके सथपानकोहिनकरेहै १२
वोरुआमगपिदूर्वाहै मधर सनावरसत्ता मूटोहेव १
यार वीडनगर नव वुंच कुट इनांकेसाथ मालसकरा
वे १३ आमलेकोरस गुडइंद्रपडो मवा मवीर इनांका

पामपोपांडुशिरा:स्तान्त्यां:कोष्ठेचनेत्र
विस्पकगण हैडेश्रो रकइमरसकेस
रपामहिनेहिनेपानं १२ वोरकमलश
नाहारामासहरदाकसरलनगरैस्तु सहि
नेयांत्रनवेवचाकुष्ठै:पारमर्दनका
पं १३ आमलकरमसुटीकुटजफलेपि
पलीनपालेतोडुकल्कैसरपामहिनेपा
नेसमाहमहिहे १४ यवपंचमूलवद
रैविल्वकुलत्थपकारयेत्काथ मदलेव
णसनेलेनिरुहणंदापयेन्मतिमान १५
मेलेसालवणानिवहरोमकोमधरसा
हरोहे लोघनघातरूवोमेत्रणेनेनसं
युक्तः १६ पभिल्लेलपकोनिरूहनिवान्
वामनदद्यात्

कल्कनगदासणाकेसाथमनरि
नेइलाकरेहै याहै १४ अरु यहै पंचमूलहृदन अनाव
विल्वकुलथ इनांकाकाथ करावे ल्लणाविडयोडगा
वे औरनेलामिलाकरबुद्धिमान वेद्यनिरुहबास्तिडावे १५
मनोबल्लणपंजहदीडे मनका हरदल दाल हरदल
लोधर गलो औरमुनर बकरी का निसविषे रलालेवे १६
इनाबलसौंकेसाथनेलपकायकेनिरूहवस्ति औरयो
अनवासनवासिरेवेसोविधिपूर्वी विसेंलिखी है अरु

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ टी॰ १८३

183

तिसकों निवातस्थानविषैं बुधावे अरु वासयी तिसकूं नबका
हावै सो रोगीकौं देवै १७ और रोगीकौं मंगलीत्रिफलेविष
सिरकेर मचांपुड मरवीर होउर लायके देवै १८ इतिवि
भूयहविकित्सा यो कारण वायु के कोपकर कहे हैं गु
निहाकरके कोपित होकर वायु अपणे स्थानमें चलके हृ
दयकौं पीडन करता है और दाह तिससे चोडा रवी होता है
१९ [illegible]

स्थाने निवातसुखके पवने चैवानिवेदयात् १७
त्रिफलामाषिनां मत्स्यान्यथालिम्पंगवे र
कान् मधुसर्पिः समायुक्ता भोजनार्थे प्र
दापयेत् १८ इति विभूयहविकित्सा
स्वस्थानात्प्रसमीरः प्रकोपैरेव कारणैः
कुपितः हृदयं पीडयति दाहवेगमोहः ख
मामोति १९ पाराभ्यां लिखनि मुहलोख
दतिदैर्न षकामुमपकौलं श्रीनेलभ
तेस्रोवस्थानेयरिवर्तनेभीरुता २० कु
हूपामार्कं इमदार्गिने वर्मिन शेमन्ने लि
गेरैनेविघानहृद्रोगं वाननसंभूतं २१ तेजो
धनेगानकणासै पवाहिंगवनिविषाक
णाकहृकाः पभिःसाहिंलोमादेनोदया
काणात्रिदोमिकरी २२

और हृदयकौं मलोकरके पूरताहै अरु हृदनो अकरकेलक
डीकैलेकौं बकमारताहै अरु ठेर स्थानविषै सुखलभता
है अरु वार वार विलसताहै २० कोइकेर्यामागगमदा
त्रिगमथेउ होतानेहै इनालतलांकरके वायुकरदहृ
गयागलेवे २१ मूलकं रथीगजपिप्पल सैधालूणहि
इपरलीमसवा कोर इनाकौंमादिरेके साथदेवे सोत्रि
निकेउकाण करकहैया है २२

© Dharmartha Trust J&K. Digitized by eGangotri

पंचमूलकाक्काथवत्पयकेतेलल्लूणपायकेअरुमवो
काकल्कपायके तेलकौ चारगुणाक्काथपायकरकेमि
ठकरोतिसकेसाथआस्थापननामपछ्काकरिइहावे २३
औरबिल्वदारुहलदीकुलथइनोंकाक्काथअरुपंचमूल
काक्काथ अरुवासाकाक्काथ इनोंकरकेसमकिटेकरके
इसवरेनीकाथकरके तेल अथवा वेशकोपकावे २४
फेरतिसकौ मलस पान नसवार अनवासनवस्ति इनो

पंचमूलस्यानिकाथसैलैलसैंधवसंयुतः
पिप्पलीनोबकलेकनभवेदास्थापनं
नृणाः २३ बिल्वदारुकुलत्थानां पंचमू-
लस्य च वासक्काथेनानेननीरेणतैलं
मधिविपाचयेत् २४ नतोस्याभ्यंजनेपा
नेनस्तकर्मानुवासने मात्रयादेवमे
नस्यानभ्यमोदेयाविशेषतः २५ इति
वातरुद्रोगचिकित्सा पित्तेकुपि-
तेरुदयेत्तापयात्मीडयेत्मनः मा
ृणान् प्रमुसवाजोलिपातिरुदयपी
डमानेन २६ मेदचापिव्मनिखाटनि
वेपनेहोमातीनम्प्रयोर्यत्ते रक्तंमत्रंम
हतिउलेकामस्त्रामसभिष्वासौ २७॥

विषे यहे प्रमाणकोमात्रा देवे अरुविशेषतेंभमपिला
वेबाभुषाने २५ इतिवातरुद्रोगचि- पित्तकेकोपके पा
कारणहृतिहोकरकेकुपितहोके रुदेकोनपानाहेअ
रुमनुष्यणकेपीडितकरताहे तिसतोइकोमोरुदके द
र्षहोतेपांसेद परमाहोताहे २६ अरुधोडएवेदाहेभाव
पालिकीधोडापीनाहे कंदटाहे अरुवालडउनाताहे वा
लपछावकरदाहे अरुगर्भडहेस्वासलेताहै २७॥

© Dharmartha Trust J&K. Digitized by eGangotri

इनों लक्षणों नें पिभन्ज लहोगन्ना एणकेचिकिन्सा कहे
निसके आदि विषे पात्र अरुद्रुपोडकौंशाकी यानाडीयों
विषेवेपरुपिनिकाले २८ ठंडेजलकरकेस्नानकरावे
अरुवेहोकरकेमालस और ठंडे चिकड के साथ बहुत
बारलेबकरे २९ चंदन मुलटकों इमुघर नेजवला
अगर लोधर देवदार खसा स्थलकमल इनों कों इगप
साथपीसकेफेर इनकेसाथ घेत्रों सिद्धकरे बुद्धिवा

ऊर्ध्वाधोऽपि भोज्य वमेवं स्नानावगाहनैः क्रियां
कुर्यात् तस्मादौ विषार्तः पात्रैर्यो पाद
कौशाखिनः २८ शीतसलिलावगाहः
कर्द्दमैः सर्पिषान् यामंगः शीतेनक
र्दमेन वबहुशः स्नानं गमलेपेन २९ चं
दनमधुककड्डकमवशीनाकालान
सारिवालोधः मदारुनलदसाद्विनैः
प्रपौंडरीकुनसंयुक्तैः ३० एभिः पयसा
पिष्टैः कल्कैः सर्पिर्विपाचयेत्मतिमान्
तेनास्याभ्यंजनेपानेवस्तौ नस्ये च दान
मे ३१ मजीकामधुकेलाग्रंकसमयाः
शिकसेरुकाः सेमानकानिशालूक
नीवकभेकावुभौ ३२ पिष्टैनसेतुकेगा
थ्रकेसर्पिर्भुवमभाएते गव्येन पयसा
लोसपकों डूयायचे ३३

ला फेर इसको मालस पान बस्ति नस्यवार इनों विषे देने
योग्यहे ३१ मनका मुलटलोदर कसेरु राज माषणां संगारु
कमलनाडु जीवक ऋषभ ३२ इनों कों पीसके गउके सखी
र वे साइव विषे रलायके मानकालमें घोडे कों पिलवे ३३

© Dharmartha Trust J&K. Digitized by eGangotri

इति पित्तजहृद्रोगचिकित्सा ॥ श्लेष्मकारणकरकेको
पकों प्राप्तहोकरके ग्रपणेस्थानते चलकेचोडेकफ
हृदयमें वेस्थित होताहै तब तासों मनुष्यनें लालावग
तोयांहैन ग्रह हृदयते वीजललालांचलनीयांहैन २४
शिरबहूतभाराहूदखकरके धारताहै ग्रह विमनहो
ताहै ग्रह ग्रासवीमैमनतेवारग्रहण करताहै इसप्रका
रकरकेकफजहृदयरोगनाशकरके चिकित्साकरावेवैद्य २५

इति पैत्तिकहृद्रोगचि० श्लेष्मा कुपितः
स्थानान्हृदयस्यावतिष्ठतेस्म ना
मावद्भालालास्रवतिहृदयेकफ २४
गुरुधारयतेशीर्षे सज्जमनाग्रासमेद
मादत्ते पवेकफजेनावाहृद्रोगेकर्मकु
र्वीत २५ नालतिमधमवेधेनश्चशिरे
मात्रयाविविकस्य स्थूलजस्यचदेयपान
मिदंश्लेष्मरोगहरं २६ ह्रीवेरपशोककुला
गनपिप्पलिलोध्रतिक्तारोहिणः तेजोवती
त्रितिविषाप्रियंगवःसवेमेकचः २७ पिष्ठा
लोहेणप्रुतापिंडीकृताप्रलेहृदयेष्वेन ग्रनु
पानेदातव्यः प्रयोगतःग्रासवोस्य २८

तिसकी नाडियां हृद्धीनरांग्रगटजानके तालकीयां
विषेवेधकरावे रुधिरमरयादकानिकाले यवसाव
यानहोवे तोकफकेहराकरणेवाले पहेदेवे २६ हरीव
ग्रशोकवृक्ष मच गजपिप्पली वल्कलमाकुलोधर को
तुमालकंगणी ग्रतिस प्रियंगु इनांकोकंठकरके पीस
के मखौरसाथपिंडीवनाय चटावे ग्रोर प्रयोविघे इ
सकेसाथ ग्रासवग्रर्के भेरसोदेवे २८

© Dharmartha Trust J&K. Digitized by eGangotri

श्ला० वटलवेल शालकी गजभक्ष दन्तिए दंदनदाणेकीजड
ही० केउग्रारा केडग्रारी कौड ऊठ वच भखेड गलो हारदल दा
१८५ लहरदल भोशरा इंद्रजवो कंरमे मळकेले अक लाख
इटसिट कालिवेल पटोल परवल लाचीयां टटर मद्य मेषशृं
गी कायाकोठी वटलवेल पित्त देवदार इनांकोमहीनपी
सके इनां साथ तेलपकावे अरु चोइनाई नसवार और पीने
वास्ते देवे ५३ और त्रिफले विच रिणके मुंगी संड मद्य मवीर

पाठाशाल्मलिकिदंती बृहतीतिकरोहिणीकुष्ठः
श्वेतात्वरकगडूचीरजनीद्वयमार्कंवेंद्रजवेश्च ३१
कृविविल्वकाकेलातात्रनंवाशारिवापटो
लैश्च पलाश्चकनामपिप्पलिश्रृंगशृंगीकाक
माचीभिः ५० एभिःश्वेतोःपिष्टैरवष्ठापील
दार्कंसशुके नैलेविपचेतसंसैद्धंयनस्यवपा
नेव ५१ मञ्जुष्ठत्रिफलासिद्धांपिप्पलिशृंगवे
रकान भोजयेन्मधुसंयुक्तान्सवत्साभावच्छा
गिनाम् ५२ इतिश्लेष्मजहृद्रोगचिकित्सा ल
साम्लोद्गारः श्वासश्चेवोपजायतेयस्य र
सेनेत्वलनयने मुखशोषो मूत्ररोगश्च ५३
त्वरितोदीनःस्विन्नःप्रधानस्तेरक्तपित्तकोपा
श्च निर्गाकीनरंगोद्वयैरेतेविनिर्दिष्टः ५४

जउनारसाथरलाइके चोडेकोवानेदेवे इतिश्लेषमहृद्रोगचि
कित्सा। जेहरनगाणि मळ्ळोदाह रम अतीलाल सावस्तकण
मूत्ररोग श्रमहारि ५१ त्वर निवेली परमावहूत अरुधांसदा
है और रक्तपित्तका कोपहोणेते इनालक्षणांकरके यो
उनिर्गाणकीरोग पुरुके कहेया है ५४

© Dharmartha Trust J&K. Digitized by eGangotri

तिसविषें छाति अरुमन्याकी नालकी इनाकालहूकेउ
वे लहूनेरहितहोयकों जलविषेंचहालेघोरेतू ४१ फेर
घेउ तेलकेसाथ मालसकरे फेरठंडेविकउसाथ अंगो
विषेंलेपकरदेवे ओरपखेसाथफोले ओरठंडेस्थानवि
षेंस्थिरकरे ४८ अरुमनका फालसे अस्थरवेर खेउखेस
इसकेजलकों घेउविषेंगुए पहेशीतकषाय ४७ अ
रुमत्योर मचापायके सन्नघोलके तिसविषेंपीनेको

विश्वामेनसघिरेश्रोरेसेमसजेवतालवे ५१
शोणितनष्टविश्रुकेनलेनमवगाहयेदस्र
अभ्यंकेनलचूर्णेनशीतेनवकर्दमेनदिग्धांग
मानमेग्रवीनयेन्नसशीतलेस्थापयेस्थाने
ज्ञातापरषकाणिवसुस्तवदराणिशर्करो
शीरे मञ्जुयानल्पशेननयोशीतकषायप
रिश्राव्य ४७ लोहकणंसस्ष्टमसकंकपा
नमसदानत्ळ ग्रामंत्तीरमर्पिः लोहंवशर्क
रादेयं ४८ श्वेतामूलंपिष्टंछागतीरेणलाव
नेदघात तीरेणानेनश्वतावस्तोवेकदुफल
शस्ता ४९ स्त्रैसेनवनायोवाशीतिकरणान
घ्यानमकचिनं दाहज्वरशांतिकरेनीरागा
कनापंनतरगाणां ५०

देनेयोग्यहै श्रोरवकरीकाहूधघेउ मत्तीर खंउदेवे ४८
श्वेता स्यालिकामूल वकरीकेदूधसाथ पीसकरलूणपाय
केदेवे ओरवकरीकेदूधसाथ कायाफलपीसकेपछेका
शिकउावे बहुनश्रेष्टकहिहै ४९ स्त्रीकेदूधसाथ योशी
तलकरणा सोबहुतश्रेष्टगणाकरकहैयाहै सोदाहज्व
रकोशमकरताहै अरुनीरोगयाकानीरागणकीयोगेगक
हेआहै तिसकानाशकरताहै ५०

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा॰ चंदन मुलठ मखीर इह बकरीके दूधसाथ पाचनकरे
हो॰ याहै निंबको कूटके भांडेबिचपाइके जलकेसाथ बुद्धि
१८६ मान मथेछोले ५१ तिसतें योफेन फगनिकले तिसो।
करके सारेदेहविषें लेप करावे ५२ मुलठ प्रियंगू भा
वमें धनियांवा कंगुणी शालिधान काई गत्ते दूर्वा मु
थर फेऊ वीरणकीजड पद्मकाष्ट कमलफल वंशलो
चन कामीयां नीलोफरकीजड भये कालिवेल शिवाला

चंदनमधुकंबालंह्रीवेरंनलपावंनेतत्स्नान
त्तृणामरिष्टकान्वस्थालानीयेनमध्येनम
तिमान् ५१ फेनोयस्तत्रभवेत्तेनांगंसर्वमालि
पेत् ५२ अथमधुकंप्रियंगुःशालिकाप्तेतृद्रू
र्वाघनलकंवमृशीरंपद्मकंपद्मलोचनं कुमु
दबिसमृणालंशारिवासेवलेवैनलदंकुश
कदलापिमूलं ५३ मंजिष्ठोत्पलचंदनंनंत्रा
णालकनागपुष्पतिलाःमनोरमःपत्तंगक
सेरकापाटलाप्तरितं ५४ पष्टीवीरमधुका
गणाःशीतप्रदेहनेकषायमधुराणाप्तहिताः
पित्तविकारजित् ५५ शारदंग्रैष्मिकंवापिकषा
यप्रतिपाययेत् नीरागकेभितापेवतथा।
पित्तोभवज्वरे ५६

उशीर खसभेद दर्भकेला वैनकीजड ५३
मजीठ कमल चंदन रक्त नामगउपत्र खैर नागकेसर तिल
राल धूप वकम नागर मोथा पाटल ५४ पहेशीतगण कां
नी अर्कभेद सौवीरके साथ लेप करावे और कषाय मिठ
अमले हितकरहै पित्तरोग जीतनेवाले ५५ अथ सरदा
रतके अथवा ग्रीषमके कषायरस पिलावे नीरागक
के संतापविषे और पित्तज्वरके विषे ५६

186

© Dharmartha Trust J&K. Digitized by eGangotri

इनचिकित्सामें सामान्ययोंहैकरावे इतिनीरागणकीचि०
योनीवत्लणज्ञासनेजन्मताहै उसकारगवीत्लणसमहि
होताहै अरुहौलि २ चलताहै अरु योवेडे होतेहैं अरुयस
केसमस्वरूपहै तिसकोअंजलिकारिकानामकरकेकह
तेहैं १८ योज्योउतिसन्मूंवोदाहै सो येसेविदग्धअन्नपव
अन्नकीन्याई पीडितहोताहै अरुविद्होसहोजाताहै सोस
भदोषांको कुपितकर संपूर्णधातूआंको विकृतकरदेता
है १९ येदोप्रकारकी विषस्थावरमिठआदे अरुजंगमस।

एवंच प्रतिकर्माणि सामान्यानि विनिर्दिशे
त् १७ इतिनीरोगाणांकवि० स्नाणसेभूलजनत
णाङ्गवर्णांश्चमद्गामीव दीर्घवरणांस्कणा
कृतिनैवांजलिकारिकामंत्ता: १८ यस्त्वा
दतिवाम्नीविदग्धइवसीदतिविसंत्त: को
पयतिसर्वे दोषान्सर्वेधातून्प्रदूष्यति १९ द्वि
विधेनविषेणांतः कुरुतेखलयद्विवेष्टितं
सहसा तृष्णाकुरुतेवाम्नीकीटस्वभावतां
दस्य २० सम्मूर्छोवाप्यतोऽगरुधारयतेशिरो
भृशंश्वसिति व्यापार्ष्याश्चसर्वैस्सविकल
त्व्युदस्विन्न २१ नासांतराभ्यां स्रावश्चसवि
क्लवः प्रवर्तते श्लेष्मा नायंसाध्योवाम्नीक्रि
यातस्याप्यस्यकुर्वीत २२

खोयहोयेयो
पांदि इनके
चेष्टालक्षणकरताहै सोसभप्रकार इसकीटकेकेखोनेकर
केकरताहै २० मूर्छा आकरा शिर वहुतकरके धारताहै
अरुवहुतनिरंतर स्वासलेताहै अरुसवेदणाहूकालाप
डाहोताहै अरुव्याकुलहोताहै अरुअतीनिष्फलहोजा।
तीयाहै २१ अरुनासाकेवीच वहुतनलचलताहै वडाउरवि
अरुश्लेष्म चलताहै वहुत इसप्रकारयोजोउहै सोसाध्य
नहिहै तदवी इसकीचिकित्साकरावे २२

© Dharmartha Trust J&K. Digitized by eGangotri

पा॰ कुट अशोक छल्ल सुनका मद्या हरीड प्रतीस चित्र मि
ह्रौ॰ लायके इनांको महीन पिसायकरके प्रथमन नमवार
१८७ काभेदसो करावे ९१ इस चूर्णके साथ वारुणी मदिरा
प्रतिपानवास्ते देने योग्य है अरुणरा अर्क मदभेद वाव
डिंग चाउल अपसेर मिलायके चोडेकों खाने ताई देवे ९८
पंचमूल लघु जडो वेर कुलथ्य बिल्वकथ इनांका काथ
पाके चेउ अरुलूण ९५ महिष संडेका मूत्र मिलायके

कुष्टमशोकं कुसमा मद्दीका रोहिणीन्तथा
निदिग्धा चभि श्चित्रकश्चैकैः सचूर्णितैः प्र
थमं नेऊर्यान ९३ चूर्णेनैतेन युक्ता प्रतिपा
ने वारुणी प्रदानया सुरया विडंगतन्दुलकु
ठव स्नेरगायदेयमत्र ९४ पंचमूलयवान्को
लान्कुल स्थान्बिल्वे च विकान्काथमेवं
परिणाम्य सर्पिमैंथयवमेचुत ९५ निषध्यमा
हिषमूत्रेनि रूहमभिकारयेत् अभ्यगः पत्र
भंगेन स्वेदोरल शोवनव ९६ ततः खिन्नो
कायस्य स्नेहपानमिदं भवेत् वचाविदार्यं
समतिहृतमोषता वरीमोरटमश्वगंधाचवि
दार्य वलीं चसुकोपसमभेद च्छिन्नानराचैव
समम्लभागैः ९९
निरूहवस्ति प छिकारीकरावे
मालसकरावे अरुपत्रोंकेसाथ सेकदेवे इथसाथ सुख
करके ९९ स्वेदकरे होगांको स्नेहपानकरावे वच शालि
पूरकणी कंडेयारा कंडेयारी सतावरी मोरेया सुगंन
चदा गिलोइलका कपीर इनका अर्क पाखानभेद गलो प
हे सभवरावर भागलेके ९८ इनांका काथ गोमूत्रके
साथकरावे फेर इस काथ विषैदूतका मंड मिलावे।

© Dharmartha Trust J&K. Digitized by eGangotri

देउपावे अरु इनां वस्तू का प्रतिवाय कल्क जमाल
गोटे की जड लहसुन दंति दंदण दाणे की जड लूण सभ
पंज विल्वकथ हरदल दारहरदल मंघा पिप्पलामू
ल चवक पुंड चित्रा त्वची इनां को सिला विषे महीना
पीसकरके इस विषे पायके तिस घृत को पकावे ८९
पुरे घृत प्रातकाल में थोडे को पान वास्ते दे तो इस रोग
ते छुटता है १० तिस ते उपरंत मच पुंड सहांजना इंद

काथ्यागवां मूत्रयुतं वक्तव्यो काथेन तु ।
स्मिन् घृतमडमेभिः दंती द्रवंतीलवणैः
सबिल्वैरभिहरिद्राह्वयपंकोलैः त्वक्
समैतैर्हेषादिप्रदिष्टैर्विपक्वमेतत् ८९
प्रतिवापयुक्तं प्रातः प्रदेयं घृतमस्य पाने
तस्माद्धि कारात्स विमुच्यते स्यः १० ततो मा
गधिका शुंठी शोभाञ्जक यवानस्तथा निर्गु
ण्डा शाखापि पत्राणि तैव लवणानि च ११
एतानि सूक्ष्म चूर्णानि स्वेदपीताय पिंडि
का दापयेन्मात्रया तस्मै शनैः प्रकामये।
चैत १२ आमं च खादने देयं निर्वातस्थान
मेव च विशोध्य सकलं मत्स्य शोतानां चूर्णीकृ
तं तैनोभिवज्ना १३ यत्नादालोडजले देयं
तस्मै सुखो भवति १४ ९१

और लूण पंज
जड बूटी के पत्र
इनां को महीन चूर्ण बनाय करके स्वेद घृत पान किये हो
ए थोडे तांई प्रमाण की पिन्नी होली २ तिस तांई देवे खा
ने को १२ खाने को कचा देवे अन्न अरु जहां वात ना होवे
उस स्थान विषे वंधावे और मत्स्य को सुकाके सारे।
को महीन पीसके जल साथ हलूनी तंग मलके ति
सको देवे तो सुखी होजाता है १४

© Dharmartha Trust J&K. Digitized by eGangotri

भा०
टी०
१८८

188

इति अंजलिकारिकाचिकित्सा चोटलगणेतें स्रव कि
ला अगाला पालाई लगा इनां करके कर्णमार्ग विषे वाय
होणेतें वातादिदोष कुपित होके कर्णविद्रलि कर्ण
पालि यद चोटकी भेदकों प्राप्त होतीहै तद क्रिमीपैदे
होजातेहैं अथवा कर्णके वच्छकारणोंजा होजाताहै । ८
अरु कर्णतें दोषके भेदकरके लाल चिट्टा दुर्गंधिकास्रा
व वगताहै सोसारे खिलरजाताहै अरु कर्णको स्रवके

इति अंजलिकारिकाचि० अभिघातात्खर
कीलकर्कृपनेशलाकादेर्णतनाद्वाथ
कर्णश्रोतस्यथवादोषैर्वातादिभिःकुपि
तैः ९ कर्णविद्रलिकावाभिघाते यदाथ
स जायते क्रिमयो वाथपश्रुवांकर्णम।
यस्यः १० आवस्तःप्रसरतिशुक्रोथरक्तो
थपूतिकस्यापि कर्णशफेनचर्षति शी
वाविध्यतोतिकंडूतेः ११ हृयपथककर्ण
रोगीतत्रशलाकांतवेष्टयेमितुना ससा
धतेयाकर्णप्रस्रवेत्तोष्टसर्पिषा १२
कार्पासीतेदुकेरीणारसमभ्रसर्पिषा
कर्णस्यसेचनेसर्वस्रायतोपेताते १ ८

साथ चोटलताहै अरु ग्रीवा काजी का मांदाहै अरु खर्क
के साथ वहत दुःखी होताहै ११ यव चोटा ऐसा कर्णरो
गी होवे तो तव शलाकाकों रूंवेकेतूवे साथ लपेटे ति
सके साथ कर्णकों रक्तिं नरोग शुद्ध करके फेर मखीर।
अरु चोटके साथ केनकोभरे १२ कपीस वावनकपाट
इनांका रस मखीर चुतसाथ कर्णको सेचन करे ए
वंविधि कथिरपाकके स्रवकीये होये १६ अरु ऐसा।
ही विधि वाय जलके साथ भरेया होवे अरु दोषांकर्के

© Dharmartha Trust J&K. Digitized by eGangotri

कर्णोंके मूल विषें यो दोषज है अरु कर्णपकणे जिसक
रके कर्ण विषें दुर्गंधि होती है तिस विषें बी यथाक्रम कर
पहि विधि करे ८० आंवले निंब हरदल हरताल मनशिला म
जीठ फटकडी नीलाथोथा पटोल गोरोचन इनोंको विचपायके
तेल पकावे ८१ बिडालिका वा कर्णशोथ वा दोषज फिंगुणी इ
नांको शास्त्रके साथ फाडकरके फेर धारके भुश्रासाथ भरदेवे फे
र दोषको शुद्ध करके सैंधव लूणसाथ तिसको मले हच्छी तरा इ
इति कर्णरोगाध्यायः समाप्तः अस्रुपातके छेदने यो नेत्रके हेठ।

तैलेन चोद्वर्त्तनं कर्णेवा कर्णमूले यद्दोषजे पूत
कर्णपूरकेण कर्तव्यं यथाक्रमं ८० आम
लकनिंबरजनीहरितालमनःशिलामञ्जि
ष्ठालोध्रीतुत्थपटोलरोचनाभिः पचेत्तैलं ८१
विडालिकां वा शोफं वा पिटिकां वापि दोषजां
विदार्य शस्त्रेण तानि ग्रहणेन स्रावयेत् ततो
दोषांस्तस्मिन्शोधि सैंधवेन विमर्दयेत् ८२ इति
कर्णरोगाध्यायः अस्त्रक्षेत्रसमुत्थो नयनाद्यो
यो भवेद्व्रणशोथस्य विधानमस्रुपातस्य चिकित्सा
प्रवक्ष्यामि ८४ कटजबकमामलकहरीतकी
क्वाथयेत्तनस्तेन परिषेकः कर्तव्यो व्रणशोण
शोधनः श्रेष्ठः ८५ पलाशेण कपायक मा
सीमभ्यकेतैलेन पयसा तैलं सिद्धं व्रणायोः
प्ररोहणं श्रेष्ठं हितं ८६

जो छोडेको व्रणका तिस
कोंअस्रुपातनामरोगजाणे तिसकी चिकित्सा अब कहता हों ८४
कोगडके सिकटु आमले हरीड इनाका काथ करके उसके साथ
तिस व्रणको धोवे सो व्रणके घायको चडाता है और शुद्ध करता
है ८५ लाची वंश पद्मकाष्ट ... सुलठ पहे जल और दुग्ध मि
लायके इनोंके साथ तैल सिद्ध करे पहे तेल घाउके चडाने को ब
हुत श्रेष्ठ व्रणका रकरके याहै ८६ आमले निंब हरदल हरताल
मनःशिला मजीठ फटकडी नीलाथोथा परवलपत्र गोरोचन

© Dharmartha Trust J&K. Digitized by eGangotri

शा० टी० १८९

इनांकेसाथतैलपकावे ८७ यहतैलऊर्ककों समकरताहै
औरअस्रूपातरोगविषें मालस इसकेसाथकरावे लोयर
मुलठ इनांकोसाथमिलाय घृतसिद्धकरे यहघृतपानवि
षेदेवे सोपित्तकोनाशकरताहै अरुदृष्टिकोपुष्टकरताहै ८
काह्ली पथर मरिच गेरी हरदल तुलसी सुरमा रसौंन इनां
करकेअस्रूपातमें लेपकरावे ८९ जमालगोटेकीजड चित्रा
कियाजड तिल लूणमहोर यहेअस्रूपातकेविषें घाउके
पुष्टवास्ते बहुतश्रेष्टकहिआहै ९० निंब भंगी मधा मखीर

आमलकनिंबरजनीहरितालमनःशिलस
मृगाभिः सौराष्ट्रीतुत्थपटोलैरोचनाभिप
वैतैले ८७ केहुप्रशामनमेतत्कथितंहग
मस्रुपातगदे लोध्रमधुकवचतथाविपा
येत्सर्पिषासाहि ८८ एतद्धृतपानेपित्तघ्न
दृष्टिशोधनेश्रेष्टं काशीसममृचगैरिकरज
नीसुरसांजनैर्लेपः ८९ दंतीचित्रकमूला
नितिलाःसलवणाःमधुः व्रणयोःशोधनेश्रे
ष्ठप्रशास्तलस्रुपातिने ९० भोजयेत्त्रिवृतामु
स्त्रपिप्पलीतोदनपिबा शिरस्रुपातनेवध
शरव्हैनेवविनाननता ९१ शालिहवीतनवाश्रे
वपयसातिप्रशापयेत् इतिअस्रूपातचि०
शोफःस्यात्पवनीसनवातवलासप्रवनिर्दि
ष्टः कुच्छ्रेनेनक्रमतेगातप्रसक्तघ्यपवंगोपांत ९ १

चेउमिलाकरकै भोजनकरावे अरुनाडीयांअस्रूपातअस्त्रीके
हेठकी औरपउपुडीकीनाडीवेधकरे नाडीयांकेजाननेवाला
९१ औरशालिचाउल इवा एवल अंजेनवृत्त इनांकोउग्य
साथदेवे ९२ इतिअस्रूपातचिकित्सा योस्फुरासंधकी
संधीविषेंसोज तिसरोगकों वातवलासनामकहतेहैं
तिसते वडेक्लेशकरके चलताहै वायुकरके अकड
जाताहै अगेकाअर्धभागतिसते संधकीसंधीस्फुरति

189

© Dharmartha Trust J&K. Digitized by eGangotri

सकी नाडी विषें वेध कर रुधिर निकासे तब शोथ दूर
होजातो है लंघन कर उनें पीछे गुड के साथ वारुणी मद पी
णे को देवे १४ वेध कर रुधिर निकासेतें शोथ ना वहुत हो
वे तो फेर सातमे दिन पीछे करावे फेर नें लंघन पान क
रावे १५ रक्तो हरदल दालहूरदल गजपिप्पल शालभेद
पलाहादि आर भेद थोर पतीस कौड इनौं विषें मठा गो
मूत्र दुग्ध पहेंद्रव सभ ते वार गुणा पायके दुग्ध वा तेल

स्यैरकान्तस्य शिरां विध्वा ध्यायेत ततः स्थ २०
पु विभुन्तरकस्य हिताय गुडप्रज्ञाता वारुणीपाने
प्रथ्ये वेद्धहृशोथः स्यादेवं तस्तनेरेवसप्तमे दिव
से कार्यं तेनास्य पश्चात्पानं तेलं जलं देयं १५
काकादनी हरिद्रे गजकर्णी पलाश भद्रकाष्ठव
गड्डीरं वात्तिविषातिक्ताः दधि वैवगोमूत्र १६
पभिः क्षीरं तैलं चैतैस्सर्वैः प्रयोगेषु पाने वा
लैन स्थेवा भ्यंगे भोजने व सुजीत १७ अन
योरेकं तैलं वातवलासस्य नाशाय पंचमूल
कषायस्य स्नेहः क्षीरं वपिप्पली १८ एतदा
स्थापनं कार्यं पूर्वोक्तेनानुवासनं पथ्यं वन
स्नेहेभ्यः स्यादक्रिकमततः पर १९ क्षीणस्य
वातप्रकृतेर्जन्मोपहतस्य पित्थ वहुकारण
दोषाद्दोषात्पिवेन्पयसा प्राप्रयात् २० सोपद्
वस्थिरोगस्य वलासस्य नसिद्धति १

सिद्ध कर सभ योगों विषें जोड पान पछकारी नस वार मा
लस भोजन में देवे १७ इनां दो के वीचतें एक तेल वातवि
लास के नाश वास्ते है ओर पंचमूल का काथ दूध तेल दुध म
वा १८ इनां के साथ यो आदि विषें यो लिखी या है न आस्थाप
न वस्ति अनुवासन स्नेह वस्ति करावे जव इनां उपायों के साथ
रोगी ना होवे तो अग्नी का दाघ करावे १९ अरु यो रोग क्षीण
कृश होवे ओर वात स्वभाव वाले का अरु योजन्म तें हि सं थि।

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा०
ह्रो०
१६०

गतहोवे औरवहुतहेतूकरके औरदोषेंतेंसंधिकेविषें
स्थितहै १० औरउपद्रवकरके युक्तऔरचिरकाल वलास
रोगहरनहिंहोसकता १ इतिवातवलासचि० येकूंचेगिटे
केपोडविषेंदोषने योगंडीकोमलस्पर्शविषें अरुआमले
समरूपअरुगोल सोआमंडकनामरोगजाने १ देवदारु ह
रदल दारुहरदल अरु धमणीयां होपछुड इनांकोगोमूत्र
साथसीलगर्मवंधनकरे २ पहलेप्रछन्नपछकेपीछेतां-
वधावे अरुधान्यस्वेदसेकदेवे औरवीजस्वेदयापूर्वकहेन

इतिवातवलासचि० येकूंचेसंधिमाश्रितदो
षनातस्ययोमृदुस्पर्शः आमलकनिभाहृ
न्यास्तेवल्वामेडुकोज्ञेयः १ सुरदारुहरिद्रे
द्वेद्ववेलेविशभेषजेवैव पभिगोमूत्रयुते
स्ततोस्यउपनाहनंकुर्यात् २ [illegible]प्रछन्न
मारोपयाउपनाहमसकृद्वीत धान्यस्वेदंकु
र्याद्दीनास्वेदोपनाहेव ४ मेषवक्रप्रविड
गा निविड्दथिकद्धिचूर्णगवांमूत्रैः पभि
पिष्टःक्वथितैःपूर्वाकोवोपनाहेव ५ नैवे
वंप्रलयंयातिग्रथ्योत्रिस्ततःपरं विदाह्या
कृशायंत्रेणग्रथीनारुकविमुचान् ६ नाव
वोहनविदहेन्ममप्रत्वाशुविवर्जयेत् ७ इति
आमंडचि० [illegible]नितकफप्रकोपाउत्रीनो
नायनेसमा०

सोदेवे अरुवंध
नकरे ३ मेंषास्तृण कुठ
वावडिंग चित्राकेंथ और मद्याहेड गोमूत्र इनांकेसाथपी
सकर काढके यापूर्वविषें याउपनाहा वंधनकहे सोकु
रावे ४ येइनाकरके ग्रंथीयां समनाहोवे तोफेरग्रंथ्यांको
कृशायंत्रकरके वीरके अग्निकरकेदग्धकरे नघइनांरहित
होके मरवीहोताहै ५ योनाववोएयंत्रसाथदाघदेवे मर्म
तेनाडीयांकोछोडकरके ६ इतिआमंडचि० कुफरकतेको
पनेंघोडेकेमफ्केलिंगकेऊपर सोजा औरफीरणीयां

© Dharmartha Trust J&K. Digitized by eGangotri

ओरव्रणपाककरके ग्रंथिगिलोयांरहितियांहैन ८
जेकरइन्द्रीण छोडे नाहोवे तो कोष्ठकीतें उपांडस्थानजे
याकी मंथी तिसकेनाडीवेधकरावे औरमूत्रकोशतें
योकांकरके लहूकढावे जबलहूकढेयादाहछ्कीतरां
निकलजावे तबघृतकेसाथ तिसताई सेचनकरावे
औरगर्मपाणीतेलछारपीणेवास्तेदेणेयोग्यहै ९
खार जऊकाछार बिडलूण खल ढुपद्येउ रसनांदालेपकरे

मेढ्रेश्वयथुःपिटिकाप्रक्लिन्नास्रवरक्ताभा ८
तेस्मात्तीणस्यशिराःकोष्ठात्याज्ञश्रितास्त्वे
पश्चा रुधिरंव मूलकोशेविरेचयेद्धनैलौ॰
काभिः ९ विश्रुतरक्तंस्नपितंघृतेनपरिषे
कयेत्तनतैस्मैउस्नोदकंसतैलेक्षारपानाय
दातव्यं १० क्षारंविडंसकिण्वंपयोघृतेलेप
नेत्रनातांतरोपणमेतत्स्नेष्टमदेडकरणम्प्रे
ष्मसंशमने ११ कासीसांजनसैंधवहरीतकी
लोध्रवह्निहरितालैः रजनीद्वयमंजिकाया
गवांचमूत्रेणसंयुक्तैः १२ पिष्टैस्तैलंविपचे
द्व्रणरोपणशोधनमहकरणं मेढ्रशोथवि
नाशनमेतद्दोषापरंश्रेष्ठं १३ अरिष्टगुग्गुलै
लेनपिप्पलीतोहंसंयुतान् भोजनंचास्यदा
तक्रंतथामलभनेस्तव १४

छायकोपढ़ेप्रोष्टहै
अमूरजुडानेवास्ते अरुनमाइकरताहै अरुशोथमकोंमम
करताहै १० कासीस सांजन संधालूण हरीड लोध्र चित्रा हरता
लहरताल दालहलदर मंजी गोमूत्रकरके एकमिलावे ११
इनांकोपीसकरके तेलकोपकावे सोतेलघाउकेकाने
को शुद्धकरनेको अरुकोमलकरनेको श्रेष्ठगुणकारहे
औरमेढ्रोगसोजेको इनतेरोगोंकोनाशकरनेकोश्रेष्ठहै १३
अरुनिंब गुग्गी तेल साथ अरुमहीर मयासाथ भोजन
छोडेकोदेवेतो सरखेकोलभताहै १४

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
ह्रो॰
१९१

इति उक्तीतरोगचि॰ जिस घोडे के अंड सूजावा खेवा वार
वार खेले वा रुक जावे तिसकरके लंगडा होया चलता है १
इसते तिस घोडे का त्रिक पिठ देह रुक जाता है सो वडे दुः
ख करके पछाकरता है ओर मूत्र करके एक दुःखी होता
है १६ अथ लक्षणा करके अंडरूकदी रोग एक घोडा कहेया
है तिसको पहले मालस फेर स्वेद सेक फेर मर्दन करावे १
उपांउ अंडे के हेठ की यां नाडी यां वेधे फेर बुद्धिमान वैद्य

इति उक्तीतरोगचि॰ वामोथ दक्षिणो वावार
वारयुदाऋषणः संकुटते नैव खेवं न सल
ति गात्रेण १५ अथ नस्य त्रिकं पृष्ठं गात्रं च वि
रुध्यते दुःखात् अल्पमूत्रकृत्ते वाजी स्पू
लाभिभूतस्य १६ अंडकं द्वौ रोगवाजिनं उ
क्रूमोमवेदयः तस्याभ्यंगः स्वेदो मर्
दनेकृयात् १७ वेध्ये वा पाउ शिरे प्रतिपाने
त्रिकटुकं करेनैव लवणानि पचस्तु रयायु
क्ता निर्वापयेत् मतिमान् १८ सैंधवगैरिक
कुष्ठैः पिष्टैरालेपनं भवेत् तस्य परिषेचनं स
लोस्मिन् अंडकयोः कारयेत्पयसा १९ यवपच
मूल मोरट बिल्व कुलस्थ अकोल सप्रुकैः
पभिः सिद्धकाथ तैलं च निरूहणं देयं २० घृत
तैल वसा मज्जा कल्कसुरदारु कुष्ठ तगराणि

मधो मरुव पुंड मक्कुके लण पंजलूण सहागके साथ प्र
तिपान को देवे १८ सैंधालूण गेरि कुठ इनांको पीसक
रके लेपन करे तिसको ओर अंडो विषे गर्म दुद के सा
थ सेचन करे १९ जओ पंच मूल हुदन जीरा बिल कु
लत्थ बेरफल इनांका काथ कर तेल सिद्ध करके निरू
वत्ति पछकारदेवे २० घृत तेल सिंक मज्जा इनो स्नेहो
विषे कल्क नगदा दिआर कुठ तगर नरव मुलठ॰

© Dharmartha Trust J&K. Digitized by eGangotri

रास्ना पंचमूल विलाण अग्निमंथ गंटर पाटल कशीर २१
पहेसभडगया पायपकायकरके अनुवासनवस्तिकरावे
अरु सुराकीनसवारदेवे अथवामदिराकीदेवे तिसकोउ
णकरहे २२ और यवदन्तिणअंडशिस्के तोवामविषे संचनक
रावे येकरवामकावलताहोय तोदन्तिणकासेचनकरावे अ
रुदोनोपासेकेहोवे तोदोनोपासेकरावे २३ जेकरअतसे
करके मुष्कहकणखिसकजावे वहुतघटहोजानु पीडाकर
केयुक्तहोवे तोकोमलचर्मकीटली वा कपडेकीलेकरके

११

आग्रनलमयुक्तरास्नाकाथः स्नांसंवमूलस्य
संवत्तीरेणयुतेविपक्कमनुवासनेनततःऊथा
नुनसेचनराद्वेयामदिरावापसनेवास्य २२
सेचयेद्वामतोस्यस्फुंडस्कवलनिदक्षिणे वा
मदक्षिणतोद्वयंअभयेनत्युद्वय २२ अनर्थ
स्फरितोमुष्कौसव्यकौवेदनार्दितौ स्तङना
चर्मपटेनवभीयात्कर्पटेनवा २४ लवणोस्त
हृदधिभिःसंडोमरवसंयुतैः समस्तकंतमा।
स्यद्वयं सर्वारूपानमोच्यते २५ काकतिंडुक
मूलानिमट्टमुस्तप्रियंगवे नसतोयेनदा।
नेमुष्करोगप्रशोनये २६ हिंगुसोवर्च।
लोपेतःक्वाथोवातारिमूलजः रुतएडवा।
लुमापीतोदिनैरगणितैरपि २७ आपमा
यतेसत्तडरष्टः साभोप्रतिहतश्चयः ।

वेधनकरे २४ अरुलूण घृत वा तेल मदा सुंठ मरिच इनो
कूकै संदरवनाय मठ्ठीका दूध प्रातकाल विषे पानकरने
कोपाहदककरयाहै २५ काकतिंडुक काकपीलु जड नागर
मोथा फूलफंगु इनकेजलकेसाथ नसवारदेवे अंडरोग।
केहरकरणेवालेप्रदहै २६ एरणकाकाथ हिंग सोंचल
लूणकरके युक्तपीणेते वहुतेदिनोंकोवी अंडवालावहेति
सकेटकोहरताहै २७ अरुजिसकोआफरा अरुटष्टिजडहोजावे

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
ह्नो॰
१५२

दमजिसको विकृतबढगेया अरुमूलमूत्र वंड़ेक्लेशकर केहोवे ऐसे चिकित्सा न करे २८ योइसाउपद्रवोंतेरहितहै सोसह्यलेकरचिकित्साकरके सिद्धहोजाताहै २९ इतिअण्ड स्कंधचि॰ अथवा जिसघोड़ेकेदोपअंडकोशहलगपड़ेहैं अरुकंवदेहैन पीड़ावहुतकरकेपीड़ित सोवातरक्तकरके है अंडवालिनामघोड़ेकानामहै १॰ अरुउसकेयोपूर्वलक्षण सोइसकेवीहै योचिकित्साकहै सोसभइसकीयोकरेउ पाउनेरुधिरकढावे अरुयोइवेविषेप्रतिपान और ओषधी

192

कृच्छ्रमूत्रगुरीषस्तनसशाकाश्चिकित्सितं २८
पतेविरिद्धेनोयस्य सस्रुमिद्धानिकर्मणा २९
इति अण्डस्कंधचि॰ अथ वृषणौ चलमानौ वे
पनौ वेदनार्दितौ स्यातां यस्य हयो वालीति
गद्यते वातरक्तेन १॰ असाध्यं न दृष्यवी के
स्याचिकित्सितं यस्य औपाडस्तकमोक्तः प्रति
पानाद्यवभेषजं ११ अंडवालनचि॰ पित्ते
स्यानातुपितं अयोगंतेमुष्कयोर्भवेद्यस्य
तस्मात योः शूलंवदाहस्याकूलता वेव १२
अथतस्योपांडुशिरेव यथेमसर्पिषाहितोभ्यग
न्त्वकलीविणावपिष्टाप्रदेहनसर्पिषायुके १३
काश्मर्यंशुसहकरफलोमस्तीकाघृतपाकया
सहितः काथः पानायहितः शीतो मधुशर्क
रामिश्रः १४

सोसभकरे ११ अंडवालनचि॰ पित्तकारण
करके कुपितहोके अपणोस्थानतेअंडों विषेगया होवे जिसके तिसकेदोनोंअंडोंमेंशूलदाहहोता है और कालेरंग केहोजाते हैं १२ तिसकेउपाउ कियानाड़ीयामेवेयकर के अरुघेउसाध्यमालसकरे अरुक्षीरवृक्षवटादि तिनाकेसिकउमरीनपीसघेउकेसाथलेपकरावे १३ कशीर मधुरकाफल मनका रस्तो इनोंकाकाथठंढाकरके मधीरनेखेंडसाथ पानेकेवास्ते हितकर है १४

© Dharmartha Trust J&K. Digitized by eGangotri

ड दअरु मधुकेसाथस्नानमेंसेचनकरे ओरठंडेलेपकरावे
ओरइरणकी पछुरी फडवे तोपित्तांडी पित्तकर अंडरोग
नैरागी होजाताहै १५ इतिपित्तांडचि० जिसघोड़ेके वृष
णदोयरक्तकेकोपतें सूकजावे वा हलकेसूजजावें अरु
पीडाहोवे कालेहोजाए वा लाल अरुवराबर नांवथा।
चटहोन १६ ओरपांडुकीनाडीतें रुधिरछुडावे अरुपा
नमदिराआसवअर्कभेदेदेवे लेपशीतलकरे ओरव
स्तिमें अतिदुग्धकेसाथ १६ जवसोजचटजावे अरु

तोरंहरथिपरिषेकः शीतान्सलेपनानिवो
मानि देयश्चपयोवस्तिस्ततः सुखीभवति
पित्तांडी १५ इतिपित्तांडचि० वृषणौ द्वावपि
फूलौ स्कधेनेरक्तकोपेन रुसौवारकोवा
सवेदनौवासमौविषमौ १६ ओपाडुरक्तमो
क्षपानेमधासवोहितस्तस्य शीताःप्रदेह
श्चकामसूक्पयः सघृतोवस्तिः १७ यदा
निषनाथपशुमूडश्रूनसूवेदनः सेदास्त
नोस्पदात्ततः वातघ्नाः स्वेकीर्तिताः १८
आस्थापनंवास्यहितंवातदोषहरशुनः त
तोवातहरंतैलंकार्यमस्यानुवासनं १९
श्रुइस्फेदनवाःप्रोक्ताः क्रियास्ताभिरुपक्रमे ८०
इतिरक्तांडचि० वृषणौकफनशूलौस्यातां
गुरुदर्शनौमस्पर्शकठिनौ

पीडावीचटजा वे तवइस
कोस्वेदसेकदेवे येपूर्वविधिवायुकेनाशकरणेवालेक
हेहैं न फेरअस्थापनवस्तिहितहै वायुरोगकेहरनेवा।
ली ओरफेरवातहर तैलकेसाथ अनुवासनपछ्का।
रीकरावे १९ ओरजोअंडस्वेदविधियोविधानचिकि।
त्साकहिहै तिनांकरकेउपायसभकरे ८० इतिरक्ता
डचिकित्सा जिसघोड़ेकेअंडकोश कफकरकेपीराघ
करहोवे अरुवडेमोटेहोन ओरकरडेहोवें सोघोड़ेयों

© Dharmartha Trust J&K. Digitized by eGangotri

भा. केलक्षणजानूएवालेयोंने क्रोष्टुशीर्षनामरोगकहिया
रो. है ४१ तिसविषें उपाउशोफकीयानाशोवेधकरावे औरपेश
१९३ मकेमांसकेविषें जेलेपकहेहैंसो गर्मकरकेलेपकरावे · ४२
लाचीया प्रतीस कोउ कठवचे हरेणु मस्तालु इनोंका
चूर्णकर मदिराआसवसाथपानकोदेवे औरगर्मतेल
193 साथपच्छकारीकरावे ४३ शरारी गजभस्म और पवइ
नोंकाकाथवनाय इसविषेंसिद्धशुतमखीरमिलाकर औ

यस्यतुरंगस्यासौक्रोष्टुशीर्षकीर्तितस्तथा ४१
तस्याशिरावेधस्सेहुपांडुयोः श्लेष्मजेनयाथ
पथ्यो येवालेपाः कथितास्तैलेपयेत्सेस्तपुको
लैः ४२ एलातिविषाविकटुकाकुष्ठवचार
एुकाकृतचूर्णं मद्यासवेनपानंतैलेनो
लेनवस्तिश्च ४३ शाल्लकियवनिःक्वाथैःसि
द्धान्नौद्देणसंयुतान् तैलमद्दोषपक्वंस्या
स्तुक्काभोजनेदयात् ४४ समेप्रक्रमये।
चैवमप्रमत्तः शनैर्बुद्ध एवंहारोगाः स्वस्था
शीतेजस्वीचोपजायते ४५ इतिक्रोष्टुवि·
रक्तोयस्यापानोमृघणोमूशवदनोयथाप
क्वो तेपच्छाउनमच्छमानीयात्सन्निपाते।
न ४६ तस्योपाउकोष्ठेभित्वारक्तंविमोक्ष
येत्ततिमान् स्पितेविविक्रतोषप्रदेश्य
म्यपिधावेत् ४७

रतेलसहुत म ताकेपुक्कभोजन
नविषेंदेवे ४४ अरुसमस्थानविषें फेरहोलीहोली।
सावधानहोके वहुतचिर इसते क्रोष्टुकांडी घोडानिरोगप
होजाताहै और वडेतेजयुक्तहोजाताहै ४५ इतिक्रो
ष्टांडवि· जिसघोडेकेवडेलालअरुआफरेहोए अरु
वहुतनिरंतरपीडायुक्त औरपकेहोवें तिसकोंपछ्छा
डीघोडासन्निपातकरकेजाणे ४६ तिसमेंउपाउतेरुधिर
निकालेवुद्धिवाला रुधिरकैकडेदे अरोगप्रगटहोयतें ए
तसाथ्यलेपकरेनिमत्र ४७

© Dharmartha Trust J&K. Digitized by eGangotri

फेरवाला मद्यं सनका मुलह ठीधर ए है कि ठेकरके मधा
सवनाम अर्कके साथपान तिस घाउ नों इदेवे ४८ पीलु चीड
पाटल वा जीरा काला तमेदी जउ इट सिट श्वेत ओर रक्त मंचा
सौंफ मिलो इनोंका प्रदेह का लेप वारंवार करावे तिसको ४ ८
यव इनों उपायोंकी येते राजी नाहोवे तवतिसके अंगको चीर
देके पुष्टकरे जव पुष्ट हो जावें तो उस घाउ को घृत और मत्ती
रके साथ भरदेवें ५० अरु तिसको पान मत्ती रसाथ मदिरा

एवंवालककाकुसाम्रहीकामधुकलोध्रमंय्
के मधास्मवेनगुरुकेपानंतस्मैप्रदापतंयं ४८
पीलःसरलःकालासग्गदनीगुनर्वेषणा।
मा शातपुष्पास्तनसहिताप्रदेहमस्तकेइवे
तस्य ४९ मस्तकीयदिनैवसाह्रषणवव
पाघशोययेतस्य मस्तुहवणमेवप्रस्वेय
न्सोइसर्पिभ्या ५० पानंतोइणसगदघ्या।
न पित्तमंदस्मा पितान्स्ररान् व्रणयावंत
वरुयांयघ्नोकेद्विव्रणीयेत ५१ इतिपञ्चा
उवि० वातात्पित्तात्कफाच्च सन्निपाता।
च्चशोणिता च्चैव सहजान्यपिवद्धयाना
मशींसिवषाहिजानीयात् ५२ नासानि
कर्णावदनेमेढ्रेनाभ्यांह्रवणायोश्चगदे
जायंतेत्वरगाण्णगुदाशीसांवस्तेकर्म
५३

पिलावे और खाने को निवके जल विषे रिनी होइ मुं।
गी देवे अरु घाउ को धोवे या विधि द्विव्रणी अधिकार
विषे कहि है ५१ इति पञ्चाउ चिकित्सा घाउ याको अ
र्श मस्से सीया छै प्रकार कीया कहियां हैं न वात पित्त
कफ सन्निपात रक्त सहज ए है भेद है सो जाणो ५२ सो
घोउ के नासा अद्वि कन्ना मुख लिंग तुन्नी अंड गुदा इना
स्थानों में होवे उनों किया या चिकित्सा होते हैं न सो सम
आगे कहते हो ५३

© Dharmartha Trust J&K. Digitized by eGangotri

शा. योअर्शाममेसीकहिहैं तिनांकोघोडेकीगुदाके विषेयंत्रदेक
हो. २ कंटशस्त्रकेसाथ फेरअग्निकरकेदग्धकरे तिसकेपीछेति
१९४ लपोसकेलूणपायकरलेपकरे घोडेकेदुःखकेशांनकरणेवा
ले ५४ अथवायोक्षारकर्मकेजाननेवालाहै सोक्षारविधिकरे
वंशकीसलाईहैकेतिवेसाथलपेटके तिसकेसाथक्षारसला
यकरकेगुदाकीनीसरिवलिविषेक्षारपावे यवज्योंछोपकेक्षो
पजामणकेरंगसमरंगहोके औरभुआंकेरंगकीन्याईहोजा

वक्षारदेनयंत्रच्छित्वाशस्त्रेणवह्निनादग्ध्वापि
षैः स्तिलैःसलवणैःप्रलेपयेद्दाहशान्तये ५४
अथवाक्षारकर्मज्ञःक्षारकर्मप्रयोजयेत् श
लाकायांवेष्टयित्वापिच्छुनावेष्टिताग्रया ५५
गुदेवलयसिक्तेक्षारंनिपातयेत् य
कंजमभृशतिकाशोशरसमनिभंयदा ५६ सम्य
ग्दग्धमितिज्ञात्वामधुकघृतसेचनैः सेचा
येत्यथावापितैलेनायुक्तनिर्हरेत ५७ इति
अर्शासाचि॰ वालाद्दकप्रदुष्टेनरुधिरेणप्र
जायते तलःकेनव्रणोदाहःक्लेदोवालावशी
रणं ५८ क्रिमीणांभुद्भवःपुच्छेकार्श्येनसमा
जायते स्वेपुच्छंशिराविधानततःपानानिपाद
येत् ५९ क्रिमिघ्नाश्चप्रदेहाश्चनीलाश्चाम्रा
श्रमतः ६० इतिवालादकचिकित्सा ।

वेतोअश्वोंकीतरांदग्धहोयाजाणे तवमस्तोरकेजल औरनोपके
पाणीकेवैवाजुथकेसाथधोयके यंत्रवाहरनिकाले ५७ इति
अर्शासाचि॰ घोडेकोरुधिरकेविकृतहोनेकरके एकवालाद
नामरोगवालचरहोताहै तिससेखरकरयाउहोताहै
दाहक्लेदचायवगदाहै वालफडजातेहैं ५८ अरुक्रेवविषे
कीडेपडजातेहैं तिससेघोडेकोलिसिआईहोतीहै तिस्से
पत्लेउवकीनाडीवेधकरके फेरपानपिलावे ५९ औरधासो
तेनीलाक्रिमियोकेहरनेवाल्लेलेपकरावे ६० इतिवालादक
चिकित्सा ।

© Dharmartha Trust J&K. Digitized by eGangotri

उदररोग आठ प्रकारके कहेहैं वाततें पित्ततें कफतें स
न्निपाततें बद्धगुद प्लीहोदर जलोदर परिस्राव ९१ इनो
समना उदरोंका लक्षण चिकित्साभिन्न २ कहतेहां संक्षे
पकरके ९२ जिसकोरेका उदर आफरावडाहोवे अरुवा
युशब्दकरे अरु लिस्साहोवे अरु खावेबहुत सोवा
तोदरजाणो ९३ योह्वोडा गर्मखासलेवे अरु भोजनब
हुत खावे परसाआवे अंगसभगर्महोन अरु फिउवध
नाजावे जिसका तिसकों पित्तोदरजाणो ९४ जिसके

उदरं पवनात्पित्तात्कफाच्चैव सन्निपाततः।
प्लीहि वद्धगुदं प्लीहोदरं सदकोदरं परिस्रा
वः ९१ एतान्युदराण्यष्टौ रूपाणि चिकि।
त्सितं समासेन सर्वेषामेव वाष्टप्रकारस्य
क्ष प्रवक्ष्यामि ९२ उदरं यस्याध्मातं वायुः कृ
तं सशब्दं समंथे कार्श्यं पवनाहारतस्य तु
वातोदरं विजानीयात् ९३ आमं सुक्ष्वमसलवड्डा
पीमिद्यते ततो स्यागः उदरं च वर्द्धते यस्य
तस्य पित्तोदरं विजानीयात् ९४ जठरे तु महाशोथे
मंदाहारस्य वाजिनो यस्य ततः प्लीहोदरम्।
थवा समेधेन हृदये हि नाभ्नीयात् ९५ अल्पास्थि
रगुरीषवातश्च निरुध्यते गुदे पीडा उदरं वि
वर्द्धते वै बद्धगुदं तं तु विद्धि ९६ एकैकस्मिन्
सफेनं सुचति मंदं न बाध्यते व गुदं मूत्रकृत
ते स्वल्पं विद्यादेतं परिस्रावं ९७

जठरउदरविषें बडासोजहोवे अरु खावेथोडा जिसको
खेवेपासविषें होवें तो प्लीहोदर जाणलेवे ९५ जिसको
लिट्यो २ अडक करकेहोवे अरु वायु रुकजावे गुदाविषें
पीडा उदरबधदाजावे सोबद्धगुदक हैयाहै ९६ जिसको
लिदलहू ओर कफकेसाथ मिली होय थोडी करे अरु
गुदाविषें पीडा नाहोवे अरु पछावथोडा २ करे जिसको
परिस्रावउदरजाणो ९७

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा॰ योउदरजलकरभरियाहोवेछोडेका उसकोंउदकोदर
हो॰ जाणो औदरकोंछोडकरके औरउदरोंकीचिकित्सावि
१९५ धिकरे ९८ वातकेउदरविषे मदिरासाथघृतलवणया
पूर्वलिखाहै सोदेवे औरस्नेहकृततेलदेणेयोग्यहै
महास्नेहकरके बुद्धिमानदेवेयववस्तिपक्ककारीफडावे
औरकुलत्थोंकेरसकीनिरूहवस्तिदेवे औरवृहत्पं
चमूलकरकेसिद्धयवागूकीपक्ककारिफडावे १०० अ

उदकव्यापन्नहंसंविधायउदकोदरंस्नेहंगा
णा स्नीहोदरंस्नस्नकाशोधणंवैक्रिया
कर्यान ९८ सुरयाघृतलवणंवातिकेप्र
तिपादयेत अथापिस्नेहदेयमहास्नेहन
बुद्धिमान ९९ वस्तिदेयानिरूहस्यकोलत्थ
श्चरसस्तथा पंचमूलविपक्कावायवागूप्र
तिपाययेत १०० अर्कमूलंवकुष्ठंचपिप्पलो
विश्वभेषजं क्षारंविडंहरिद्रांचपिष्टातैलं
विपाचयेत घृतंवापिययाथापिनदेनप्र
तिपाययेत चित्रकारिंगमहौषधमागधि
कान्क्षारलवणाभिः १०१ दध्यादिभिःसमू
त्रैस्तैलपक्कहितंपाने अञ्जलोमैःकषाये
स्तहृतमथोविपाचयेत १०२ तस्मिन्तोयदि
एौदेयंतेषांचूर्णंनवापुनः श्रवणाय्य
वमेवस्याच्छ्रुकवातिकेपुनः १०३

ककीजड कूठ मघा संड धरेस्नार विडलूण हल्दल इ
नांकोपीसके कल्कपायतैलसिद्धकरदेवे अथवा घृतयो
दायदे नेमाहीसिद्धकरकेदेवे चित्रा हिंग संड मघा जव
स्नार पंचलवण इनोंकरके और मढा दुग्धरसादिक औ
रगोमूत्रआदिइनोंकेसाथसिद्धतैलकपानवास्तेहितक
रहे योवातरकोनिमथक्वाथरे तिनकरसिद्धघृतइनो
केचूर्णसाथपिनउदरवालकोहितहै १०२ अरुयावात उदर
विषेकहेहनसोईद्रव्यादिकंकफोदरविषेभीहै १०३

© Dharmartha Trust J&K. Digitized by eGangotri

यो इत्यादि प्रतिपान कहे या है सो बद्धगुदोदर में गुदा के
द्वार से देवे अरु जलोदरवाले का उदर में वेध कर जल वा
हर निकास देवे १४ हृदय अरु नाभि तनी के खबे पासे
रोमराजी ते अदी अंगुल स्थान छोड कर के शस्त्र की विधि।
में वेध करे १५ जिस में शस्त्र के पर की लाली वा रअंगुल प्रवे
श हो जावे तिस कर के जल बाहर कड देवे और बुद्धि वाला
वैद्य यो रवे विधि कहि है सो करे १६ इति उदराणां चि. अ

इत्यादि प्रतिपानं च गुदे बद्धे प्रयोजयेत् १३
कोदरिणः कोष्ठं भित्त्वा निर्वाहयेज्जलं १४
हृदयस्य च नाभेस्तु विद्धमर्मं विवर्तनः अ
ङ्गुली रोमराज्या वामे शस्त्रेण वेधयेत् १५
ते चैव शस्त्रनाडी स्यात्त्वे शपावनंगुला शो १६
थ एवोक्तविधिना भिषक्कुर्यात्सबुद्धिमान्
इति उदराणां चि. धान्यामामानियदापक्का
तिनिषेवेते बहूनपथ्यः मस्यानियवादिनो मे
विनैस्तैरन्नौषेन १७ प्रतिमात्रमयुक्तेन
वासनैर्विषममार्गेषु एवं विधैर्योगैरसक्त
पोरवितः मारुतः १८ दूषयति त्वगूर्ध्व
नैनगात्रयथोनाम्न दृष्यानां प्रकं देसेन भवे।
वेनः प्रकारः सन्निदिष्टः १९ वातपित्तात
फाश्च सन्निपाताच्चवेनवैश्यन्कम्

चक बे यटप के होय बहुत खावे मांस यउ कन क इत्यादि सेव
न करणे कर के बहुत खाणे कर के अरु योग जोड की विधि को
नही जानदा तिसने बहुत विरेड मार्ग विषे फेरणे ते इत्यादिक
खोटे योगों कर के विकृत होया रस सो लहू को बिगाड देता है
सो विकृत होके जोडे के अंगों को अरु छाती को रोक लेता है ति
स को प्रसक्त करते हैं देह पकड जाता है सो वार वनरंकाक।
हे या है १९ वात पित्त कफ सन्निपात ते सो बोडेयों को रक्तप्रथा
ने ते होता है २०

© Dharmartha Trust J&K. Digitized by eGangotri

शा. टी. १९८

196

वा स्रकरकेयोहै तिससें सभेदहै ग्राकृइजातेहै अरुकफपि
त्तनेचौडेको दाहअरुदेहभारीहोताहै कफकेकोपनेयो
है तिससेंसमअंगभारीरहैहोवेहै ८१ सभनालहलावा
लायोशर्कदहै सोसन्निपातकहियाहै इनांरोगांवालेचौडे
यांकोअन्तदोषबलनिबलदेषकर्केपहलेवनकरावे ८२
वनकेपीछेचौडेकोंपहलेवासकायाहरुवेइयोउत्तुआवे
जलतिसतांई इच्छाकेअनुजवपिलाके दोचडीवलगकेफर

शोणितनस्रोलोवानो शर्कदस्वेषविनेयः ८०
श्लेष्मामारुतकोपाभ्यां देहेन भारिकफपित्ता
त् प्रतिभारिक सर्वांग कफप्रकोपाद्विजानी
यात् ८१ सर्वैर्लिंगैर्युक्तः शर्कदः सन्निपातकः
प्रोक्तः आदौ लंघनं मथवास्वंतदोषबलाबल
त्वात् ८२ अथवलंवितस्य सर्वेग्रामस्रोकुष्टद
पयेन्मतिमान् सलिलंवक्रामतोस्से तनों उ
ह्नेस्थितं विधेयेत् ८३ गौरवंयदिवोरस्यंवो
रुस्रोखावेतेततः बाहुस्रेयदि मम्येत पार्श्वेया
भ्यातंततः स्रुतिः ८४ तैलेषु ग्रान्त्यादोषरो
मांगतं तदस्रकस्रुतिः नचनैगौरवंमस्तावा
पांशभ्यामस्रवनुस्रुतिः ८५ सर्वेष्वेतत्सम
पश्येत्सर्वानभिस्त्वविरेचयेत् नचात्पदापथ
नीयं भोजनं तोवोदनानि वा ८६

नाडीवेधकरावे ८१ यव उरस छातीभारीहोवे तद
छातीदाकधिरनिकाले यववाहुओंविषेसूटआई
होवे अर्करजाण तोपयाणसूवैततरहूनिकाले दो
नोंपासेतें ८४ यवतलविषे शर्कदहोवे तवरोमनतर
रसंधितेरुधिरनिकासे जवपर्दोकेविषेसुटआईभारी
जानिए तोउपरइ अडीकेपासतेंलहूनिकाले ८५ यवस
भस्यानींविषेवराबराटदीप तोसारेस्यानोतेरुधिरनि
काले फेरनदिदेवे पाणीहाणाचासजिसको ८६

© Dharmartha Trust J&K. Digitized by eGangotri

उपरांत मखीर का पाणी मधु का कल्क पाय कर के देवे
और लोहितादि प्रतिपान मखीर पाय के पिलावे ८७ वा
यु के प्रस्कंद में लूण मधु सुरा मद पिलावे पित्त के विषे
मधु संग मनका रस खंड ८८ लोधर प्रियंगू मखीर
पद्म आसव मद भेद के साथ पिलावे कफ के विषे मधु
मखीर आसव के साथ पिलावे ८९ और मद लोधर सं
ग भलावे मखीर मुस्था हरीमद दिन के साथ पिलावे ९०
यव उदर विषे पंचक्षीरवृक्ष पिप्पल बोड रुंबल पलाक्षया

पिप्पलीकल्कसंयुक्तमथवदद्यात्मधूदकं लो
हिताद्यं प्रतिपानं मधुयुक्तं प्रदापयेत् ८७ प्र
स्कन्दे वातिके पानं लवणानि कणा सुरा पै
त्तिके पिप्पली संहितं मद्वीकारसं शर्करांवितं ८८
लोध्रप्रियंगवः सौद्रपायये दासवेन तु क
फजे पिप्पलीलौहं पाययेदासवेन तु ८९ क
फजे पिप्पलीलौहं संहितं भल्लातकं मधु प्रस
न्नया समायुक्तं सुरालेन सह पाययेत् ९० उद
रे त्वोदुम्बराणां कल्कपुत्रागानि कणानि च साधि
तं पाययेन्मानपानीयार्थं यथान्नं च ९१ एवं ग्री
ष्मशरदि वर्षासु पिबकारयेत् हेमंते शि
शिरे कर्यादभ्यंगस्वेदमेव च ९२ नतु ग्रीष्म
शरदीवा पीत्वा के वाप्ययोजयेत् वसंते दशमू
लसक्वाथं मधुकणायुतं ९३ हेमंते शिशि
रे पानमासवं पिप्पलीमधु ।

रस पिप्पल इनां के सिकर अरु कोमल पत्र इनां के सा ९१
थ सिद्ध करके जलपान वाले अन्न के अनुसार पिलावे
इसी तरा ग्रीष्म शरद वर्षा विषे करावे अरु हेमंत शिशि
रमें मालस सेक पसीना देके करे ९२ अरु पहे विधि ग्रीष्म
शरद ऋतु पेनक में ना करे वसंत ऋतु विषे दशमूल
का क्वाथ मखीर मधु के साथ पिलावे ९३ हेमंत शिशि
र विषे मखीर मधु के साथ आसव अरु के भेद पान देवे ।

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ अथवा दशमूलकाक्काथ यवक्षार तेल मिलायकर
हो॰ केपानपिलावे ९७ कैथकाफल मजीठके साथपी
१६७ सकरके अरु क्षारके चूर्णकसाथमिलाइकरकेदेव
शिशिरविषें प्रमाणकासिद्धकीयायोतेलहै घोडे
९७ कोपिलावे ९५ अथवारुधिरकडायहोइघोडेता
इकटुचूर्णपायकरके घेउसभरतनजोविषेंदेनेया
गहै अस्वचिकित्साकेजाननेवालेनेकहियाहै ९९

दशमूलकषायंवाक्षारतैलसमायुतं ९६
कपित्थमञ्जिष्ठक्षारचूर्णावचूर्णितं
शिशिरेपाययेद्दस्वंसिद्धंतैलमायया ९
अथवाकटुचूर्णेनसर्पिःस्यादवचूर्णितं ८.
विश्राविलायदानअस्वैघनकुंजाननता
श्वीद्वेवापरोद्धेवद्दयंवक्रामयेत्सदा ल
घुमृतस्यसलिलक्रमेणवदुवादनं ९८
इतिप्रस्कंदवि॰ प्रस्कंदीयस्तुरोगोलंगतिवि
ह्वलोपिदोषशोषण अतिभिन्नेरुपक्कृतित
स्यवामिथ्याप्रवारेण ९८ तस्याभ्यंगक
र्याकल्याहिष्टेनसंयवायेन स्वेदंवनतः।
सर्पिःक्टुरचर्णेयुतंचपानाय ९९ कुर्या
दकस्ताववहुप्राणात्मसराहदा विश्रांतवि
श्रांतेसतितपवेपयेत्नरंग १००
प्रातःकालसंध्यामेंघोडेकोसदाफेरे जवशरीरहोला
होवे तौजलपिलावे क्रमकरकेचासदाणादेवे इतिप्र
स्कंदवि॰ प्रस्कंदरोगवालाघोडाकफदोषकेशोषरहने
करकेलंगडाहोकेदुःखितयोहै सर्वकरकेउपाकरणते
वामिथ्याभोजनविहारकालनेउत्कटकरनेतें ९८ ति
सकोकल्पविषेंकरेया योसंयव सेर तेल तिसकेसाथ
मालसकरसेदसकदेवे औरकटुचूर्णकेसाथपानवाले
हनपिलावे ९९ ... कमयासनमेदिनविश्राम।

© Dharmartha Trust J&K. Digitized by eGangotri

देके निकाले पहिले स्निग्ध करके पीछे नाडी वेध करे
घोडे को १० जिसको रुधिर हूछी तरां निकाले होय तल
विषे पीडा होवे तिसको यो एवं तल लघित वाले घोडे यां
की चिकित्सा कहि है सो सभ करावे इति अजु स्कंद वि०
अब राजयक्ष्मा का लक्षण कहते हैं रूक्ष भोजन करने ते
और भोजन के पचने विना ऊपर ते होर भोजन करने ते
व्रत जाने ते अजीर्ण ते और यो एवं वायु के कोप के कार
ण कहे हैं इस घास के लेने वाले रक्त रोक लेना है तिस

अथास्य कामं तिक्तांतं पथ्यं कुर्यान्न लेहनं त
था पिकायो एवं कां क्रिया यान्न लेगिना १
इति अजु स्कंद वि० अथ रूक्षैर्ण हारै रूक्षस्या
ध्यशनैर्लंघनाज्जीर्णैः एवं कैर पुवातैः प्रकु
प्यते वायुरश्वस्य २ स रुणद्धि स्रोतांसि चरत्सा
विकंधानमज्जक्ष्यां च शोषयंति तत्सरोगः
नामः परिहीयते सततं ३ हीनस्वरजवं वर्णः
अश्रुसूक्षणोदरेक्षणः अश्व च्छायामभिलष
तिस दैवं मत्तिकाभिद्रुतो रहीनः ४ स भिर्लि
गैर्यो जो रुद्धत इति राजयक्ष्मणान्वेयः तस्य
तस्मात्साध्यां साध्यं उपेक्षा वाक्रियां कुर्यात् ५ आ
हारवान् दीनश्चापि मंत्रा विमूढ वान् कृशः
न स्यात्सोयक्ष्म भवेत्तस्य चिकित्सा भिषक्
कुर्यात् ६

में घोडे को सोष करवे ता है जिस्ता होजाता है और
स्वर वेग वर्ण बल घट जाता है अरु सो जाहोती है अउ
उदर अख्ती इनां विषे और छाया पे जातो यां हैं अरु स
तीयां वहते कृपा देती यां हैं तिस ले मांदा होजाता है ४
इनां लक्षणां करके घोडा राजयक्ष्म रोग युक्त जाने तिस
को साध्य असाध्य लक्षण जान के उपाय करे ५ जो भोजन
न खाता है उडानहि अरु सुरत यथार्थ है होर जिस्ता
वहत नहि और दमनहि तिसकी चिकित्सा वैद्य करावे ६

© Dharmartha Trust J&K. Digitized by eGangotri

भा. ष्टिका हरीड वहेडे आमले पत्रा इनों साथ वारुणी मदि
टी. रा पिलावे यवादिभक्ष्यपान्न विलेके मांसरसके साथ भो
११८ जनदेवे ७ इसेन आमले वावडिंग दंथ्यार भूरकणी हरी
ड इनोंका चूर्णकरके घेउ विषे रलायके वेघनम वारड
खावे घोडेको ८ वकरीका रुधिर घेउ मठा से थालूण
साथ पान हितकार है इसके पान करणेकरके राजयक्ष्म
वाला मनुष्य तिन दिन विषे घोडावलाकुरयुक्त होजाता है ९ म
ठा तिलाकी खल वा भुगा घेत मे थालूण खेउ युक्त चय

चित्रकत्रिफलैर्युक्तैः सघृतं वारुणि हितापाने
यकमांसरसै घृतयुक्तैर्भोजनं दद्यात् ७ आ
मलकविडंगानि शठ्यप्रपर्णी पिप्पली हरीत
कः चूर्णं कृत्वा नसघृतं भक्षेद्रोगयक्ष्मति
मान् ८ छागमांसपयः सर्पिर्दधिसैंधवसंयुतं हि
तं पाने समाहारं च निर्बलियक्ष्मा प्रतिकर्म
णा तेन ९ दधिकिराततैलसर्पिलवणोरविड
ग्धितैस्मरपाने पवारुवादद्यादकं घृतं स
तेनवास ९० दधिमस्तुलवणयुक्तं तिलोदनं भो
जनं हितं दद्यात् शालान्नभोजनं वा साजांगा
लं रूपपीसितै वा ११ निरूहं च स्निग्धदापयेय
क्ष्मिणः कदाचिदपि इष्टाग्रासादेयारक्तोद्य
मेव रूपस्य १२ इत्यात्रेयवैद्यगणकृतेराजय
क्ष्मचिकित्सा.

दिन वा पंजदिन घेउ तेल है वकरीका देवे घोडेको ९०
मरा अस्त्र दाउम लूण साथ तिलभत भोजनके साथहि
तेहै अथवा वासमतिका भत जांगलमृगपक्षी अथवा
नलके जीवके मासरसके साथ भोजनदेलावे ११ नि
रूहका थादि वस्ति पक्वका फिरावे राजयक्ष्मवालेको
वाक्षाका ग्रास देवे करके और यारलोग्य रूपकरे याहि
सो भुरवावे १२ इत्यात्रेयवैद्यगणकृते सिद्धयोगसं
ग्रहे राजयक्ष्मचिकित्सा.

© Dharmartha Trust J&K. Digitized by eGangotri

वायुकोपकरयरक्त होकर पित्तरक्तको कुपितकरके स
मस्तअंगोंको पीड़ा अरुनपाय देता है विशेषकरके श्रो
णितपरस्थान हृदयकोपीड़ाकरके ऊपरतेश्लेष्मको
पीड़ितकरता है इसप्रकार सन्निपातते व्यालकनामरो
गउत्पन्नहोता है १२ वातरक्तकेकोपतें सबभागमें यो
ड़ेकी पीड़ा होती है मूर्छा शुत्व उलटाकरके कंठकरके
वड़तकरलाता है अरु मासक्रांतदेह होजाता है १४ अ
रु हृदयविषेपीड़ितहोनेमें लमापयाहोयाकरलाता है

वायुः कपित्तः स्थानास्थितं रक्तंप्रकोपयित्वा
न सर्वांगानि विबाधानेतापयति विशेषा
नः श्रोणी हृदयं च पीडयित्वा तत्र हृदं पी
डनेश्लेष्मा एवं च सन्निपातेन जायते व्याल
कोव्याधि १२ मारुतशोणितकोपात्सर्वांगे
पीड़ितेहृद्यामूर्छेत व्यस्ताश्च भवेन्मासाक्र
नेथ्यकंठेनचास्पर्यं १४ हृदयेनपीडमानेप
रिकूजतिवैभृशंशयानस्य मंदत्वादतिपिव
तिसवलतिततोविह्वलः प्राणा १५ एतानिप
स्वरूपाणि मतितव्यालकविडंव्याधिं स्वादा
वाभ्यंगकर्पा क्षेपनतैलेन १६ भगमस्वेदं वा
ततस्तैलंतो इप्रसन्नयासहितं हृत्वा विप्रस्ट
तिविमिश्रव्यालिकेनेदापयेत्पानं १७ एवंवा
युः श्लेष्मारक्तं चैवोपशांपतिहृदयस्य पिष्ट्वाविषा
ग्लानिवपयमाकार्यः शिरोलेपः १८

वहुतवारंवार अरु थोड़ा जैसा खानपानकरता है अरु
व्याकुलहोकर डिगपरता है जिसघोड़ेकोइतनेप्रलक्ष
णहोंन सोव्यालकनामरोगवैद्यजाने तिसकोप्रादिविषे
कुष्ठतेलकेसाथ मालसकरावे १६ अरुभगस्वेदकरावे
फेरतेलमदीर मदिरेसाथपीनेताईदेवे मसूंकाचूर्ण
पायकरकें १७ इसप्रकारकरके वातकफरक्त घोड़ेकासम
होजाता है अरुकमलकेदलमपेडूगपसाथपीसके सिरके
ऊपरलेपकरावे १८

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ टी॰ १९९ बकरीका दूद तेल मज्जा डालचीनी इनांको पाय करके
दूधका दूद इसको पान करने वात रक्त कफ यह ल रोग वा
ले सभ समन होजाते है १९ तेल सेर दो चार सेर दूध पाव
दस सेर पाणि इकट्ठेसा सेर सेर मलौर चेउ २० वावडिंग
वच्च कौड इन्द्रदल दाल इन्द्रदल मज्जा मरच सोंठ त्रिफला स
रेयांसैन इनांका चूर्ण २१ इनांको कट्ठे कर इक भांडे पाय
कर सभनांको छोले इक्ठिनरमृथाणीकेसाथ उसने
पाम रवन निकले तिसका लेप चोड़े नाई भलोवे २२ फेर।

अजेन्द्रीरं तैलं क्षुरसोमसमन्त्रगां विपाचयेत्तेन
वातः श्लेष्मा रक्तं मालकिनः स्थपाश्यते पानात् १९
तैलस्यैकप्रस्थं हा वै वा यस्य दापयेत् यस्य सो तो
यस्य पंचमाग्राणि तत्र मधुमपि षोमात्रा २०
तत्रामि विडंग वचा चक्र इन्द्रद्रुमां हरिद्रे द्वे
रुषणा चित्रक मषपञ्चकानि च हरणोये न्मति
मात्र २१ पक्वी भूते स्थाल्यां मथ्येन च मथ्येयत्नाव
नस्मि त्रयं नवनीतं तत्र रंग परिलेपयेत्तेन २२
लितां तु मे य्यनेत्रतै नेवनर्पये च्चास्य ते ता भ्य
गो कार्यो वस्तिते नैव दातव्यः २३ तस्मिन् स्त
क्ते दग्धा स्थाति तिलमिश्र तांपाचयेद्यचाशैव
प्रशान्त राशिनेवेत देयं भोजनं प्रातः २४ उ
ह भूतो गच्छति यो रक्तेन ख लवायतेन दाचा
स्य मन्थाक्त शोधोरसाः पिरा स्नेवे मात्रा।
या वेद्याः २५
उसके साथ भी लोन पीण करे अरु माल स तिस
के साथ वस्तिपछ कारी देवे २३ अरु तिस विष छार
निल बलटोर में पाय कर यवागू सिद्ध करे सोप्रातका
ल विषं नेरने होइ तां ई भोजन वा स्ते देवे २४ भारा हो।
डेकी पीडा करने हे नवममा शल उरस छाति इनां की
या या त्रय नाडीया प्रमाणकीया वेद्यकरने योग्य हे २५

© Dharmartha Trust J&K. Digitized by eGangotri

हरदल दाल हरदल इनोंकों वकरीके दूधसाथ पीसके ९
वालकरोगकेनाशवास्ते वारंवारपानकेवास्तेदेवे २
कौड कानेकोजर मद्य संड चेउमवीरसाथदेवे अरुस्या
नतिसकों सदरवानवाला औररक्षासवास्ते खलकियां
डुवांदेणायोग्यहै इति बालचि० वायुकोपयुक्त होयके
अपनेस्थानतें चोडकेत्रिक अरुपिठविषेंस्थितहोके
रके चोडहडीयां नाडीयांकोपीडाकरताहै २८ इसप्रकार

हेत्वरजन्मोमिहितौ रिणाजेन वेसमाझके बाल
करोगविनाशाय दापयेत्रासकृत्पाने २९ तिका
मुस्ता: सहृतमाराधिकाविषमधुसमायुक्ता:
स्थानेप्रवातयुक्ते हृदंवायवेसप्रदातव्या २२ इति
बालचिकित्सा वायु:कुपित:स्थानात्तिष्ठतिरु
हैत्रिकेचवाहस्य संधीमन्तोनितरास्नायुधीपी
डयमासौ २८ एवंसपीडितोवैसौनोभिश्चेवस्तु
हातिन्तुरंग: नभेवद्राशोमसपोरिनेननुह्रिपीड
येत्सर्थं २९ स्थानेनलभतेसौख्यंरुजाकायोभवति
नेत्ररोगीवसंविशतिनथोत्तिष्ठतिमंदग्रासोत्र
त्यमश्वशकृत ३० एवंराजोहतविकारवान्तस्य
विधेतकर्म: प्रमाख्योयविकित्सांतथापिक्रि
ययाभिषकुर्यात ३१ तस्माद्दावभ्यंगंकुष्ठतैलेन
थायवनार परिमर्दनेवकुर्यात्स्निग्धमवयवे
सेनम ३२

घोडामोहव्याकुलहो
कोनहाडोंकेपीडनेतें
जाताहै निरंतरपीडाकरके सोदिनरातकवीसखीनहि
होता २९ किसीजगामेसखनहिलमता अरुदेहभारा
होताहै अस्थियोंकारोगहोताहै औरउठतावैठताहै
अरुग्रासथोडाखाताहै पच्छावलिदथोडीकरताहै ३०
इसप्रकार रात्रिहतविकारवालेकी चिकित्सानहिक।
हीकरणे वैद्यजनबादकर चिकित्साकरे योग्यस्नमेक
हिहै ३१ आदविषे कुठतेलमिठा युडनार इसकीमर्दना
करावे फेरस्निग्धकरके नाडीवधकोड देकरावे ३२

शा॰
हो॰
१००

२०

कंडेआरीवढ़ी यमाणीयांहोप ककड़शृंगी मूरकणी पला
हमोड़ेया रनाकाक्काथकरे प्राणीविच २२ कुठ पीलू तेल
पकावे सोतेलसैघने पानवस्ति नसवार मालसविषे देने
योग्यहै २३ और मद्यांकाकल्क मिलायकर मदिरापिला
वे तिसको अरुघोड़ेकोसदास्निग्धकरके पीछे वातके
हरनेवाली निरूहकाथकी वस्तिकराके वहिवाला २५
अग्निमंथ बिल्व मरवीर घोड़पाय पिलावे अरु भोजन रूक्ष
स्निग्धतरकरके लूणपायके घोड़ेको भोजन देवे २६ १

वातीकीटेववले शृंगिरनेनाचमेषशृंगीच अं
शुमती चपलाशस्त्रमोररेकाथ्ययसलिले २२ कु
ष्ठतैलपीलुवकल्ककृत्वा विपाचयेत्तस्मिन् दे
यपानेवस्तौ नस्ये चाभ्यंजने भिषग्जा २४ देयाप
नायमद्यामागधिकाकल्कसंयुक्तेन वास्य स्नि
ग्धस्य निरूहवातघ्नंदापयेन्मतिमान् २५ पाव
कमंथबिल्वश्रुतमथ सर्पिर्मिश्रितं प्रदातव्य स्व
स्निग्धलवणीकृतमसमस्तरोगस्य भोजनंदेयं २६
इतिनाड़ीरहतवि॰ वातादिकिनाश्रुताः श्लेष्माऊ
पिताशिरसम्भवस्य: तिष्टतिनासावंशोहयस्य।
नासाश्रितानितत: २७ अंशोस्यचवापीफाः अ
श्रूलमांसानिपीडयेतिभृशा पतनाद्भियातान्
हा अभिघातेनासिकावापि २८ दृषः शोणितं।
मिश्र: गुदावास प्रवर्ततेश्लेष्मा अभिभूतस्तथ
दोषैर्विरूपकंवानिवर्ततेसदारुणी २९ कफ्यि।
नोवानि अस्लस्वेनेवैविकारणं

सिराविरहतवि॰ वात रुधिर पित्तकफकुपित होकर ना
शिकाहाड़ उछलकर घोड़ेके नासावंशविषे स्थितयोनाडी है
तिनमें आमहोके वा हममें थूल सोज मासविषे पीड़ावरू
त होती है चोटलगणीतें नासामें भटहोके तिसतेपा।
कल्हरू फूट शोणितबगनाहै नासतें सोदोषोंकरके पीड़
त होके दुर्गंध चलती है २ नीलनलणवाला घोड़ाचूर्णी
रोगवालाकरियाहै २९ ... केव उ ... ते

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रासलेता है निर्बल लिस्सा अरु दिन दिन घटता है ४०
भोजन थोडा खाता है पानी भी थोडा पीता है कंठ विषे खे
दनें अरु विमन होकर स्थित रहता है तिसको नामका अ
दे चंद्रमा के प्रकार की न्याई चीरकरावे ४१ इहां केन खेके
साथ शस्त्र के साथना चीरे तिसको मासके सणी घूटके
रे अरु लोहे की सलाई तपाकर के तिस जगाको दग्ध क
रे फेर उस घाय को सूत्र के नाल सी देवे ४२ हरताल म
नसिला लाख हरदल इनांका चूर्ण घाय के ऊपर वरदेवे

कृष्णोच्छ्वासी दीनः कृशश्च परिहीयते सततं ४०
मंदं च पिबति खादति कंठेन वसतिष्ठमेनासततं
तस्यत्वनामा व्रणविपाटयेद् इंदुचंद्रनिभं ४१ अ
ग्नौ वितप्तशस्त्रेण शोधयेत्तरसा शमत्वंश लो
हशलाकादग्धं वसीवयेनंत्रणसूक्ष्मा ४२ हरि
तालशिलालाक्षास्तरोचनाचूर्णेन व्रणानांत
तैलंमृदुस्तरकल्केन पक्वमभ्यंजने श्रेष्ठं ४३
हरितालमधुकचंदनशीलाकालानुपारि
वालोध्रैः रजनीघृतसंयुक्तैर्लांगलीरेणसंपि
ष्टैः ४४ तैलंमहातिलानां पक्वेनस्मः ग्रणाम्य
तैवेतन्न सतपीणव्रणानामशेषभंनरोपणाश्च
ष्ठ ४५ कटुमूहाः लोहाकाः कुसलासर्पिपुतास्र
दानव्याः श्लेष्मस्य चूर्णितः पीर्षविरेका
कस्यकस्योक्तः ४६ इति चूर्णविधि·

अरुदेव घारे के कल्क साथ कोमल अग्निकर सिद्ध तैल
मलने वास्ते श्रेष्ठ गुण करे है ४३ हरताल मुलठ खेतचंद
न तेजवल काली वेल लोध्र हरदल दालहरदल पहेम
भवकुरी के उग्य साथ पीसके महातिलांका तेल में पा
यकर के पकावे इसको नमवार मे चूर्णि रोग हरहोजाता
है अरु घाउ को संतर्पन मकरता है शुद्ध करे है अपरफेडा
ता है ४५ त्रिकुट सुंगी मलोठ सिलाय मचाये उरलायदे
ने पीगपरे ये सम्य करके चूर्णि रोगवाले को याकल्प वि
धि तिसरो विरेचन करे याहे सोकरावे ४६ इति चूर्णविधि·

© Dharmartha Trust J&K. Digitized by eGangotri

भा० टी० २०१

201

योनासाविषेमोजनैहे अरुमुमेसी औरअंग्रेथीयांयोहे सो
सभटमकोपीडाकुरतेहै पहुसभनिश्चयकारगलूकक
हैहैन ४७ गलाकरागकारोकेगये खास जिसछोडके
सोवलताहोयावजनतखासलेताहै अरुमूर्छाहोतीहै
तेरलीआउतीहै आफराशहूघुमके अरुव्याकुलहोकरपृ
थ्वीऊपरगिडताहै औरकिलसावारंवार ४८ तिसगला
कीरोगवाले चोटूकाजानकरके चिकित्साछ्हणिकीक
हिहै सोसभकरावे नासाकेचोरणते सर्वलेकरके ४९

नासाश्चिनाश्चशोफाः अर्शोसिग्रंथयोपिवाये
स्युः वांयतेश्वासवयाश्चैतेस्वलगलूकाः प्रोक्ता :४७
गलूककण्ठश्वासोज्जननहृद्यः श्वसितिनाम्यति
खिन्नः आध्मायतेचभृशमोपतितनिभृशविह्वलः
कथ्यते ४४ नगरिकिनगरगलात्वाप्रतिके
मकारयेनत्र यच्चोक्तंखलछर्णिनाःपाटनप्र
वेनतनकपान ४९ निर्मलोनपदानौनगलको
शोधितानाभोस्पाना सछेणनजावानदानपि
नोवनपुरुषोः ५० इतिगलिकाचि० मतःपाने
नरयःसवलमानोवेपतेभृशखिन्नः रक्तंमूत्र
मेहतिदिशश्चमतनविलोकयति ५१ तस्य
तसीताःकार्याः परिशेकाः शीतलाः सर्वाः व
कामयेचमनकेजीर्णेपानेसखीभवति ५२
अपरेधःक्षीरैवःजीर्णेपानेप्रदापयेचास्य०

यवक्षेपगलूकप्रहुकीपनिर्मलहोजावण नरसूत्र
कीतनकेसाथ दोनोपासेनेसी देवे दोनोंको ५० इति
गलिकाचि० मदपानकरनेकरके नरमनछोडिगदा
है अरुकंवदा वहुनपरमाआउदा अरुलालरंगकाप
छावकरदाहै औरनिरंतरसभदिशाविषेदेखदाहै ५१
तिसकोसीतललेपस्नान औरसभठंडेकार्यकरणे अ
रुहोलिहोलिफेरणा यवपानपवजावे तवसोचाउग
नेडुग्धपिलावे तिसको औरसदाअरुपत्नीयोंके

© Dharmartha Trust J&K. Digitized by eGangotri

मासकेसाथभोजनमिठेखाणोकोदेवै इतिमद्यमन।
वि॰ सौहित्यलक्षिकरयोवलहै तिसकारकेयोमलहै
ग्रोत्रा तिसकेनेत्रलाल ग्ररलिंगकोउद्यायकेवहूनतहि
णकराहै ग्रौरलिदते पछावकोमागताहै ग्ररक्रोधके
रसभचोड्डेयांकोमारताहै योदेखताहै तिनांको ५४ कौ
उग्रतीस मूत्रा इलूयव सेंठ इनांकोमदिराकेसाथ तिस
की इन्द्रियाके मदकेनाशवास्तेपानवैद्यपिलावे ५५ हर
दल दालहरदल वटलवेल रेठा ऊठ मुनका इनांका।

मृगपक्षिणांलमधुरै:मांसरसैभोजनंदद्यात् ५३
इतिमद्यमनवि॰ सौहित्याद्दलमनरकेमूत्र
मूत्रीयहेषतेमर्थं विसृजतिमूत्रलेंडप्रमन्था।
नाड्येकोपान् ५४ कटुकातिविषाक्रैणाश
क्रयवाभृंगवरमधुको मरयापानंदेयंतस्ये
न्द्रियनाशनंभिषज्ञा ५५ हेनरजन्योपाठाक
फरूहेमधुरसाग्रनकाथं गोमूत्रेणकाथक
ल्कपानायदातव्य ५६ त्रिफलाक्काथनिंववि
पक्कमुद्गान्मधुविश्वपिप्पलीभूकान् पाना
यगवामूत्रंदद्यात्त्यक्तानिपानानि ५७ इ
तिवलमनवि॰ शास्त्रनिषिद्धस्यानेवडूस्ता
सितस्यभीतस्यसंत्रासुजतिविनाशं तनोत्र
हेणाभिभूयतोस्याउन्मत्तोवाजीवोदति।
जिहोष्ठवाहूकरुलीव ५८

काथकरेगोमूत्रकेसाथ परेहकाथवाकल्कपानके।
वास्तेदेणायोगहै ५६ हाउ वहेडा ग्रामला इनांकाका
थ ग्ररनिंवकेरसमेंमूंगीकोरिनके मस्तीर संठ मघो
इनांकेसाथखाणेकोदेवे पानवास्तेगोमूत्रदेवे ग्रौर
योनिमपानकरेहै सोदेव ५७ इतिवलमनवि॰ योशास्त्र
विषेनिषिद्धपानकरेहैयाहै तिसविषेवड्नेकरकेडरे
होयवौडेका पहेलत्रणहोतेहैं सरननाशहोजातीहै ग्र
रुग्रहोकरके तिरहरकोप्राप्तहोकरमस्तहोयाराजिहा
ऊंठ ऊंलि इनांकाचकमारताहै ५८

शा॰ समजीवांकोंडरानाहै प्रकवडताहै प्रतीलाल पडे ८९
हो॰ रोगवडाकठिनहै इसकीचिकित्साकोईनहिंकरसकदा
नइवीदोषोंकेसमकरणेवास्ते तिनोंकीचिकित्साकरु
२०२ ताहां वोडकों पकेवृथनाकेसाथ हड्डीतरासारेपासेते
रोककरके रुधिरकोमलाईवेउयत्नकरकेपावेतिसको ९०
202 हिंग मछकेले मंचा केलाजड वचे समभाग करकेप
छावसाथपीसके नसवारदेवे ९१ हरताल मनशिला
गुग्गुल चोरुग्रा ऊठ हरीड छडगुडी वचे पडेसमभस्मरि।

नासयति सर्वमसांस्त्रभक्ष्येचापि रक्ताहः दा
रुणापृथविकारोन चिकित्सा चस्य शक्यते कर्तुं ८९
दोषाणांशमनार्थं प्रतिकर्म तथापि वक्ष्यामि ते
वपनेसृक्समुद्धृतैर्वधासवीवक्रमयशुक्ता ९०
ने श्रीजनन्तकृधिरेण कारयेद्यत्नतश्चास्य हिंगु
करंजस्य फलंकुसाकवलीवचासमांसानि ९१
पिष्टानिवस्तमत्रेणानेन नस्यात्रु भेषानि ह
रितालशिलागुग्गुलचोरककुष्टानि हन्तनाके श
जटिलावसमैरेभिः पिष्टासर्पिः पचेद्धिमान् न
स्यात्रानपानेश्वेरयमनेनाश्रुतर्पणावेतन्न ९१
यद्येवं नस्याद्वीर्यस्या चदग्निकर्मनिक्रूचीन ९४
इति उन्मतचि॰ एवं नाभिनालकस्याद्रवति चर
काश्ववाजिनोकष्टे एवंवतःप्रकारेतस्याचिकि
त्साप्रवक्ष्यामि ९१ वातिकेमरुडमेस्पर्शोकठि
नपरिलीयते॰

नोंकरके चोडपकावे वतरवेद्य इसचूनको नसवार
सलाई ग्रहस्थलीमेंतपेण इसकेसाथकरावे ९३ य
द इसकरकेराजीनाहोवे तो फेर अग्निकर्मदाघदेवे
९४ इतिउन्मादचिकित्सा चोडयाकों वात पित क
फ रक्त इनोंकरके कोडवारप्रकारकाहोताहै तिस
कीचिकित्साकरतेहां ९५ योवाधकरहै सोस्या।
शीविषकोमलकरइहोकर मर्देकोंनयहोताहै यो

© Dharmartha Trust J&K. Digitized by eGangotri

एवं के अर्द्ध भाग विषें नमें है अरु पिछले अर्द्ध भाग में कर
रयो है ९५ यो वायु कर रूढ है सो जब मर्म स्थान विषें न
हि है अरु उपद्रव ने जो रहित है सो साध्य सरलेकार हो जा
ता है यो पित्त का है सो दाहकार है अरु प्रगट होता है फिसला
ता है ९७ न चापक जानौ है और कालातल हूव गदा है यो श्लेष्म
का रूढ है सो प्रगट प्रतीत न हि होता अरु देखने विषें भाग प्र
तीत होता है ९८ चिरकाल कर के उठता है अरु पकता न हि
गर्मे हूआ उबीन हि पीड वीन हि जैदी यो रूढ यह शूल अरु

ऽरुक्शूनेन च वर्षी रूपता है कठिनो वतन ९९ भवेत्सा
ध्यमर्मस्थवातिको निरुपद्रवं पैत्तिकं दह्यते ऊ
ष्मा नमात्रेणाभिद्यते ९७ न चैव पाकमाप्नोति कु
लोमवतिशोणितं अव्यथे श्लेष्मणा रूढं भवेच्च
गुरुदर्शने ९८ चिरोत्थानमपाकं च निरुक्पागन
वेदनं श्लेष्मजे साध्यमेवं स्यादनशूलमपद्रवं ९
रक्तजं शोणितं चापि समानं पैत्तिकेन तु यो यः
स्नायुसिरायाश्च मर्मसेचिपि वाभिद्यते १० असा
ध्यः सन्न विज्ञेयाः समंतात्स्फुरितच्छविः प्राण
सारेण वा हीनो वयस्यो बलवांश्च यः ११ निरु
पद्रवो ल्परुक्शोन प्रभिन्नोल्पकेदुरः स साध्यस्त
स्य कर्म देवस्ते समनाश्च यः १२ अरिष्टकृत्तानत
हतात्पिप्पली शृंगबेरकान् त्रिफला चूर्णसंयुक्ता
न्भोजयेद्धृतसंयुतान् १३

उपद्रव ने रहित होवे तो साध्य होता है ९९ रक्त ने यो है तिस
विषें रुधिर वगता है और पित्त रूढ के लक्षण समजाणे
जिस जोउ के स्नायु नाडी शिरा नाडी मर्म स्थान संधी यां वि
षे भेद पीड होवे सो असाध्य जाने अरु यो फिर पास ते प्रगट
प्रकाश युक्त छवि होवे अरु देह बल घटे या ना होवे उड़ना
होवे बल युक्त होवे और उपद्रवों ने रहित होवे पीडा थोरी
अरु फूटे या ना होवे थोरक थोडी होवे सो साध्य कहे या है
तिस का उपाय प्रसन्न मन होके करना है १२ तिवसाय सि
हत पिपली गी धाचन मझो आदक त्रिफला चि रनो के साथ भो
जन खाने को देवे १३

शा. आदि विषे पकके सजि नगर मोरयां इनांको करके मले अ
हे. थवा हरडेम पुआं ते हरदल करके मर्दन करे १४ और
२०३ मघां सेउ साथ करे वावडिंग नागर मोथा इनांको उकले
विषे कूट करके गोमूत्र के साथ पीस के मखीर मघां रला
यके तिस नाई पान देवे और गो का मूत्र बकरी का हाथी
का महीका हरदल लाल हरदल १६ हेडेवांके बीज वि
ना वावडिंग देवदार करन्ज मछकेला लूण पंज इनांको
पीस के सम कठे करे फेर उपचार दिन धूपे रख के तपावे

अक्षुयिना ततः संवे सर्जिकानागरेण च सर्षपैः
मेदये ह्यापि गृहस्य महारिष्टया: १४ पिप्पली
शृंगवेरं च विडंगं भद्रमुस्तकं उलूखले तोदये
न्गवा मूत्रेण पेषयेत् १५ मधुपिप्पल संयु
क्तं पानमस्मै प्रदापयेत् गोमूत्रमजामूत्रं गज
मूत्रं माहिषं हरिद्रे च १६ प्रपुन्नाटबीजं चित्रकं
विडंग सुरदारु च करञ्जः लवणानि पंच पिण्डी
मेलयित्वा सर्वमेकत्र १७ त्रीणि सप्त समेतं अहं
ग्रहं रत्नतः प्रदेहन्त्र प्रदिग्धो हि निःसान्यकं ज
लं तमवगाहयेत् १८ प्रातः पिष्टं मन्त्रसृष्टं श
कुष्ठविनाशनं नातीनका हुन्निवाकेपत्राणि
कृमिशत्रु च १९ करंजस्य हिङ्गा चैव शृंगवेरं
मरिचं तेनेव वनी चित्रकं च गवां मूत्रेण पेषयेत्
उष्णेन वर्षणे च सदा कृष्यादितस्मिन्त सौरस
पिंडपानाय सारिष्टं च भोजनं २०

फेर उसके साथ लेप करे फेर मल करके जल विषे स्नान
नाही करावे १८ फेर दिने धूपा विषे नम करे तो निश्चय
कर कुष्ठ का नाश करता है मालती मछकेलाण निंब
के पत्र वावडिंग १९ मछकेले थोर सेउ तेजबल
चित्रा गोमूत्र साथ पीसके २० इसके साथ बुटना अरु
उस दा मले सा वथान होक और उपचारे उपीणा को देवे और
हरदल साथ भोजन खवावे २१

© Dharmartha Trust J&K. Digitized by eGangotri

मदिरा क्षार यवक्षार तेल घृत इनों का प्रदेह लेप चम
डावाल रोम पसम वर्ण रंग इनांको करता है ८२ इति कु
ष्ठचि० जिसकीन त्वाविषेंड छ रुधिर होकर के फैलदा है
तिसको दद्रु यामा खोऊ दर्पा पित्त होते हैं ८३ एकसतार
परिसर्प किनास चित्र दद्रु पहे पंचकफ पित्तते सारे दे
ह विषे होते है ८४ सो के स्तान गात्र कोष्ठ इनांको दुख
केदा है और जब दोषकी उत्पत्ति होने के वेले त्वचा विषय

स्वक्षारांश्च तैलं च घृतं चैतत्प्रदेहनं रोमत्वग्
वालवर्णानि सर्वमेतत्प्रदापयेत् ८२ इति कु
ष्ठचि० अथ यस्य त्वसृङ्मांसं विसर्पति शोणितं
तस्य दद्रुश्च पामा च देशाः पित्तज्जायते ८३ स
तारुः परिसर्पश्च किनासश्चित्रमेव च दद्रुवः स
र्वगात्रेषु भवन्ति कफपित्तजाः ८४ स्तनः केशा
न् गात्राणि कटिकोष्ठं प्रदूषयन्ति त्वचि दोषाद्
मेनास्य मण्डलानि क्वचित्क्वचित् ८५ भवन्ति नी
लनेत्राणि पिटकानि बहूनि च आदौ विस्राव
णेन तं धाराशिराभिः प्रच्छनेन च ८६ पञ्चक्षारं वी
ज विरेक सिंधूत्थं करंज बीज निर्गुण्डः हेतरा
ने लोमश मना विडंग मूंढी हरीतकी ८७ पि
चुमर्दक विभीतक सर्जिका भिक्षा मेघजः सर्व
पिष्टे गोमूत्रेणानु कल्कं कुर्यान्मुभेमाडे ८८
एकांति शांपर्युषितेन कुर्यात् लेपयहतेन
केहयस्य ०

रफड किसी किसी स्थान विषे होते हैं ८५ और नील रंग
वालीयां फिंगुणीयां बहुत होतियां हैं न पहले तिनां
कानाडी कारलहू कडे अथवा पछकरा के रुधिर निका
ले ८६ हेडमा के बीज चित्रा सैंधा लूण मळके लेवणा
हादल हाल हरादल मालतीपत्र वावडिंग मंडु हरीड ८७
निंव एक वहेडे सज्जि इनां सममनां को गोमूत्र के साथ पीस
कर कल्क बनाय एक रात्र अंदर भांडे विषे राखे यवके रावे

© Dharmartha Trust J&K. Digitized by eGangotri

भा०
टी०
२०४

तवत्थोडेकों इसकालेप और मर्दनकरै दोसेरभलावे कटक
रके दोसेरतेल विषे तिनोंकोपकावै ९७ फेर पहलेबुटणा
मलेहोए थोडेको पीछेतैं इसतैलसाथ मालिसकरावै तव
थोडेकों दद्रीखरक पामा कंडु और सभतरांके कुष्टनाश।
होयातेहैन ९८ निंब मछुकेलण राडा मजीठ मरेयां म
या पंगोष्टल मद्दाकी सलारि दारुहरदल इनांकोंगोमूत्र।
साथ पीसकेलेपकरनेतें दद्रीको नाशकरताहै ९९ हरड

हराणांच भल्लातकप्रस्थमेकं प्रस्थंतैलस्य पा।
चेत्तत्त ९७ एवंसमुद्धृतिनकस्यपश्चादभ्यंज।
नेतैलमिदंप्रयोज्यं दद्रुश्वकंडुश्च तथैवपामाकुष्टा
निसर्वाणिच यातिनाश ९८ निंबकरंजमदनैःस।
मंगामिद्धार्थकैर्भागयिकायवक्ष स्यात्छलकी।
विडुगवांचमूत्रैःपिष्टैःप्रलेपेननिहंतिदद्रु ९९
त्रिफलाचित्रकंदंतीहरिद्राभद्रमुस्तकं विडंगंच
गवैरवप्रपुन्नाटफलानिच ९२ गवांमूत्रश्रुतं।
कल्कंदशशात्रिस्थितस्त्वतं पानायदद्यात्सर्वाद्रु
नाशःस्निग्धस्यसम्यग्माः ९३ कुष्टाध्यायेपिय।
त्प्रोक्तंतद्दिहापिवकारयेत् ९४ इतिदद्रुवि०
व्रणाभवंतिप्रक्लिन्नाःस्रावोभवतिपीतिकाः
यस्मिन्सिंचतिरोमाणिवालाःकेशालघ्यवच ९५
दंतैर्दंष्टैतियच्छात्रव्रणास्तत्रोपजायते०

चीहडे आमले चित्रा दंदुलदानेकीजड हरदल नागर मो
था मणर बायविडंग सेडु हेडमाकेवीज ९२ इनांकोगोमू
त्रसाथ जगदावनायकरके दशरात्रिस्थिनरखके फेरघुण
के प्रातकाल विषे रयनालीपिलावे पहिलेमध्यममात्राकरि
के ९३ औरयोकुष्टाध्यायविषे चिकित्साकहिहै सोसभ
इसविषेकरावे ९४ इतिदद्रुचि० जिसविषेघायवणणावा
लेहोन अरुपीलारसभगे अरुजिसकेरोमवालकेश फ
इपेण अरुदंदोंकेसाथदरकों छेकेंदेहैं तिसतेघाय
होजातेहैं औरपिंडेकेउपर अफरपडजातेहैं अरुचमडे

© Dharmartha Trust J&K. Digitized by eGangotri

विषं जलवगनाहै यजपहेलतलण होण तोयामाकेंड।
जाण तिसकी येचिकित्साकहिहै सोकरे येनाडीपामा
केपासहै तिसकी स्रावकर्थिरनिकाले औरकाडीकीत्व
चामें षट्कोष्ट इनोकी यानाडीयों विषेवेपकरावे ९७ म
वो वावडिंग हरडल सुंठ अतीस टाटर खैरसार ९८ इनोकेस
विरेसाय प्रातसमें विषं हर्थिरकेनिकालहोय होउनाई
पिलावे ९९ मेती सरियां तिल खेल चित्रा सुंठ परे समभव

मेदुलालिनगात्रस्य वणस्रावस्य जायते ९६
पवेयामात्रविज्ञेयात तस्याकर्मद्समाचरेत वि
स्रावणेन तस्याः पामाभ्यासेन यासिराभवति ८०
मस्यायां तत्र षट्कोष्टे पिचयासिराव्यधः
कुष्ठाविडंगरजनीविषानिविषाकटंनेटी
शीरे ९७ मध्वासवेन पानं स्वीक्रस्कुकर्थि
रस्य सितसर्षपकिणवतिलैः खित्रकमहोष
यसहितेस्य ९९ पिष्टैर्गोमूत्रयुतैः कथितैः प
रिमर्दयेदथ १०० कुष्ठविडंगकरवीरमूलपा
ठाहरिद्रास्वफलानि दंती विंबीवरकासित
सर्षपास्वजने नोअतीचानि विषाफकीव १
त्रिवृतीनयेवाकेकरंजको वसमजिकाम्फोत
विषाणिकाच कुस्यावसकावकणवृवाच
पलानि गोमूत्रयुतानि पिष्टा २ तैलेपवेत्स
षपजेविधितोप्रभंजनानतकाठिनानिपामा।

संकोगोमूत्रकेसाथपीसके काढलेवे फेरउसकीम
दैनचौडेकोकरावे १०० कुठ वायविडंग गडीलेकीजड
वटलवेल केडेआरी केडआरा त्रिफला दंदणदाने
कीजड कडूरी सरियां छोत अकुलाल नेजवेल अती
स टेगर १ थार अक्क मक्केकेले दुत करेनु मनी काति
वेल मेफ्राफूगी मचो कोड वारण वचे इनोकोगोमूत्र
केसाथपीसकरके २ इनोसाथविधिके जानने वाला
सरियांकातेलसिद्धकरे इसकीमालसकरणेते

© Dharmartha Trust J&K. Digitized by eGangotri

कमिन कंडू दद्रौ इनांको सतावी दूरकरतीहै ३ निंवपत्र
पटोलपत्र मंझा सलरीकेपत्र कुठ हरदल दालहरदल
लूणपत्र दिसार मरिच गलो हरडु वहेडा आमले १
नांकाकाथवनाय वैघणीतलकरके पीणेको देवे यो
डेयांताई तिसते कंडु पामा वर्ण विछति और सभ प्र
कारके कोड़ पसभ नाश होजाते हैं ५ चित्रकेपत्र वाडी
लेकेपत्र कंरज मक्के लणकेपत्र हेत करन्जकेपत्र इनां

दंडूवकंडूवनिहंति सद्यः पत्राणि निंवस्य प
टोलपत्रं १ कुमाचपत्राणपथ शल्पकीनांकु
ष्ठं हरिद्रे लवणानि चैव स्याद्रूकाष्टमरिच
गडूचीसर्वाणि युक्तानि फलत्रयेण ४ कषा
यः कथितः सुसीतः पानाय देयो भिषजा हये
भ्यः कंडूवयामा चविवर्णनाच कुष्ठानि सर्वा
णि च यांति नाशं ५ चित्रकस्य च पत्राणि कर
वीरस्य चोभयोः पत्रान्यथ कंरजस्य ह्रष्टं तत्र
योजयेत ६ एतै स्तु सम भागै स्तु तैलं पीतं वि
पाचयेत् तेनैव सवै सभ्यस्य तथा सलभते सु
खं ७ इतिपामाचि. गृध्रयः कौलमात्रा स्त्रशो
का यस्योपजायते दंते खोदति गात्राणि कं
डूते स्वानि षीदति ८ सद्देसपितंसप्तको विठ
यस तुपाचरेत तिल सर्षप कुष्ठानि निशासजि
कोगोमाहूत्रूमे: पिष्टैः ९

कोषिलाके

इपरपीस
लेवे इनांसभनांकेवरावर तेलपकावे बुद्दिमान तिस
केसाथमलिसकरनेकरके घोडासुखकोलभताहै ७
इतिपामाचि. घोडेकोंवेरीकेवरावरगंडेहोतियाहैं
तिनांकरकेषाज होजाती है अरुदंदोंकरके पिंडकोंच
डताहै अरुअंगकेसाथपीडितहोकर वैठताहै तिसको
पितसंदग्ध जाणे उसकाउपायकरे ८ तिल सरयों
कुठ हरदल सजी इनांको गोके गोहेदेरसके वे
पीसकरके अरु गोमूत्रसाथलेपकरे ॥

© Dharmartha Trust J&K. Digitized by eGangotri

वहूनवारमर्दनकेरछोडेको १० रसमाद्यरेदा सैंधा
लूण खेलतिल हरदल दालहरदल हैंउग्रादेवीज
सरेयांसनी भांगरा सेंउ दिग्रार इनाको गोमूत्रकेसा
थ लेपकरावे वैद्य ११ कुठ मछकेलण त्रिफला वाव
डिंग वटलवेल हरदल दालहरदल कौर वर्च दंदण १
दाणेकीजउ लवी चित्रा सेंउ इनावस्तूवरावरलेउसि
हकेर जलनाजावे पकेतोउतारलेवे प्रातकालग्रोर

गोमूत्रयुतैर्लिप्तंवहुरूणाःपरिमर्दयेदथ १०
आगारधूमलवणमंकिण्वतिलाहरिद्रेप्रप
नाटवीजमिद्धार्थकामार्कवविडंगशाकगोमू
त्रयुक्तमलमेवमुदहृ ११ कुष्ठकरंजत्रिफला
विडंगपाठारजनीकटुकावचाव दंतिलद्दृ
द्धिमहौषधानिपभिल्लसर्पिर्विपचेत्समा
सैः १२ नोपद्रवंयदासिद्धं तदेवमवतारये
त् पूर्वाह्णेवापराह्णेवापानमेतत्प्रदापयेत् १
ह्यहेवैवत्र्यहेवापिपाययेत्सर्जिकायुतं गा
वामूत्रेणवपुनद्दृतंपानाय दापयेत् १४ वि
डंगानिकरंजानिगवांमूत्रेणपेषयेत् पिष्ट्वा
समर्दनेकार्यं दद्रूणांशमनेपरं १५ हर्वी
वयवसंदद्यात्सर्वातेष्वापनानिव १६ इति
दशापितवि॰ ग्रंथयोवहवोमूत्रामरुजाः प्र
सवंतिये नासिकारुधिरवापियदिवाप्ययशो
णिते १७
सायंकालदेवे ११ दोदिनवा त्रेदिन सज्जीकेसाथपि
लावे फेरगोमूत्रकेसाथ धृतपीनेकोदेवे १४ वावडिंग
मछकेलन गोमूत्रसाथपीसकरमर्दनकरे अरुहुग्य।
साथकरे तोपरमरोगशमनहै १५ छायकेवालेतृ
वोदेवे अरुरसयानवायुवालेथ्यार वनावे १६ इतिदशापि
तवि॰ वहूतगंडीहोकरके पीडावहुत वगणेवालीयां
येहैन अरुनासाते लहूवा पाक अथभगंदरके १७

© Dharmartha Trust J&K. Digitized by eGangotri

भा० यदसर्पीकेरे नवस्रावकावगनीयांहैं नवपचजाती
टी० है १८ येपाककेयुक्त ग्रहदाहकरके सारेदेहमें झेजावे
२०६ तिसको परिसर्पजाणे योश्वित्रनामकुष्ठवाएकरकेहै
सोलालरंगकाहोताहै ग्रहकाला वा चिटा कालेरंगका
206 होवेसोपित्तकाहै १९ योश्लेष्मकरहै सोश्वेतवर्णकाहै
कंडूयुक्तयोहै संरभपीडाविशेष ग्रहस्निग्धावी सोउष्णा
सोकपालग्रथवाग्रौरहै २० येदेकुष्टसाध्यहै तिनका।

यथस्सर्पीतिचास्त्रावाग्लदेवासग्रपथ्यते विं
यादपिवकुंडूंतयान्येवुविनिर्दिशेत १८ स
पापैः सपरीदाहैः परिसर्पन्तंतेविदुः श्वित्रं
वातात्मकं रंकं कुसएपावचपैत्तिकं १९ स्तेयं
स्रेष्मात्मकं श्वेतं कंडूरंचैववयद्भवेत् संरंभा
त्मरहसोन्याचकपालमथवापरं २० साध्यानि
यानिकुष्ठानितेषांमृणुचिकित्सितं रक्तस्रा
वश्चस्रवौकाःपानान्युन्मर्दनानिच २१ करवीर
पीलजातिकरंजार्ककेशीपहलवाकुष्ठे हेवरि
देनिंवप्रपुन्नाटेलापटोलानि २२ प्रतिविषा
चित्रकमरिचंतेसुवकसंचूर्णकारयेतकल्कं चि
ष्ठत्पालेपोयंकेदुकुष्ठापहःप्रोक्तः २३ कटु
फलकलस्यसेदोषिधाणिकाधावनीचकुं
पीसकरवीरमलचित्रकदंतीप्रपुन्नाटवी
जानि २४

चिकित्सामृणु
परिलेहधिरकढावे
केरपानमर्दनकरावे २१ गंडीला पील मालती कोग
रअर्कसरलपत्र कुष्ठ हरदल हालहरद्रल निंब हेडमा
लाचीयां परवलपत्र २२ प्रतीस चित्रा इनोकासकायचू
र्णकेरफरकल्कबनाय कुष्ठस्थानको छोरडकेलेपक
रे तोकेरू ग्रहकोडवेनाशकरकेदेयाहै २३ कायफल
कलम्य सेर मेढासिंगी कंडेआरिकाहि गंडीलेकीजड
चित्रा दंदरणासतीकीनर हेडमावीज २४

© Dharmartha Trust J&K. Digitized by eGangotri

वन मल्लीका वा कुरमाल हरदल दालहरदल नमेकी जड
मघा लांगली दंती भेद कंडयारी या दो त्रिफला इनोंकर
के सरसोंकेतेलको २५ अष्टगुणगोमूत्रपायकरकेपका
वे इसतेलकी चोउदयोकोमालसकरावे तोकुष्टदद्रीस्वित्र
सर्षपपामा कंडू इनोंकोनाशकरताहै २६ चित्रा वावडिंग
सरसों हरदल दालहरदल कुठ सज्जी सोंठ हेउमा त्रिकुटा
निंवरू मूली कंडोलोकेवीज २७ मदिरा दंदणदाणेकीजड

आस्फोतारजनीद्वयगवाक्षीदंतीपिप्पलीविशल्या
च बृहतीद्वयफलत्रिकैरेभिस्तैलं तु सर्षपजं २५
गोमूत्रेणाष्टगुणेन पक्वमभ्यंगमेतदपाभ्या ह
न्यात्कुष्टदद्रुश्वित्रविसर्पपामा २६ चित्रका
विडंगसर्षपरजनीद्वयकुष्टसर्जिकाविश्वैः सप
त्रारटककरकतेवरुमूलककोशातकीबीजैः २७
हलादंतीमरीचैरगवादनीहिंगुशिग्रुकाश्वेव
लांगलिकाकणाविश्वकणागृहधूमसमानाद्धूस
हितैश्च २८ एभिकर्षैकभागैर्वसार्यपलमंयुते
सुपिष्टैस्तु पूर्वेकतीरविमिश्रैस्तथास्नुहीक्षीरस
युक्तैः २९ मूत्रेणैवहूशः सुभाविते: कारयेल्ल
लेपांस्तु पतैनेववविपक्वंकटुतैलं प्रशस्तमभ्यंगे १०
पाययेत्कटुकैः सर्पिः शुद्धीनैवीप्यवहूर्णेन
पुरीषभिद्यतेयावत्तावन्मात्रंप्रदापयेत् ३१

मदिरा विवडदीजड हिंग. सहोजना रेमण लांगल विष
मास्नीफुल जीरा संठ मघा धमाचारदा सोफ एदे सभलो
ला २ विष मोरा दातोले और अकके दुधसाथपीसे और
थोरकेदुधसाथपीसे २९ फेरवककीकेमूत्रकरकेवहुत
वारभावनादेके लेपकरावे अरु इसीवस्तकेसाथ कौडा
तेलसिद्धकरके मालसकेवा लेवहुतगुणकरहै ३० अ
रुकटुचूर्णकेसाथ वेउपिलावे अथवाकटुचूर्णदेवे जि
तनाविरलिटकोभित्रकरे इतनाचिरदेवे ३१

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
श्लो॰
२०७

207

अरु निरंतर तिसको वमन संगी देवे और त्वचा मसकाला देवे
यो रुधिर दुष्ट विकृत होकर त्वचा विषैं स्थित होवे सो पम
हा विष वाले के बराबर जाणं ३२ पराक्रम अरु वीर्य ते पाक
तें भी विषके सम कहते हैं तिसकारणते तिसको विषकी
भाईं हरकरे ३३ तिनों को तीक्ष्ण अरु विषके नाशकरनेवाले अ
रु मूत्र रेचना करके शोधन करणे योग्य है तिन्होंको शीतल
अरु मधुर क्रिया चिकित्सा हरती नहीं ३४ कहिया है अग्नि
की अग्नि औषधी अरु विषकी विष औषध है तिसकारणते

अभीष्णं तिक्तमूत्राणि अग्निक्वाथं सेवदापयेत् रक्तं
च विगतं दुष्टमारी विषविनोपम ३२ वीर्येण च
विपाकाभ्यां तुल्यमाहुर्मनीषिणः तस्यैवं सदु।
ष्टस्य विषस्येव निवारणं ३३ कार्यं तीक्ष्णं विष
घ्नैश्च मूत्रैश्च परिशोधनं नहि तेषां क्रिया शीता
मधुरा वा प्रशस्यते ३४ अग्निरग्नेस्तु भेषजं विष
स्य विषमौषधं तस्मात्तारैश्च मूत्रैश्च न विषस्य
निवारणं ३५ रक्तेच विगते दुष्टे शीतानि मधुरा
णिच पानखादनभोज्यानि सेवमन्नं विवर्जये
त ३६ शालीहोत्रेण याः प्रोक्ता यावगर्गेण भाषि १७
ता त्वग्दोषिणां क्रिया कृत्स्ना समासेन प्रकीर्तिता
३७ इति श्री वैद्यगणकृते सिद्धयोगसंग्रहे त्वग्दोषाध्या
यः त्वग्दोषिणां क्रिया प्रोक्ता योपकारा मधुनाश्रुण १८
वाताजस्र दुमस्यांशः शीतो नात्यामो विसीयते चोस्य

तार अरु मूत्र साध्य त्वचा के रोग हैं तिनों को हरता है ३१ दुष्ट रु
धिरके हरहोणे ते करशीतल मधुर पान भोजन खावण पा
हिये हैं अरु अग्नि संसर्ग को त्यागे ३६ यो क्रिया चिकित्सा त्व
चा के दोषों की शालिहोत्र ने अरु गर्ग ने कहिया है सो सभ
चिकित्सा गणवैद्य शास्त्र के जानने वाले ने संग्रह विषैं क
हिया है ३७ इति गणकृते सिद्धयोगसंग्रहे त्वग्दोषाध्यायः
त्वचा के रोगों की चिकित्सा करी है अब सो जे को सुण या
पो पूर्वा एककरके है सो सर्वविधिकोमतले है अरु ठंडा है अ
रु गर्मी करके लय का हरजाता है ३८

© Dharmartha Trust J&K. Digitized by eGangotri

योपित्तकरसोजाहै सोस्पर्शकोंनहिंसहारदा अरुपके
जाताहै पीडावहुत अरुस्पर्शविषेंगर्म अरुयोकफकरहै
सोकरडा भारा हूणा औरथोडीपीडा औरठंडास्पर्शमें यो
रक्तकरहै सोवहुतलाल अरुपीडाकरयुक्त योसतावो
पकजाताहै ३९ अरुसभदोषोंकेलक्षणवालायोहै सो
सन्निपातकरकेकहेयाहै ४० योआगंतकशोथहै
सोपित्तसोथकेसमलक्षणवालाहै यहेछेप्रकारकेसो
जेहोतेहैं अबइनांकाउपायसुणो ४१ आदविषेंइनांको

पित्तात्स्पर्शंहेषीपाकीवहुवेदनाचोसा: क
ठिनोगुरुर्गंभीराकफोऽवेगमंदवेदन:शीत: ३९
रक्ताच्चमहातृक्त:सवेदन:त्रिप्रपाकीच य:
सर्वदोषलिंगैर्युक्त:सतत्सन्निपातिक:प्रोक्त: ४०
आगंतकश्चशोथोविज्ञेय:पैत्तिकेनसम: ए
वंएवलर्वेरःशोफाजायंतेष्टएउविकित्सितंते
षां ४१ ऊर्ध्वाधःशुद्धिरमादौप्रमासक्ता:शिरोव।
ध्याः लघदोषिणान्नपानानिप्रोक्तानियानि
लेपनंयच्च ४२ कटुचूर्णंतथसर्पिस्तदेवशो
फस्यनिर्दिष्टं उसगरूसस्निग्धंलवणंवात्
वजशोफस्य ४३ उपनाहनमथपानंक
तंऽम्वाजिणासने: शीतंमधुरंतिक्तंकषा
यमप्यदापयेत्तच्चैव ४४

पक्वकरावै फेरयोसोजकेपासकीनाडीहै तिसकोवे
धेलहूनिकाले येत्वकत्वचाकेदोषोंकरकेभानलेपन।
करे ४२ औरकटुचूर्ण अरुघेउ सोसभसोफकेवास्ते।
वीजाणे अरुवातसोफविषें गर्म अरुभारी चिंदलाणे
अरु हूर्जाकरके ४३ वंधन अरुपान यहेहोवेयोंके
वासोंकेजानणेवालेयानेकरणेयोगहै पित्तसोज
विषें पीतल मिठे कसैले तिक्त काथ्य औरघृतदुआवे
रक्तसोज औरआगंतविषेंबी योपित्तसोथविषें उ
पायकहेहैंतेन सांरकरे ४४

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰
टी॰
२०८

208

कफकृतसोजविषैंकोउ नीदना इन्हे होलेगर्भ अरु चि
पानीयंविना छोडेकोबाहरे अरु अंदर श्लेष्मके हरणे
वाले उपायकरणे योग्यहै ४५ सन्निपातसोजमें योसा
धारणचिकित्साकुहिहै सोसभकरावे ४६ वरमीकी
मिट्टिकालेप सभनाशोफांवालेकोकरणेकहेयाहै
अरु हेउ पनीस वटलवेल मद्यांउपरपायकरके मरवीर
आसव मदिरा भेद इसनाइपानकेवास्ते देने योगहै ४७ ७
नवत्तार माहा मैरेयमदभेद पाटला कालिवेल घृत १

पित्तोत्थे शोणितेनेचापथ्यावागेनकेवैव क
ह्वंकेनीलाहरेह लघु वाल्मपिच्छलेवबाहा।
ना ४५ वायाभ्यंतरकायेकतेश्लेष्मशोफ
हरे अथसन्निपातशोफेऽयोन्साधारणी।
क्रियांकुर्यात् ४६ वाल्मीकमृत्तिकाचै- ले
पनेसर्वशोफानां विस्मातिविषापाठापिप्प
ल्यश्चवहृणीयन्मातिमात् ४७ तोद्गासवसं
युक्तंपानवासमेशदेयंस्मात् ताशेमाषाः स्नि
ग्धाः कालापपामाउनेनेवेहेत ४८ वातोका
सकनाश्मागवेधकाचाश्वगंधाच गजकर्ण ५०
पलाम्पुनाम्बवहावचामातष्याग्निमंथश्च
उपनाहश्चरणाणांप्रशस्यनेसर्वशोफश्च
पित्ताढीनांचहिताः परिषेकाः शीतलाः प्र
देहश्च ५० कफजेवत्तिकाश्चह्मः सर्पिमंथ
सश्चनाशकाः ५१ इतिश्वयथुचि० नाभे
रतः पश्चात्रस्तदयेवामूत्रकोशेषु ·

रुधिर रक्तरु रुधिर ४८ कंडेआरा दांदर धमणी सहुंजन
परणा पलास सालभेद वचे दोउअरणे ४९ इनोंकरकेबी
जपोंको उपनाहकोर सभनासोजेयोंकोकरे अरुपि
तरक आगननकी शीतललपोणे अरुसेचनलेपकरा
वे ५० कफकेवास्ते तिकरणी घेउ मरवीर साथाश्रेष्ठहै ५१
इतिश्वयथुचि० नाभिकेनीचेआगे औरनाभिके पिछे

© Dharmartha Trust J&K. Digitized by eGangotri

हृदय मूत्रकोश विषें उदर स्तनां विषें वहुत वधे या हो
यो सो जाहै सो थोडे यांको द्रोणिक नाम रोग कहेया
है ५२ सो पित्त करयो है सो रंग में अरु लाल रंग स्पर्श विषे
कोमल है अरु पित्त के समुल तरण अरु वर्णा रक्तज द्रोणि
का के कहे हैं ५३ अरु आगंतज यो है सो वी पित्त सम है
पहे त्रय जाप्य जतन कर सिद्ध होजाती यां हैं यो वात ते
है सो स्पर्श विषें नर्म है अरु यो कफ करि है सो श्वेत से क
र के वहुत करडी कठि है ५४ सभ दोषों के चिह्न जिस

जठरे वयः प्रवृद्धः पोफासं द्रोणिकां तद्वे
गाणा ५२ पित्ताच्च भवत्यसावसौ लोहिता साम्र
उस्पर्शा पित्तगुणान् समानास्याने नैव रक्त
जाप्रोक्ताः ५३ याप्यागंतुसमुत्थासिस्वल्ल
ल्पा भवस्येताः वातान्नरड उसस्पर्शा कफाच्च
कठिनाश्वेतसुहिष्टाः ५४ सर्वैश्च दोष
लिंगैः समन्विता सन्निपातोत्था एताश्चषट्
निर्दिष्टास्तरुणाणां द्रोणिकाः पृथक्केन ५
श्चासामिमां चिकित्सां समासतः सप्रवक्ष्यामि
या द्रोणिकान्त पित्तारक्ता वागंतुका वया
प्रोक्ता ५६ ताः परिषेकैः शिशिरैः शीतै।
भेलैः प्रदेहैश्च सर्पिर्मधुरैश्चभिषक्सर्वो
मैत्नारवल्लिभिरुपशमयेत् ५७ विस्रावणेच
कोष्ठ प्रवास्यते वेनतस्तासो •

विषहोय सो सन्निपात करके होइ जाए है ६ हे छे प्र
कार क्रिया द्रोणिका भिन्न भिन्न करके दिया है ५५
अव इनां क्रियां चिकित्सा थोडे करके कहते हां यो
द्रोणिका पित्त रक्त आगंतुक के कहिया है तिनां को
ठंडे सेचन स्नानपोप अरु सीतल भोजन अरु ठंडे ले
प अरु मधुरव्हैन अरु एवं विधि यो नार अरु वल्लि पल्ल
का रियो कहिया है तिनां साध्य वैद्य शमन करे ५७ अरु
कोष्ठ स्थान विषे यो है तिसको विस्रावण रसभिकास

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ श्लो॰ २०९ देवे अरुयोवायुकी अरुकफकी है तिनां दोनों विषे स
जीके साथ घेउ पीना श्रेष्ठ गुणकारहै ८८ अरुपानके
वास्ते स्निग्ध वस्तु देवे अरुस्निग्ध स्वेद सेक बहिवा।
लावेघकरावे देवदिआर तिलखल तलसी ३२ सिर
209 हावेस्वेन रक्त नालपत्र कालिबेल अरु पलास के न्वार
गोअग्रा परणके पत्र मठे के साथ पजस्वेद सेक उपनाह
बंधन इनांको करावे ९० कन्नछाती ग्रंझे विषे वपन
मालसपळ्ळकारी करावे अरुस्निग्ध पूर्वक्रिये हो पछो
यापाकनाघात कफात योहितं मर्मिका शुन
मपि ८८ पानायतनः स्निग्धे स्वेदं कुर्याद्भिषक
मतिमान स्वरदोहकि एवत्तल सोयुनने वे।
नालपत्रिका षपामा ८९ नार्य पलाशानां
गोमयमेरंड पत्राणि दभामसहितं पच कार्य
स्वेदोपनाहनेबाम ९० कन्नोर सिवोपांडेलि
त्पसविरेवनुशस्ते विष्णुगोमूत्रेणान्नपुनने
वैद्वेतयाशगयाव ९१ वायस्तनामा वालंव
षाचलेपः सखोसस्तु कुष्ठसिंघुकपथ्यफ
लं वैनेनोवतीवचातिविषा ९२ कटुकापुन
नेवेद्वेगवेधुकेश्रुणवीरच मूलानि मुद्दावृक्ष
स्पवदरीमूलमनःशिलामरिच ९३ गोमूत्रा
णान्नमाषानम्ना ग्नानामेषषेरशदि पनस्त
खोसमयसलेपनमर्वशोफसंशमनं ९४
उंको रेचन जुलाब करावे गोमूत्र के साथ पीस करके
१२ सिर श्येन लाल काकतेजी भंगुन ९५ कायाकोटी
वाड्दल मंजी इनांका मील गर्म करके लेप करे कुष्ठ
वणे के फुल अरुफल नेजवल प्रलीम ९२ कौड एक १
२ सिर धमणी मेद सिंबलकीजड बेरकीजड मनसि
ला मरिच गोमूत्र के साथ मरहाम शीनशिलाके
ऊपरपीसके मील गर्म करके लेप खाडे को करे सभ
प्रकार के सोजको हरता है ९४

© Dharmartha Trust J&K. Digitized by eGangotri

अरु सिर विषें पछकरावे रोमोंकी पंक्तिकों छेके अरु
लहूकडके लूणकेसाथ उसस्थानकोमले ९५ उपरंत
मद्यों मिरच मिलायके मधुनाम आसव मदिरापानवा
स्तेदेवे और मद्यों वायविडंग सुंठ यवक्षार सज्जी लोधर
वनगसां प्रवलपत्र इनोंकेसाथ मदिरापीणेकोदेवे हरी
डकाक्वाथ हरदल लूणपज पायकेपिलावे ९६ औरये
उमिलायके चोडेतांईभोजनखानेकोदेवे जबइनां इला
जोंकरके राजीनाहोवे तो अग्निकर्मचरड देवे नाभिना।

प्रछन्नमथ्यशिरसि विवर्जयेद्रोमराजीच रक्तं
वैमोक्षयित्वालवणेन विमर्दयेत्ततोदेय ९५ म
धासवं तु पानाय पिप्पलीमरिचसंयुक्तं अथवापि।
प्पलीविडंगैर्विश्वयवक्षारसर्जिकालोध्रैः ९६
फलत्रीपटोलपत्रैर्युक्तां दद्यात्सुरापाने अभया
क्वाथसुंठीरजनीलवणानिचैवसंयोज्य ९७
ह्नन्तु युक्तं सायाह्ने प्रदापयेद्भोजनं चास्मै यद्ये
वेनसाध्योसस्यादग्निकर्मततःपरं ९८ नाभिं
हृदयमूलंचरोमराजीचवर्जयेत्तु ९९ इति।
द्रोणिकाचि० महापरिग्रहस्तन्याः क्रोडाग्रय
स्फटस्पनेकठिनः कूर्मसंस्थानाः सकछपक
उच्यते १०० शरावःसदृशः शोफःशरावइतिसं
स्मृतः पार्श्वोवाप्यथवा गुदे ह्निर्णयदिवान्तरे १०१
अयलाचक्षणानामावेशोसमीयतिश्रुति ०

औ हृदय रोमराजी इनोंथानोंको छोडकरके दग्धकरे ९९
इतिद्रोणिकाचि० एकमहावडासोज सर्वीरने रहको
रोकनेवाला छातीके अगे देखिदारहै वकूतकरडा कछो
पडके देहके सम सोकछपनामकरके रोगकहेयाहै १००
अरुयोशोथ्यशराईवां गुरहै तिसको शारवनामकहै।
याहै योसोज चोडके वत्तीयोंविषें अथवा सजे वारवे
गेडस्थल वालोमें १ वानेत्रोंकेबेठ नासावंसविषें स्थि
नहोवे वडूनकरडा अरुपीडायुक्त होवे।

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
टी॰
२१०

2.10

योकोमलहोभाकेसहस्रभा जिसकोजैसहोजेको पुं
डरीकग्रहनामकहते हैं खोखोनेगौकेकोणनासा।
केआगेग्रोथ पुवड करा इनोविषे १२ जिसकोग्रेसा
सोजाहोवे अरुमुखजिसकाश्वेत अरुआफेरकीमा
ईहोवे इनोलक्षणोंकरकेयुक्तघोडाहोवे तोमुखदूषी
णिकानामजाणो १४ तिसकोपहलेपछकरावे य
नाउमुखकेपासस्थितहै तिसकोवेधे तिसउपरंत

कठिनः पुंडरीकाभो दृश्यते यः सवेदनाः १२
यस्यैवअपघुल्लस पुंडरीकग्रहः स्मृतः छका
निकृत्वामायोयास्त्रवणा निमस्तकेवेव १३
अपधुघस्तयस्यनश्वेता घ्राणाभिवदने
एभिर्लिंगैर्मुखेनाविज्ञेयाघ्रोणिकान्तरेगा
णा १४ तस्याः प्रच्छन्नमादौ शिराश्चमुखसंस्थ
यावेध्याः अथ हरिताल हरिद्रालवण क
णालारकुष्ठग्रहस्पमेः मूत्रतक्रमद्धीयाक
दैमलेपोहन्ताकस्य अकेन्तीरमुष्टीमुकुना
सामनिकानिविषा १५ एभिर्गोमूत्रहृतेः
कल्ककुर्याद्भिषकमतिमान् उपलेपनम
खोमहतदिग्धागमपकारयस्प्रेह ११ अथ
मनिकायाः कल्केनालेनलेपनंकुर्यात वा
ल्मीकमृत्तिकावेमाषाः नारमिनाः प्रदेहा
स्म १६

हरिताल हरदल मैं पालणा मधां यउ
खार कुठ ग्रहम्म इनोकरके तिसकोमले अरुफेर
हतमिलायके विकरकालेपकरे अरुकुप सेड मो
रम मजी अतीस १५ इनोको गोमूत्र होउसाथ वेय
कल्ककरे वेउकेसाथ पहले अंगमलकेपीछे तेशी
लगमकरलेपकरावे वहतेभोहरे ११ औरमजीक
लबनायके गर्मकरलेपकरावे वर्मीकीमिति महा
यडाखार मिसरी इनोकालेपकरावे १६

© Dharmartha Trust J&K. Digitized by eGangotri

हरड़लके चूर्णसाथ ल्येउपीणेवास्तेदेवे विडंग्रा मह-
ग्रा वटलवेल पटोलपत्र निंवपत्र कुठ इनोंकरके ८९
कौउ देवदार मरवीर इनोंसाथ आसवमुदिराभेद पिला
वे रक्तो कंडेआरी दो लटर दिश्रार कहरी ९० वचे सालि
कमाहन्के फल कुठ कायाकोटी इनोंओषधीयोंको
पीसकरके ल्येउपकावे ९१ सोघृतभोजन अरुपान विषे
सावधान होकेदेवे अरुयोकल्कविषे कटु शुद्ध मुंगीया
कहिया नसो ल्येउ औरमखीरसाथखाने कोदेवे ९२ यद

रजनी चूर्णेन युते सर्पिपानाय देयं स्यान् विडंक ४
मरिच वेकपाठा पटोलपत्र पिचुमंद कुष्ठैश्च १
कटुका सुरदारु युते भूनाचैवासवं पानं का
कादनी बृहती मुष्कक नासाभ्रद्दारु विवीव ९०
बंधूयाच विदारीकंदव श्वंच कुष्टव पमिस्त
काकमाची युक्तैः पिष्टैर्विपाचयेत्सर्पिः ९१ तद्भो
जने च पाने च योजयेद्प्रमत्तस्तु कटुसुद्भाको
स्याक्रान्सदापयेत्सोद्दसर्पियुतान् ९२ यदिनैव
मरोगी स्याद्दग्निकर्माणि कुर्वीत ९३ इति मुखरो
गिणिकाचि० महाहिक्का च गंभीरा युगपज्जायते
वया मूहिवाक्षारनावेति हिक्का पंचप्रकीर्तिताः २४
महता घोषेणाहृदयस्य हिक्कानां यस्य कुप्यते हृदय
श्रायास्यते प्राणाः तस्मात्विद्यान्महाहिक्का ९५

इनों करके चोअगजीनाहोवे तांफेर मुखिकुर्मसेकदाचि।
करावे ९३ इति मुखरोगिणिकाचि० हिड्कीयाहे सोपंचतरां
कीकहिहै एकमहाते गंभीरा यमला मंदहिं साध्या
येहिक्का महा अरु गंभीरहैन सो एककालमें होजा २४
नोयाहीरहती याहैन येमंदहिहे सोभोजनमें होतीहै
याचोउको वडेसार करहिडकीआवे अरु जिसकाल
होगेके आजावे अरु प्राणजैसे बार निकसजाते हैन
तिसहिड्कीको महाहिक्का नाम करजाणलेवे ९५

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰
टी॰
२११

211

जिसमेंमनुष्यविशेषवहतसोकता अरुकिंतरवहुतउष्मापास
वत्तोपीडा अरुमर्मस्थानोंविषेपीडा पहेलतणाहैन तोगंभी
रानामहिक्काजानलेवे ८६ येहिकुकीइकवारीहोतीरहेतिस
कोमुनियोनेयमलानामकहियाहै इनांविषेदुयप्रकारकी
यांअसाध्यहै अरुदोसाध्यकहियाहै तिसकोंयेहिक्का कंठस्था
नविषेतेहिहोतिहै अरुमर्मकोबीपीडानहिकरे सोमद्रोना
महिक्काजाणो ८८ येहिक्काचोडकोभोजनदाणाघास खांदेहो
यंमितावी सोनहारनाडीमार्गरुकजानाहै तिसकरकेहोजा

मुखशोषश्चात्यर्थमततोच्छ्वासश्चपार्श्वशूलंच म
र्मस्थपीडाहिक्कांगंभीरांभीतिजानीयात् ८६ यासं
ततान्हिक्कासायमलाप्रकीर्तिताश्रुतिभिः पतति
तोमसाध्यासाध्येहेसंप्रवक्ष्यामि ८७ महीयस्या हि
हिक्कांकेरस्थानात्संप्रस्थितायस्य नवचापत्नेस्यम
र्मोपतापचूंडीविजानीयात् ८८ प्रथमहस्यापवहा
रेणवात्तिलेभोजनस्यपवमस्य सोतांसितिनिरु
ध्यतेनतस्यसंजायतेहिक्का ८९ मर्मवेदनापूतःश
स्त्रिन्नस्त्वालोचनश्चभवेत् तस्याहारस्यसंधाया हि
क्कांविद्यात्तरंगस्य ९० इत्येतेहसाध्येचिकित्सितं
वानयोप्रवक्ष्यामि पंडुविल्वमलोद्भूतेनपुष्पकेदापये
द्रुपं ९१ सर्पिःपूतेनगरोणक्कलुसपुंतनमसातोऽ
मासीमपुकोन्मिश्रप्रदापयेहोस्मसाय ९२

नीहै तिसतेसोचोडपीडाकरकेश्वासयुक्तहोताहै परसाहो
तीहै नेत्रजडहोजातेहैं तिसकोभोजनतेहोइदीहिकुकी
जाणलेवे ९० पहयोदोसाध्यकहियाहैन तिनांकीचि।
कित्साभेकहताहौं परणकीजड विलपकीजड इनां।
कोकूटकरलायकरके धूमदेवेपानकेवास्ते ९१ चोडपू
वगोका अरुचोडकीलिदकारसविषैचोलकर छूडा।
गुडी पुलह चोडनाई वरणीवटावे ९२ गलो तलसी
के डेग्रारी ठिग्रार इनांकाक्वाथकरे इसक्वाथसाथ॰

© Dharmartha Trust J&K. Digitized by eGangotri

शुंठ्यादिगणविचपाय घृतसिद्ध करे ९२ इसघेउकेपीणे
करके हिड्की वेग दम समहोजातेहै अरुयेकल्यस्थान
विषे वर्णीयाकहियाहैन सोउहिवालावेघेदेवे ९४ मो
रपंखकी नालियां दग्धकरे तिसकीखाहा मखौर अरु
घेउसाथ चटावै पहेलेरहिकाकों हटादेताहै ९५ इसी
नरो सेहके रक्तले नउ सिपी चूर्ण [illegible] भखवे गउ
मूल इनांकोभस्म भिन्नभिन्न चटणीयांकरे मखौर घृतसौ
चटणेयें हिड्की हरकरनीयांहैन ९८ वंसलोचन रसों।

अम्रतां सरसां लाक्षां सरदारुकषायेन तत्सलेन
काथेन पचेत्सर्पिर्तुं कं शुंठ्यादिगणेन ९३ हिक्का
कासश्वासाः शाम्यंते चास्य सर्पिषः पानात् कल्पा
कानिचले हानिदापयेत्तु हिमालयघः ९४ ना
लानि मयूराणां निलिंपा दाहयेत्ततः सचूर्णं पम
धुसर्पिसंयुक्तं लेहो हिक्कां निवारयति ९५ प
वंसलूकि मनलेप्स कितगर्भे वसरक्थ्यरदेवाव न
लमूलं चैकत्र्यक हिक्काशमनाय कल्पीत ९६
एवं तु रगान्धीरीरसांजनन्सु किकांहरिद्रांव सुं
ठ्यादियवक्षारं हिंगुविडंगानि सैंधवं चैव ९७
सचूर्णं पचेत्सर्पिर्दिवभगरमेरथ्यात्रिगुणेः पा
नस्यानायहिते हिक्काश्वासापहं घृतं श्रेष्ठ ९८
रयोनाकेन च धूमो हिक्काश्वासं च नाशयति
सुरदारुखदिर चित्रकपलाशपाठाउलीभा
तिविषा ९९

न सिपीयां ह्र दल शुंठ्यादिगण
यउखार हिंगु. वायविडंग सैंधवलूण ९७ इनांको
महीनपीसले अरुबांसकारस त्रिगुणपाय घृतपका
वे सोघृत पानकेवास्ते हितकरहै अरुहिक्कादमका
नासकरहै ९८ अरु टांटरे साथ धूमपानकीयाहोया
हिउकश्वासकों नाशकरताहै दिआर खैर चित्रा पला
ह वटलवेल त्रवान प्रतीस ९९

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰
टी॰
२१२

212

और दूधखानेकीजगह सूंठमठा इनोंकोमट्ठीनपी
सके इनोंकरकेचेउपकावे सोघृतहोवेयांके श्वास
अरुहिडकीकोनाशकरताहै १८ सुभ्रादिगणकाज
लवनावेपीनवास्ते अरुगावा रैसन सैंधालूण हिंग
पउलार मठा सूंठ वावडिंग इनोंऔषधियोंसाथ वा
सकेपत्तोंकारसपाय बुद्धिवाला वैद्यह्नसेउपकावे इस
घृतकोंप्रातःकालविषेपिलावे नवहीउग्रहिकीहो
जाताहै २ यहचिकित्साहिक्काश्वासकेहरणेवालेके

कटुकारोहिणीसूंठीमागधिकांचैवसंचूर्ण्य प
भिर्विपचेत्सर्पिर्हिक्काश्वासवरंहितंनराणां १८
शुंसादिभिश्चसलिलेक्वथितंपानायदेयंस्या
त् रास्नासैंधवहिंगुयवक्षारपिप्पलीविश्वैः १
सविडंगंघृतमेभिर्द्विषपुत्ररसैःपचेद्धीमान् ए
वंद्विपाययेदेतन्नतःसंपद्यतेसुखी २ यथा
चिकित्साकथिताहिक्काश्वासनिवारिणी ३
इतिहिक्काश्वासचि॰ वक्ष्याम्यधुनाश्वासानूर्द्ध
श्वासस्तथामहाश्वासः छिन्नश्वासस्तमकः
श्रमजश्चैवपंचप्रोक्ताः ४ यद्यपिदारुणतापि
तेनपार्श्वरोगैश्छिन्नकृच्छ्रश्वासः इत्येतन्निर्दिष्टा :
श्वासामुनिभिस्तुरोगाणां ५ संततमूर्द्धश्वास
निरुद्धनरणस्यानितपार्श्ववान् यस्तद्विनौवि
शुद्धसंज्ञोमर्मवापीड्यमानेषु ६

रिहै ३ इतिहिक्काश्वासचि॰ अबश्वासकेभेदनामउ
पायकहताहूं पंचप्रकारकाहै ऊर्द्ध महा छीन तम
कः श्रमज परश्वासकहैहैन ४ अरुयेविदारुणता
सोंकरकेपार्श्वरोग अरुरोगोंविषेछोडकोश्वासविक
रहोताहै परेइनने श्वासछोडयांकोमुनियोंनेकहै १
छौड निरंतर ऊंचाश्वासलेताहै अरुपार्श्ववर्तीयांको
जेपरखिचदाहै अरुदीनमोहाहोजाताहै औरसारता
हरजातीहै मर्मोंविषेपीडाकेहोतीयां ६

© Dharmartha Trust J&K. Digitized by eGangotri

सोऊर्द्धश्वासकुकहोजाहै इसकोचिकित्सानहिकरसक
ताहै योवडेशब्दकुरकेश्वासलेताहै अरुलिसाहोजाता।
है मूर्छा अरुवस्तीयाउपरलिवोएअरुविहोसीहोतो।
है अरुखेलांकीनंएघुमताहै शब्दसाध्यदमलेताहै सो ८
योउमहाश्वासवालाहै इसकीचिकित्सानहिकरेवैद्य
अरुखोउ २ करवडाश्वासवारंवार नासांतेलेतीहै यो
तीएहै तिसकोतीएश्वासकुकहोउजाएए ॥ पहेत्रै
श्वासअसाध्यरूपहै इनांकाउपायनहिकरे १ योहोउ

उर्द्धश्वासीसोऽप्यसाध्यचिकित्सानप्राकुनेकंते यो ७
येणयोनिमहतांश्वसितिहृययोमूर्छितोदीनः
उन्हिमपार्श्वप्रनष्टसेत्तः प्रधाम्यतेतीव सोऽप
स्तमहाश्वासीनस्यचिकित्सांनकुर्वीत ८ वि.
छिन्नंयोवलवान्महृन्मर्ह्मः श्वसितिनस्यनःतुर ९
गस्यः तीएः श्वासंविंद्याद्साध्यरूपास्त्वयस्वेत
यः श्वसितियश्चाऊर्ध्वकठिनकफेनाप्तिका
वृध्यो: यस्यनसन्ताननाशोनवापिसर्मोगिण।
वाध्यते ९ एषश्वासस्तमकोलिंगांस्तनानि
वेगमोस्यापि गैष्मिकशारद्योरपिलिंगान्य।
नानिजानीयान् ११ पितोतगुस्तकस्थिता
एतेश्वासास्तयस्त्वरंगाएणा एवपितश्वासाः
साध्यायाप्यस्तमजकःश्वासाः १२

कोयधुकहोपकीनरांदमलेताहै अरुकरडेकफकर
केनासापुटरूकजाए अरुस्वरनजिसकीनाहटे अरु
योममस्यानकोपीडनाकरे १० पहेतमकश्वासकेल
तेएकहेहैं अरुयोसाध्यकेमकाकेयोदमहै तिसकेवी
पहेलतताहै अरुग्रैष्मकशारदश्वासकहेहैं तिनांके
वीपहेविष्ठहेन ११ पहेत्रयप्रकारकेश्वासवोउयाके
करेन सोपितप्रधानकरकहेन पहेपितजश्वासहै १२
साध्यहेअरुतमकश्वासयाप्ययत्नसाध्यहै

© Dharmartha Trust J&K. Digitized by eGangotri

तिनोंविषैंठंडेहि पान लेह भोजन वस्ति पळकारी पित्त
श्वासमें देनेयोगहै ग्रोरयोपित्तकेनासकरछुप्रहै सोदे
वे १३ ग्रोरयोश्वासकहेन तिनोंकीपहिक्काविषैचिकि
त्साकहिहै सोसमकरणेयोग्यकहतेहैं ग्रस्वशास्त्रके
जाननेवाले १४ इतिगण० सिद्धयोगसंग्रहेश्वासचि।
कित्साध्यायः वात पित्त श्लेष्म सन्निपात इनांकरकेचा
रकेग्रतीसार ग्रपणो २ लक्षणोंकरकेकहेहैन उनां
केलक्षणचिकित्साकहताहौं १५ जिसविषैगेरा ग्र

पीनानिश्चतिपानानिलेहभक्ष्याणिवस्तयः पि
त्तश्वासेप्रदेयानिपित्तघ्नंयच्चकिंचन १३ श्वा
सानांमपरेषांतुहिक्कानायश्चिकित्सितं तदे
वसर्वकर्तव्यमितिमाहुश्शास्त्रकोविदाः १४ इ
तिगणकृतेसिद्धयोगसंग्रहेश्वासाध्यायः
वातात्पित्तात्कफाच्चसन्निपाताच्चदोषलिंगे
स्तु वदतोऽतीसारांस्तेषांप्रतिक्रमंवदामि १५
कलिलमथविछिन्नंसफेनमल्पंद्रवंपुरीषंस्या
त् रुक्तमनिलातिसारात्सेकोवस्त्रवगाहणं १६
तत्सलिलावगाहः स्नानानविवर्जितस्ततोद
द्या पानायसस्तामेंषवडिंगदाडिमबिल्वविष
घ्नाः १७ निःक्वाथदर्भमूलानिशृंगिपर्णि।
पानावरीमधुकेन तेरलीरमाध्यतक्वाथस्वा
दुनेकार्थ्य १८

रुछिन्नरंग भिन्नभिन्न ग्ररुच
डेशाचूकर पतलामलहोवे ग्ररुरवोतो वायुकर
ग्रतीसारजाणे ग्ररुयोंग्रगाकोकिठाकरलेवे १६ नि
समैंथोडेकोंजलविषैं नाभीलग्रावे ग्ररुजलनापिला
वे फेरपानवास्ते सैंधालूण वावडिंग नारदाना विल
कथा सेउ इनांसाथ मदिरादेवे १७ दर्भकामूल इंद्रयव
शानावर मुलठी इनांकाकाथवनाके तिसविषैंडया
काडे तिसका फोग मदिराकेसाथमिलावे १८

© Dharmartha Trust J&K. Digitized by eGangotri

जिसको रक्त राव रखके सोडुग्ध अरु मदिरा मखीर मिला
यकर घोडे को पिलावे फेर हन्ता अन्नात्रुलाके तेलको प
कारी करावे १९ मठा सुंठ बिल्वकण मुलठी इनाको म
खीर घृत साथ वायु के अतीसार के हरने वास्ते पीनेको वैद्य
देवे २० और कटु चूर्ण सैंधा लूण मदिरा साथ पिलावे इ
सकरके वायु का अतीसार घोडे का सतावी दूर होजाता है २१
इति वातातिसार चि० जिसका गुद बहुत बार हगकर है अ
रु वायु निर्बल होजाता है अंगों विषे परसा अरु चित्त स्थिर न

नामकरा जो मखीनो ली रसों मधु संयुतां पिवे
द्वाजी दद्याच्च तैलवस्तिं हन्तान्नं भोजयेत्ततः १९
दधि बिल्व शलाटूनि च मधुकं सह सपिष्टा मधुना
व दद्यात्ततो नायं भिषक् वातातीसार रोगहरं २०
कटुचूर्णं सह सुरया सैंधवयुक्तं च पाययेत्तमिमा
न् वातातीसारेणेन नश्यति क्षिप्रमश्वस्य २१ इ
ति वातातिसार चि० परिशुष्कगुदो दीनः प्रसि
क्तांगो न च स्थिरश्चापि वालैर्वीजयति दृशं गुरु
मुहुर्विश्वसेच्चैव २२ तोयं शोणितमिश्रं पीतं र
तेना च शीकरसदृशं पित्तातिसारेण तुरंगं वा
तिसार्यंत २३ तं कर्दमदिग्धांगं प्रशोचयेद्धी
तलैश्च परिषेकैश्च तेनु कषायं मधुषा कल्कं
मधुसंयुतं दद्यात् २४ द्राक्षापरूषकालेयमधु
कं सदाडिमं समं गाव०
इंवको निरंत
रहता अरु
रफेरता है अरु बारंबार स्वास लेता है २२ अरु पाणि ला
हूके साथ पीला वा हरा करणके रजत विंदु के सदृश
पित्त अतीसार करके युक्त घोडे सो वह तुरंग पित्तवाला
मल त्यागता है २३ जिस घोडे के अंगों विषे चिकड लगे
वे अरु ठंडे योडु महेन तिनां करके परिसेचन घोणा ना
मण के क्वाथ को मखीर साथ पिलावे अरु दखण के
मिकडी का कल्क बनाय मखीर साथ देवे २४ मुनका
फालसे पीतचंदन बाकला हर रदल मुलठी नारदाण

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ मजीठ इनोंको महीन पीसकर ठेउ मखीर खंड पायकरले इह
टी॰ चरणीदेवे २५ मुलठ डुवो खीर काकोली तिसके अभाव
२१४ विषे पराली मजीठ इनका ठंडा हिपाणा मखीर चून साथ
पिलावे २६ लोधर फूलफरंग तदभाव धनियां विदारी वर
मलठी धाइकेफूल पहेपीसके मखीरसाथरलायके च
रणीपिन अतीसारको हरकरती है २७ मरेडे अंबकी
गुली नारदाणेकेसिकड नमपाल मजीठ इनाकाचूर्ण
मखीरपायडथकेसाथ पानवास्तेदेवे २८ पित्तकेअति

पिष्टाच्युतमधुयुतं सशर्करं दापयेल्लेहं २५ य
ष्टीमधुकं लेहं हर्वो सपयसापेषयेत्स मंगा व
शीतकषायं पानेप्रदद्यात्लोद्गमधुच्युतसंयुक्त
लोध्रप्रियंगुक्षेरनषष्ठा हेटानको युतैःपिष्टैः २९
लीडमलैनेश्चलेहः पित्तातीसारसंशमनं २७
गोलशुकमाम्रसारं वदाडिमनवकमंगयुक्त रि
ते पूतलोद्गणयुतं तीरेणवदापयेत्पानं २८
सतांपिष्टुं देवरशलाडुचूर्णं प्रदापयेत्मति
मान लोडलीरविमिश्रं पित्तातीसारसंशमनं २९
इतिपित्तातिसारचि॰ आमेकफेनमिश्रं समूल
मतिसार्यतेवापीना पंचविधैस्तलिंगैः श्लेष्मा
तीसारउदिष्टा ३० तस्यान्तविश्वकटंनटमाग
धिकापीलदारुभिः कथितं शीतंमधुसंयु
तं कल्कंपानायदेयस्यात् ३१

सारकेशमनकरणेवास्ते कंवलकेकचेफल कुटकरम
हीन मखीर अरु तुथसाथपिलावेवैद्य २९ इतिपित्ता
तिसारचिकित्सा तिसविषे आम अरु कफ मिलते होवे
पीड ककुक पीनश्चेसारमलआवे जिसके पहेललक्षण
होणतो श्लेष्मातिसारकेहयारे ३० तिसमें संठ टोटर म
हो पीतल दिमार इनोंकाकाथशीतलकरके मखीरसाथ
पिलावे अथवा कल्क नुगदाकरके साथदेवे ३१ मुल
ठी लोधर महुआ संठ लामबीरणकीजर इनकाकाथकरे

© Dharmartha Trust J&K. Digitized by eGangotri

तिसका क्वाथ जलविषें सठीका भक्तदिनके वैद्य घोडेको पि
लोकोदेवे ११ क्षारसाथ तैल श्लेष्म अतिसारके नाशवास्ते
वहुत श्रेष्ठ कहेया है हरडे वहेडे आमले इनोंका क्वाथ मखीर
के साथ पिलावे बुद्धिमान् ११ सप्ताहमेंविषें भोजन कराय के
घोडेको तेलकी अनुवासन वस्तिपञ्चकारी देवे अरुवाइके
अतिसार विषें योकहेया शीतसुरा मदसोपानके वास्ते देवे १
नारदाण कैथ कायफल इन्द्रयव हेवलफल रसौंत इनोंका
चूर्ण मखीरके साथ चटणी श्लेष्म अतिसारको हरकरहे १४
इति श्लेष्म अतिसार चिकि० योहवे विषें योकहे वातादक

यष्ट्याह्वलोध्रमधुकं पद्मकं विश्वशीराणि साध
येत्सलिले तस्मिन्क्वाथे सिद्धं प्रदापयेत्वष्टिकोप
नैवेद्यः १२ तैलं क्षारविमिश्रं श्लेष्मातीसारनाश
शने श्रेष्ठं पाने त्रिफलाक्वाथं तोद्रयुतं दापये
न्मतः ११ तैलेनततः सायंभोजितमेवानुवा
सयेदश्वं वातातीसारानं शीतसुरांदापयेत्पा
ने १४ दाडिमकपित्थकटूफलवत्सकवीजा
रसोंदुवर शलाटु समसारसांजनयुक्तं वलेहलो
ह्यमेयुक्तं १५ इतिश्लेष्मातिसारचि० वातादयः
प्रकुपिताः स्वैस्वैः कारणैस्त्रयो दोषाः जन
यंति सन्निपातेकमेवातीसारमश्वानां १६ तेन
प्रवेपमानः श्लेष्माणं सजलं गात्ररोवाजी पिच्छि
लमथवारक्तं सफेनं लंवातिसार्येण १७ कवि
दामकविदाहैक्वचिहि शुक्लकविदूवं चैव अ
तिसार्यते पुरीषं नानावर्णरूपं तव १८

दोषांके कोपितकरनेवाले कारण तिनों करके कोपित
होयपये त्रय वात पित्त कफ सोघोडेयांको सन्निपात
क अतिसारको पैदा करते हैं १६ तिसकरके घोडाके
वदाहै श्लेष्म दम ज्वरक पीडन होताहै अरु पिपानी
वाला वा लाल अथवा वहुत कफवाल दस्त होता है
१७ अरु कदे आम अरु कदे छिला कदी सकादा
कदे कपतरा अरु अनेकरंगांवाला औरममल
दस्तलगताहै १८

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ यहे अतिसार असाध्य कहेया है तदवी यहे चिकित्सा इ
टी॰ सकी कोरे ठडे जलविषे न्हालना अरु चिकडे का लेप
२१५ करणा कहेया है ३९ मुलट टाट मधी सौवलसूण वा
डोंका आटा वटल वेल रनाकी पिछी वनाके देवे अ
थवा तिलभक्त मरिच गुड मधी यहे देवे ४० सठीका भ
त फलयोंके रससाथ अथवा मासकेरससाथ खाणे
को देने योग्य है मठेकने अवलसाथ मधी खंड मि
लायकरके भक्त खानेको देवे ४१ अंगोंका फकजाणा

यष्टनसाध्योरोगस्तथापिकुर्यात्क्रियामिमां
वास्य शीतोदकावगाहः प्रलेप इति कर्दमेना
का ३९ मधुककट्वङ्गटङ्कलासौवर्चलशालि
पिष्टपाठाभिः पिण्डकृताद्दद्यात्तिलोदनं मरि
चगुडकणाभिर्वा ४० कौलत्थमांसरसैर्वा भो
जनमथ षष्टिकौदनं देय दध्ना सनविमिश्र
माग्यिकाखिण्डसंयुक्तं ४१ लोमोवेपथुरा।
ध्मानत्स्वास्वामविपर्ययः गतास्वषाम।
नीमारालतत्वणमवधारयेत ४२ इति अ
तीसारचि॰ पित्तश्लेष्मावातेन प्रेरिताएवरो
भृता: सद्यच्यनन्मासे सर्वाण्यगानि बाध
ते ४३ एवं वस्त्रिपानेन वातोवातस्थमरि
ताकठिना रक्ताभासाकोलेम्टड्डुभिः परिपी
ड्येनतुदेय ४४ अभक्तयाल्पभक्तः प्रकपि।
त:स्निग्धउष्णाशन:

औरकंपहो न अफारा लषा
अरुदमविकृत उलटा आउणा यहेलषणजिनाकी
अवस्थानविषे होवे तो होने हैं इति अतीसारचि॰ पित्त
कफ वायु करके प्रेरित होय दे अरु खौरे हो करके
तचा अरुमासकों विगाडके सारेअंगोंका पीडाकर
ताहै ४३ यहेरोग जोडकोंमत्रिपानकरके है अतिक
ठिनकहियाहै अरुरक्तवर्णकाप्रकाश अरुउत्तीयांको
मलपिंडका फीगुलीयां करके सदापीडित होताहै ४ म
वीडाइसकरके थोडा खाटा है अरुकंवटा है अरुस्निंदा

215

© Dharmartha Trust J&K. Digitized by eGangotri

गरुगर्भमेंदेहवालाहोताहै यहरोगअसाध्यहै नदवी
इसकीचिकित्साकहताहूं ४५ इसविषपरलेपछकरा
लेफेरनाडीभेद हथिरलुडाना उपरंत मधुनामआस
व अर्कभेद मखीरसाथपानवास्तेदेवे ४६ कुठ नगर
हरदल हिंग्आर समालवीज वणदेवीज इनांकोगोमू
त्रमें सभनाकाक्वाथवनायकरके सीलगमेसाथ रको
रवेंयन उपरकरे ४७ कालिवेलवा मधा वचे हिंग के
डेआर भरवडे कंउआरी हारर कुठ वसमा असगंध १२

यष्टोसाध्योरोगस्तनिकर्मनयापिवक्ष्यामि ४५
नेत्रप्रच्छन्नमार्दौसिरावेध्यस्तंततश्चैव मधा
सवंवपानंदद्यात्तोहमधुसंयुक्तं ४६ कुष्ठ
नगररजनीमरदारुहरेणवोगवामूत्रे पतन
कथितंसर्वंसलेसंपनाहनंकुर्यात् ४७
एणामावचांसहिंगंवाशार्नाकोशकनासातथा
कुष्ठ कासांतरंगगंधांशनैवेहंततःपिष्टाः
गोमूत्रेणकथितंसलेसंपनाहनतुहितं
देयाक्ष्य सूक्ष्माविषकणासोहहतमिश्राः ४८
त्रिफलाओषविंडरोमरेणनीसमपणकु।
ईलारारुयुतैःप्रतिपानंतोहघृतमासवं।
देयं ५० इतिकोरवातीचि० शीर्षोललाट।
स्थितिरक्षसंवेयसोर्द्धगस्तापयतिप्रभंजनः
शूलानिकुर्वंसततंभिस्रोमाप्रोक्तेनशमितं
रुगः प्रयाति ५१ न इनांकोपीसक
सिर२१कैसे
रके ४८ गोमूत्रसाथकाउके सीलगमेउपरवंधनेकरे
याद्रे अरकमंगी सेउ मधा मखीर चेउमिलाइके खा
नेकोदेवे ४९ त्रिफला मधा मरिच सोउ वावडिंग
चिवड नमामेद मलोना कुट दालहरदल इनांकोम
खीरसाथ आसव मदमेद पानवास्तेदेवे ५० इतिको
रवातिचि० शुउपुरीया मध्य सिर इनाकोकहरोग निवा
रहोके नस्ससरुपीउशूलकरताहै असकसखातिको
णमें अरुशोथपावडुकरके इष्यवीविषेगिरताहै रोग
खेडे होता है ५१

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ थकेमाकेसारै देहहोजाताहै सिरहिलासटदाहै
टी॰ अरु छूटदा जाताहै अरु बारंबार सिरमारदाहै तिस
२१८ कोपहलेलक्षणहैं तिसको वातकर सिरोविकारजा
णो ५१ तिसविषे पहिले नाडकियां होनारी याको।
वेधकरावे फेर शंखस्थानकर्ण अरुमत्थेका मध्यस्था
216 नकीयां वेधे लहूके निकाले होयां मदिरा लूणके सा
थदेवे और मंडा वचे शतीस इनांकापान बनायपिला
वे ५३ योकल्पस्थानविषे सिररोगवाले नसवारकहि

क्रमान्नितोम्यस्तु शिरं हीयेन्मुहुर्मुहुस्यापि भृ
नोति शीर्षे एतानि रूपाणि भवन्ति तस्य वा।
तोद्भवस्तस्य शिरोविकारः ५१ पूर्वं शिरेना।
लं नितस्य वेधशंखे च वेधो रुधिरं सनेव द
द्यात्समद्यालवणानि तवचकुष्ठं वचा वातिवि
षाच पानं ५२ नस्यं च कल्पेन यथोक्तमस्यदे
यं च तैलाक्तस्य रसाटनं च स्वेदं च कुर्याच्च तमस्य
पकं यथागेम वातहरं प्रयोज्य ५३ इति वातशि
रोरोगचि॰ संतप्यमतीव शिरः स्वेदस्तस्य जा
यते स्यामः पीनेहरिते नेत्रे पित्तसमुत्थे शि
रोरोगे ५५ तिक्तानि घृतलान्नाम रोषधे पेपे।
धयेत्समा सानि एभिस्तैलपक्वं नस्यदद्यात्।
स्रावो भवति ५६ इत्थं क्रूपणं मले देयगाथा
तिक्तेश्च रायातैलमस्तैः
ऐसा देवे और रहूत युक्तमास रमत नेभूनदेवे अरु स्वेदसे
कदेवे और ये वो उवायके हरनेवाले शास्त्रविषे कहे
हैं सोटेने योगपहै ५४ इतिवात सिरोरोगचि॰ पित्त
सिरोरोगविषे पहले लक्षण होते हैं सिर बहुतन तपदाहै
परसोल्टा व कुनदम होता है अरु अतियापीली।
यां वा हरीयां पहले लक्षण होते हैं ५५ कोउ सें पालूण
लारव मु इनाके बराबर लेकर पीसे इनके कल्क सा
थ तेल सिद्धकर नसवार देवे तवतोउराजी होता है ५ ९
गना इस इनके जड अश्वगंध कोउ लसन पोम •

© Dharmartha Trust J&K. Digitized by eGangotri

इनोंकोपीसकरघृतमिलाइकेथोडेनांईरसदेवे ५७ अ
हचिकित्सासभशीतलकरेथेनीराणकीविकारवि
षैहितकहिहै अरुजासकेवास्तेववलकीयाडुवादेव
अरुकुंभकेविषेहोयपउरवानेकोदेव इतिपित्तशिरोरो
गचि० जिसमेंसिरभाराहोरिगैरीलालावगणअरु
किलनथावकरणसाथहोलीनलन विमनहोना प
हेलवणहोननोकफकरसिरोगजाण ८९ तिसकीनां
डीयांविषेवेधकरावे नालशंखवुडवुडीयांमध्यग
लेनाडीयांकोउहरुधिरनिकालकेउपरंतपहेचि०

पिबेच्चनस्तंमिश्रैःस्वमेष्वास्मेप्रदातव्याः ५७
क्रियाश्चशीताःकर्त्तव्याश्चनीराणांकिनाहिताः
हवींषयवमेदघादेयाःकुंभभ्यवायवाः ५८
इतिपित्तशिरोरोगचि० शिरोगुरुत्वायतनयस्य
हरिवलीलाप्रसेकःकण्ठनसन्कूजनेन मंदश्रवा।
रोचस्तइमिनेत्रकफोद्भवस्यशिरोविकारः २५
तस्यशिरोविरेचनानिशंखवमनस्यधोश्चव
रकेष्वुतेप्रदुष्टेततःक्रियांकारयेदेनां ९० त्रि।
कटुपटोलत्रिफलावचामृतालोध्रमधुमसमायु
के श्रामलवमनसेदधानप्रतिपानेकफाशिरोरो
ग ९१ नस्यंप्रदेयेद्वृहतीफलाधिनस्यापिपानानि
कफापहानि मृद्वंश्चतिक्तान्नवलभोजनयेच्चप्र।
शांतयेश्लेष्मशिरोरोगदस्य ९२ इतिश्लेष्मशिरोरोग०

किन्साकरे ९० मधुमरिचमंजुप्रवलपत्रहरडवहेडेआम
लेवचगलोलोध्रइनोंकेविषेमरवीरलायके इसके
साथआमवअर्कमेटमद थोडेनाईपिलावेकफकेशि
रोरोगमें ९१ वृहतीकेडआंकेफल इत्यादिथोनसवा
रहे सोचडावे अरुयोकफकेनाशकरणेवाले नसवा
ए अरुपानहैन सोदेवे अरुयोनिकमगूदकरेहें सोखा
णकीदेवे श्लेष्मशिरोरोगकीशांतिकरणेवासेथोडे
कोउचितहै ९२ इतिश्लेष्मशिरोरोगचिकित्सा०

© Dharmartha Trust J&K. Digitized by eGangotri

भा. यो सभ दोषों के मिलित लक्षण होंय तो सन्निपातिक जा
टी. नलेवे यो आगन्तक शिरोरोग है सो पित्त शिरोरोग के
२१७ बराबर लक्षण कह्या है ९३ सन्निपातक विषें साधारण
क्रिया चिकित्सा करै आगंतक शिरोरोग विषें यो पित्त
रक्त विषें चिकित्सा कही है सो करै ९४ उनों के सम चिकि
त्सा करै अथ शास्त्र के जानणे वाले वैद्य सन्निपातरक्तंग्र
ग वि. जिस चो उकी नासा ते कफ अरु रक्त ते उपन्न होकु
रके क्रिमि नासा ते निकाल ने ओथमान कुडको हत्ता ते

सन्निपातेन रूपाणां नानीया सन्निपातिके आ
गन्तकः शिरोरोगः पैत्तिके न समः स्मृतः ९३ स
न्निपात समुत्थाने कुर्यात्साधारणीं क्रियां आ
गन्तकः शिरोरोगः पित्त शोणित जाश्रये ९४
तेषां तुल्या क्रिया कार्या भिषजा संविजानता
सन्निपातरक्तागंतक वि. कफशोणित संभू
ता नासाभ्यां निःसृतात्तरगस्य क्रिमयोयस्तत्
मस्तकं भ्यते प्राथमानस्य ९५ भुत्तयात्मस्तक
मेवं चर्षति निःश्वसितैः शिरोरोग विघा क्रि
मिसंभूतस्य चिकित्सा प्रवक्ष्यामि ९७ नीक्ष्णा
पूर्मं कुर्यात्तु यमनं मधुनावनानि नीक्ष्णानि
मद्धा शुभोजयेद्दविडंग चूर्णेन संयुक्तान् ९८
कटु चूर्ण सविडंग पानायहितेन तैन संयुक्ता
कम उपक्रं विकोऽच सद्धेता दद्यात्तो द्वण
संयुक्ताम् ९९

होय तो नासां विषें देखीदे है
न ९९ मस्तक को कमावा है अरु खाया करता है और उच्छु
श्वास लेता है इनों करके क्रिमियों कर शिरोरोग जाणे
तिसकी चिकित्सा करता हों ९७ तीक्ष्ण धूम्र खाणे वा
पिलाने तस वार और तस वार भेद अथवा तीक्ष्ण देवे
और वावडिंग का चूर्ण पाय करके संगी खाने को देवे ९८
अरु कटु चूर्ण सर्वं कह्या है सो वावडिंग रलाय देउस्मा
घ पान वास्ते देवे कालीमीरी सेउ मखीर साथ देवे ९९

217

© Dharmartha Trust J&K. Digitized by eGangotri

वमीकरे आरीकेफल अतीस मघां मरिच सुंठ ऊठ इनोंकाचूर्ण
महीनकरकेपीसलेवे इनोंकरके सिरोविरेचनकरावे निरंतर
वारंवार औरमदिराकेसाथ रलाइकरके इसचूर्णकोंदेवे १०
कंडेआरेकेफल पोस्त हिंग वचे सजीखार कालिहारी वायवि
डंग गोमूत्रकेसाथवगावरहल्दीनरोंपीसकरके ११ इनोंकर
केतेलपकावे इसकीनसवारकरावे जुदिवाला गोमूत्र
साथ यवागू सिद्धकरकेउपायकरके खाणेकोदेवे १२ तग
र वचे रारदल रालहरदल इरसिटखेत इरसिटरक्ते ऊठ

बृहतीफलान्यतिविषामागधिकांऊष्टंचचूर्णयेत्तस्मा
त्तण शीर्षविरेचनमततंप्रसन्नायालोऽदेयंस्या
त् १० बृहतीफलेरसोनंहिंगुश्वेतानसवर्विका
वैवकाणीसमविडंगंगोमूत्रेणसमाप्ततेपिष्टा
प्रभिस्तैलंविपचेन्नस्तस्यास्मिंप्रदापयेत्यास्त:
गोमूत्रेणयवागूंचभोजयेत्तौटदृत्तपुकां ११
तगरंवचांदारिद्रेउनेवेऊष्टमर्कमादाय
पिष्ट्वातैलंविपचेत्प्रदापयेन्नावनीतेन १३ इ
मागधिकामरदारुसरलंसितसर्षपंसमादा
य तैश्चूर्णितै:चूर्णकेर्नस्तै:प्रम:प्रदेय:स्या
त् १४ त्रिफलापानायहितानिम्बक्रिमिना
शनोत्तरंगाणां एवंक्रमिसभूत:शिरोविका
र:शमंयाति १५ शीर्षाभितापःक्रिमिज:

एवंशिरोरोगचि०

अक इनोंकोलेकर पीसके तेलपकावे पकायके
मखनसाथखाणेकोदेवे प्रमाणमात्रादेखकरके
१३ मघां दिआर चीड सेती सरेयां इनोंकोमहीन।
पीसके घेउमिलाय नासांविषइणी घुलावे १४
हरड बहेडे आमले पानवास्ते श्रेष्ठहै निमहि होडके
क्रिमीयोंकेनाशकरणेवालाहै इसतरांक्रिमीयोंकरके
होयायोरोगहै सोशमहोजाताहै औरक्रिमिविष यो
अभितमसोवीहरहोजातीहै १५ इतिशिरोरोगचिकि
त्सा०

७१

© Dharmartha Trust J&K. Digitized by eGangotri

शा. निदानविषेवीसप्रकारकेलिंगितकहेहैन तिनोंविषेद
हो. शयत्नकरकेसाध्यहोनेहैन ग्रोरयेदशप्रकारकेहैन
२१८ साश्रसाध्यकहेहैन १९ पकदर्भक चूर्णक केशी स्राव
प्रकरकी अपनासश भग्नसधि रोहिणी सधिमुक स्रा
218 वृद्धिरक्त येहदश असाध्यकहेहैन ग्रन्ययेदश साध्यन सौ
हेएउ १८ नलउपताप नित्रपिकुंचलेगिन प्रथ्यस्थि
लेगि उरोलेगि ग्रंशलेगि त्रिकलेगि उभयलेगि वक्र।
सक्थिलेगि स्परानातलेगिन येहेदशलेगि साध्यकहे

निदानेयानिचोक्तानि लिंगिनानिनविंशति
दशतेषामसाध्यानि दशसाध्यानिकर्मभिः १९
दर्भकश्चूर्णकः केशीनथास्रावः प्रकोटको अ
पन्यासोपप्रकस्य यथ्रभग्नससंधिमु ॥ रोहि
णीसधिमुकस्य स्रावुद्धिरवयउवेत् असाध्या
निदशैतानि दशसाध्यानि वैशृणु १८ नलोप
तापः प्रथमे नित्रपिकुंचलेगिने ग्रथ्यस्थिजा।
नुलेगीने नमोरस्थिगनवतन् १९ अंशलेगीत्रि
कलगीयश्रोभाभ्यावलेगति वक्रसक्थिस्प।
रानातेदशमसाध्यलेगिने ८० ग्रजेतिब्रगोग्र
णहृयोमदुनिमसेवनेमतलेलगी नस्पतले
नयोनेविशोपयेदसवाशणात ८१ शाल्यय
दिभवतिनलेनमष्टरेहावेननतःपश्चात् ती
तैनकरुकषायेणसान्तोरयमेन ८२

है ८० योघोडासेवकेअग्रभागकरकेचलताहै ग्रस्
कोमलस्थानकोसेवताहै इच्छाकरताहै सोतलेलगी
घोडाजाणे तिसपादकेतलकोधोनेहापेन् हत्याविषे
लेकरके यदउसकेविच मल्ल कंडापथर होरकछुच
बादाहोवे उसकोकढलेवे फेरउससेवकोधुक्षावे
नीरतहवड वडीरुवल पलाश वैत इनोकेकाथसा
थधोवे ग्रोरइनोकेउपसाथधोवे ८२

© Dharmartha Trust J&K. Digitized by eGangotri

काशी लोध्र कांफल त्रिपंगु कांउ १ नां के चूर्ण करके सं
व के तैल विषै लेप करै अरु छाय विषै सूरदल मलोर सा
थ लेप करावे ९२ चौड तैल मिल कर खी हडी यां के मध्य
की लाख व रोजा गुड मखीर राल १४ १ नां को पीस के भं
डे वट लोही के विषै तपावे ९४ यह तप जावे पादतल वि
षै इसका सेक देवे वैद्य जितना चिरना पकाएणा करे या है
उ होजाएणा के करावे ९५ पहले चूर्ण अरु काथ १ नां करके
उपरंतैं चर्म के खंड साथ बंधन कर देवे चौडे के पादतल को

काशीशलोध्रकटुफलनीचूर्णैस्तैलेन पादतले
लेपनयाशोऽइणाचगुके चूर्णलेपनं कुर्यात् ९२ श्री
ततैलं व सामज्ञालालाशीवेष्टगुडमधुमिश्रैः स
मेरसमद्रुतैः पिष्टैः स्वरितैः स्थालिकायां तु ९४
तमैपादतलेतलतापं वा सकारयेत्प्रातः ताप
स्तदयामाज्ञात्वा ज्ञात्वा कर्म कुर्वीत ९५ पूर्वं क
षायचूर्णैर्वभीयाच्चर्मणा तलवासः स्विन्नैतले
कषायेणवेपयेद्धि स्विन्नं तलजातं ९६ तैलं चो
त्रपानं खादनमत्रप्रदापयेद्वैद्यः तललंगी
भवति ततो निरुजं खलु कर्मयोगेन ९७ इति त
ललंगीचि· पवनकफकुपितसंयोगसमाश्रितः क
ण्टकासकावा सूक्ष्म जनयेद्ध लंगितं इति ततः
कण्टकांतयां ९८ स्थाने प्रसार्य पादतिष्टत
स्तु ततः खराग्रेण ·

सोयस्त्रिवस्वेदउ
नवकाथके
क सोव फेर पादतल कीयां नाडीयां को वेधे ९६ फेर
तैल अरु उसर पान यो है दाणा खाणा इत्यादिक उसा
वे वैद्य १ नां उपाओं करके निश्चे तैल लंगी रोग स
ली होता है ९७ इति तललंगीचि· वायु कफ संयोपा
ए जंडा कांटा उ तिस विषे स्थित होयादा चोडे के पा
द विषे लंगा करदा है और कण्टिका स्थान संवस
थि को नड कर देता है ९८ इस स्थान विषे संय को वि
ना के चोडा सब के भार खडा रेहा है पहे निश्चाने कचे

भा०
टी०
२२८

219

गिरेहैं लिंगीकेलक्षणकहेहैं कृच्छिकालिंगीबीश्नकोक
हतेहैं ९० इसमंग्रादिविषैमालसकरावै फेरपत्रभंग
योसेदसेककरेया सोकरावै ग्रोरयोगस्थानेलिनि।
त्वोहै सोनसवारग्रोरमर्दनविषैयोडे ९१ ग्रोरतिस
कोंसिद्धार्थादिसीलगमेकरकेवंधनकरावै बाहरके
ग्ररुग्रंदरकेदोनोविषैं तिसकीयानाडीयोतेरुधिर
निकाले ९२ योगिरेंतेउपरशोथहै केतुणनामनाडीवि
षेयोडेकों तिसकेतणमें परमासेकमर्दन योपहलेकहे

पथ्यश्वल्लकृच्छलिंगीकृच्छिकालिंगीतिवाग्रोके ९
ग्रादौतस्याभ्यंगंकृत्यात्स्वेदंवपत्रभंगेन ततस्ता
घमस्यतैलेनतस्याभ्यंगेप्रयोक्तव्य ९१ कृत्यात्सि
द्धार्थादिघृतसवोसमुपनाहनंततस्तस्य वाह्या
भ्यंतरयवविरेवयहेसैयथिकेवक्षिर ९२ उपरि
शाकुचेस्यतयःशोथःकेतुणग्रिमोस्वस्य सोके
ङुरेतितस्यास्वेदाभ्यंगौतस्वौकृतौ ९३ परंतु
लोनविरेतसिद्धार्थादिसमुपनाहनंकृत्यात्रुधिर
ङुतेतिसम्यकनतस्यथिकेचवोध्यः ९४ इति
कृच्छलिंगितचि० यस्याथिकेतसंयोकठिनेपा
षाणवद्भवेत्सोस्थि ग्रष्ठस्थितदेवौकेतस्या।
युपनाहनंएवं ९५ तस्यस्वेदस्वेदाश्चवेष्टना।
चैवकार्यन्मतिमान् यदितेवंशमंयातितन
क्रियाकार्यचेया ९६

याहैं सोकरावै ९३ ग्रंतरविषैं पाणदपत्रदेकरकेफेर
सिद्धार्थादिउपनाहवंधनकरै रुधिरहल्लीनानिकल
ग्रावै नवमूहसायकोजाणलेवै ९४ इतिकृच्छलिंगिन
चि० जिसघोडेकेसंथिनाउस्थानविषै वडीकठिनपथ्थ
रकेसमहडीवधीहोईहोवै सोग्रष्ठस्थिजिसकोकह
कहतेहैं तिसकोएवंविधिवंधनकरावै ९५ ग्रोरस्वेद
घृततेल ग्रोरस्वेदसेक एकोर उपरतैलपेरणा वृद्धि
वानकरावै इनोंकरकेयदनारानीहोवै तोफेरपरैरा
चिकित्साकरावै योग्रागेकहियाहै ९६

© Dharmartha Trust J&K. Digitized by eGangotri

क्षीर तरू वडी वड ऊंबल पलाश बेंत पारस पिपल ।
इनांके क्वाथ छान बनावे तिसकर के मल्लथें त्रबनाय
लेवे तिसके वीच कपडेकी यांटा की यांटा की यां दे कें
अथ अस्थिवधि होइ अस्थिको वेधन करे ९७ तिस विषे
पवन्चाय ह्रोण योदारणीय व्रण विषे चिकित्सा कही है
सो करे ९८ इति अथ अस्थि चि० तिस घोडे का जानु सने
अथवा सकजावे अथवा आकडजावे अरु वारले देह
को हरना वा लिखना करदा है सो जानुलेगि कहिया है ९९

हिंदलेनीरीतरूमयं कार्यं वैमल्लाय त्रकेतेन
वीरणभेणतनः कुर्या अस्थिवेधन ९७ तत्रव
णोनुजाते सदारणीयेव्रणोपक्रमः कार्यः य
द्येवेनोपशमेदग्निः परमाक्रियाकथिताः ९८
इत्यस्थिचि० घ्नतेले विगुण्यनेवासत्वेवा
जानुयस्य तुरंगस्य हतनिचवाह्यगात्रेसजानु
लेगीविनिर्दिष्टः ९९ तस्याक्रियाविधेयाक
थितायाकुर्वेलंगिनोथस्य पात्रेयवेहृष्टके
यीतस्याग्निकर्माणि १०० इतिजानुलंगित
चि० पतनादभिघाताद्वायामाद्वाप्लाय्यवा
यतस्तु प्रस्तब्धएवकायोगुरुक्रमः कास्तने
स्पर्शम १ दुर्गंधमल्लवलातोनाम्नास्याम्भांश
वनेनेचापि तस्मुरोलंगिनमष्यविघ्नाद्वरा।
स्नापिनेवापि २

तिसको योकुर्वेलंगित विषे विधि कहि है सोसभ
करे अरु पात्र स्थान की यां नाडीयां विषे वेधकरावे फेर
अग्निकर्म ली कदा हकरावे १०० इति जानुलंगित चि०
योघोडे को डिगने ते अरु चोट लगने ते वा वहुत धाया
म लेदने वा वा युडत्पन्न होके अकडगया है अग्रका पूर्व
भाग जिसका अरु वहुत भारकरगलि हरएण अरुवे।
गवहुत होनी १ कफ दुर्गंधि वाला होनो नासांते चा
लना है तिस घोडे नू उरलेगि जाणी अरु उरस्ता पिवी
तिसको करते है २

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा॰ हो॰ २२०

तिसकों स्निग्धघृततैलादिकीयांमर्द्दनकरे अरुभो
जनवी स्निग्धकरावे रुमपानवाभुवावे अरुपरहे
छातीमेंरुधिरछुडावे २ रुधिरकढेहोपछोडंकोह
सोदिनविषे तेलजल मुनका मखीर छेडरावै पान
केवास्तेकाढदेवे ४ परणदेबीज सरेयां यउ तिलके
एक सहांजणा खल इनाकोपीसकरके सीलगमले
पकरे अरुसकीमर्दनकरे इनोकी ५ मदु अंवलवे
नीरा विल्वतगर इनोकेसाथतेलसिद्धकरे परेचोर

तस्याभ्यंगास्निग्धाःसुस्निग्धंभोजनमुत्तमम्
उरसिचरक्तस्रावस्तेषांसर्वाक्रियाकथिता १
तैलंतोयंद्राक्षामधुसर्पिःफाणितंचपानाय
अपरेह्निदानंत्वंविसृतरक्तस्यवाहस्य ४ प
रंडबीजसर्षपयवतिलगोधूमशिग्रुकिराव श्री
पिष्टैश्चतैःकटुस्नेःप्रदेहपरिमर्द्दनेकार्यं ५
दध्यम्लकोलमोरटविल्वतगरैःसघृतंपचेत्तै
लंनत्कृततोस्यदेयंमांसरसैर्भोजनंचैवविहि
तं ६ नस्यंवस्तीचभोजनेनैवदापयेन्मतिमा
न् यथैवंनसुखीस्यात्तदाग्निकर्माणिकुर्वीत २
इतिउरोलगिताध्यायः वायुःकुपितःस्थाना
न्यस्तोऽसमस्तपुषपृष्ठेतस्य अथमथवांशाकृ
टविनष्टेनतस्यपूयेद्दा ८ प्रोक्तोस्तसोमल ।
मीनस्याभ्यंगादिकाक्रियापोथी

कोथोडादेवे ९ जैहे
ल्लेहयोएवंकहियाहे सोनसवाखविस्तिपछकारी अोर
खोनेकावैद्यचतुरदेवे यदइनादिकीपछेडराजीनाहो
वे नोपेरअग्निकर्मदागलीकरदेवे १ इतिउरोलगिता।
ध्याय: वायुअपणेकोपकेकारणोंकरकेकुपितहोके
अपनेस्थाननैं तिसअसवारविषेवा किसीभागमें प्रा
महोवे होइकेसोस्थानसकजाताहे अथवाअसतेनो
ताहे सोअुप्रासलगीवोडाकहियाहे ८ तिसकीपरले
कारणकहिहे यहइसकारवेराजीनाहोवे नोपहे

220

© Dharmartha Trust J&K. Digitized by eGangotri

चिकित्साकरावे तिसकोपाखसाथ भेदकरकेछेद
करे तिसकोंवाग्रकरकेभरे फेरसिंककेसाथचन्नर
वैय उसकोदग्धकरावे १० जिसघोडेकापिच्छलापा।
सासुकहोयाहै तिसकीसक्थिस्थान ओडेकेपासकीप
रकाजोड तिसविषे भेदकरके वायूसेपूरणाकरके चर्बी
साथसाहहसेकदेवे ११ यदपूर्वभागसूकजावे तोचित्र
स्नेहकीनसवारफडावे यदपश्चिमपिच्छलापासाशुष्कहो
वे तोचित्रनस्नेहकीपछकारीफडावे तबघोडानिरोग्य

पूर्वंयदिस्त्रवीनस्यात्ततःक्रियांकारयेच्छेनां ९
गात्रविशुष्यमानेपिभित्वाशस्त्रेणकारकेशाहृ
ग्रे वातेनपूरयेत्तेनतोदद्द्यात्मेदसानिस्त्रुनः १०
शुष्कपश्चिमकायेपिसक्थिपरभेदनंकृत्वातु
वातेनपूरणंतत्रमेदसाचैवदाहस्तु ११ एवं
गात्रेनसंनीणगात्रेनपश्चिमेवस्तिः चित्रा
तेनदानयोभवेत्सरोगीततस्तैव १२ ग्रंशाल
गितात्प्रायुः श्रोणीत्रिकदेशोवायस्यसमीर।
णेनवाध्यतेयस्य विकरःपश्चात्स्खलतिव
कंपतिवैपश्चिमोपादो १३ प्रस्तव्यसथिश्च
संथिस्त्रिकलंगीस्पष्टकीर्तितोनिपुणैः तस्मा
श्रंगःस्वेदोविध्येवोपादजेवंसिरे १४ दशमू
लस्यकाथोविस्वकणगौरसर्षपपूर्तः विस
ष्टलवणपनतपश्चात्त्रिगधोसःस्यात्त्रिकहस्त १

होजाताहै १२ सनिधमांसलेगितात्प्रायः जिसघोडेके
पश्काविकस्थान नेचा श्रूरुलककाजोड वाग्रकरकेपीडि
तहोवे तिसकापिछलापासाविकृतवेडाहोताहै श्रूरु
त्रिगड़ाहैसेव यथार्थंनहिंपाँदा श्रोरपिछ्लेसेवपर
डेंदेचलदेहैन १३ श्राकडजांदेहैन संधिजोड पिठत्रिक
कोत्रिकलंगीछोडा वनतेनेकहियाहै तिसविषेमालस
स्वेदसेककरावे श्रूरुडपांउसक्थिकीसंधिकीथांनाडीयां
विषेभेदकरे १४ दशमूल बिल्व श्रग्निमंथ हांरस कशीर
पारल कंडचारी २ प्रस्कपी दम्बार भरवेडमडमनी० ॥

© Dharmartha Trust J&K. Digitized by eGangotri

सेनी सरियां अगरत्मूण मैं धव पाइके से ह तेल घृत
मिलाय सीलगमें निरूवस्ति पक्वकारी कराडे १५
अथवा दिग्रार रेसण चीउ मुलठ इनां को मही न पीस
के दूधमिलाय स्निग्धकर पक्वकारी कराडे धोडे के
घास पालिहोत्र संयुत के जाणने वाला वैद्य १६ फेर वा
युके हरणे वाले ये घृत तेल है तिनां करके पक्वकारी सें वे ह
अरु धान्य प्रदेह लेप अरु स्निग्ध सेक कराडे १७ यदि इनां ते
सुखी ना होवे तो उपरंत अग्निदाह कराडे अर्थ रेखा त्रिक

अथ देवदारु रास्नाशल्लामधुकैः सपिष्टैर्नरैभि
लीरघृतैः स्निग्धोवस्तिर्देयोऽश्वशास्त्रैः १६
ततो वातहरैः स्नेहैः वस्तयः सुः सलवणाः धा
न्यप्रदेहान्नुसैः स्निग्धास्वेदश्चप्रशस्यते १७
यदि सुखी भवेन्नैवमग्निकर्म ततः परं लेखा
तिस्त्रस्त्रिकेकार्याभासेलसंयेपवाहि १८ त्रि
कपिंडयोरुभयतः रवेन्नैरीमस्त्रिवेशयेत् त्रि
कलंगीचि॰ उभलंगीतिविज्ञेयाविच्छिन्नग
तिमाश्रयः विषमंक्रममाणस्यहूषणः स
दतेपिच १९ तमुभयलिगिनंज्ञात्वाअभ्यके
सदयेत्ततः निरूहाद्याः क्रियाः सर्वकार्याःश्वो
नुपूर्वकाः २० त्रिकलंगिनियाश्रोक्ताविस्ता
णेष्वाग्निकर्मत्रि पदंगात्रंविदाहोस्याधेनगा
त्रेणलंगतिः २१ उभयलंगीचि॰

दूपरकराडे १८ अंडकोश अरु त्रिकटकविषं रवेन्नर
के समकरे दाह १९ इति त्रिकलंगीचि॰ जिस घोडे की
गति भंग दूरन नहि होवे विषम करे मार्गविषे अरु
अंड हूषण नल सक जाण तिसकौं उभयलंगि जाण
तिसको मालसकराके फेरसेक टकोर करे अरु योग।
वे त्रिकलंगिन विषे विधि कहि है सो सब कराडे अ
रु अग्निकर्म विशेष है जिस स्थान विषे लंगाहोवे ति
सविषे लीकपाणी २१ इति उभयलंगिनं चिकित्सा।

© Dharmartha Trust J&K. Digitized by eGangotri

गोडेवा गोडेहेठयोलंगाहै सोवायुकेकोपतेहोताहै सोजं।
घाको किंचानहिंकरसकदा अरुस्थुरासंधिआकडजातिहै
अरुजेघायपीडदाचलदाहै २२ स्थुराकेलंगितमेंसरीरआ
कडजाताहै अरुवडेयत्नसेचलनाहोताहै अरुचक्रसक्थि
पटाकेहेडगोडेकीसंधि इसविषेंवीयोलंगितहै सोस्थुरा
केसमकहेयाहै २३ तिसविषेंस्वेदकरमालसकरके जिस
स्थानविषे उससजगाविषेरुधिरकढणाहितकरहै औरेल
पस्थानवस्ति अरुअन्नकेचूर्णकारकेबंधनकरावे धान्यचूर्ण
एवंविषेलिखोहै २४ स्थुरासंधीविषेयोदाहदेणा सोविड

स्थुरायाश्चक्रसक्थ्यावालंगतेवातकोपतः न
संकोचयतिखंजो स्थुरासंधिप्रकर्षति २२ लं
गितेस्वेदमगात्रस्य स्थुरायाश्चासौ गुरुक्रमः च
क्रसक्थिस्थुराजानंतस्यभवतिलंगिते २३ हि
त्वाभ्यक्तस्यतस्यापनगात्रे स्थुराविस्रावनं हि
तं प्रदेहास्थापनेवापिधान्यचूर्णोपनाहनं २४
स्थुराप्लीतरेलेखा विद्धवस्थापिप्रशस्तिताः सर्वे
षामेववैषांतलंगितानामभिधीयमानानां अभ्यं
गायैकमभिर्त्रिःपरमाक्रियाकथिता २५ इति
चक्रसक्थिलंगितास्थुरालंगितचिकित्सा अ
यमेडुकाविविरोजायतेदर्भमूलवद्यस्य पा १९
देषुतीरिकायांचदर्भकीलास्वतविधान्
मांसपादतलेयस्य हण्णवत्संप्रकाशते स्प्रस
नस्तीयतेक्रियाभिः सनसिध्यति हणिकीवा
हः २७

कीन्याईहुआहै अरुयोसमभनरोयोलंगितलंगाकहेहैं
येमर्दनादिउपाओंकरके शमनाहोवे नोतिनोंविषेंअ
ग्निदाहलौकपरमेष्टचिकित्साकहिहै २५ इतिचक्रसक्थि
लंगितस्थुरालंगितचिकि० जिसघोडेकीमेंढूकीकापा
दकेतलकाविवरतिसमैंदर्भकेमूलकीन्याईहोवे तिसि
काविषेंदर्भकीलजाणे २६ जिसघोडेकेसंवरेठ हणित
गलवे सोचिकित्साकरावे सिद्धनहिंतो सोहणीकीघोरा
कहेयाहै २७

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ जिसघोडेकेपावोंकेहेठवालोंकीनसां रेखोंस्निग्धांकरके
हो॰ भरेयाहाहोवे सोघोडाकेशीकहियाहै अरु उसकोंश्रवण
२२२ तेस्रावकीकुहतेहैं २८ जिसघोडेकेरोमांत सवसंधिविषें
२२२ लोहेकीडुंकरीसम वा भेड़केसिरसमगंडीकरडेआहोवें
उनाकोप्रकोटकाकहियाहै २९ एवंविषेंयोंअपथ्यकरेहैंन
तिनाकरकेवायुकोंपकरगात्रशरीरघोडेदेकोंसुकादेताहै १॰
है तिसतेडुरननहिंहवा तिसकोवायुलगिनकहतेहैंन
अरुयोघोडेकी आग म्लान मलिन विकृतहोइहै अरु
गलनाडीउलटीयांकाडीफिंकगेइजिसकी सोअपस्मा
केशानिभैःश्रोतोभिःपारतलेयस्य स्रुतेस्रुतेः
केशीसविनिर्दिष्टःस्रावाद्वा स्रावकीप्रोक्ता १
मेषशिरसासमानारोमांतेष्ठीलसमन्विताश्वा
पि येंग्रथयस्तुकठिनःप्रकोटकास्तसमाख्या
ता २९ अपचारैःसर्वोकेवायुर्गात्रविशोषयेद्यो
स्य हरतिन्नजसंगात्रेसवायुनोलंगतेस्यये १
आमम्लानभवतिहि मस्यावर्तनेयस्य सो
पस्मारीकथितःप्रतिकर्मकथिततविद्यतेत
स्य ३१ वेपस्यवाहानोवायुस्साराःसुमतेनतेरगस्य
गजामस्तभावकस्तुभवेत्तमणशुंकविजानी
यात् ३२ भग्नस्तुसंधिदेशेषुसंधिभग्नोहयो
विनिर्दिष्टःलुगतकेउगकासिध्यतिनहि
शास्त्रविच्छिन्ना ३३ वंधाभिघातपतनैयस्य
सस्तेसरोहिणीसंधिशुकस्यात्॰
सिघोडाकहेयाहै तिसकीचिकित्सायोएवंकहिहै
सोईजानो ३१ जिसघोडेकावधेहोपवाचलतेहोप
वाडरउनरतेया अरुहाथीकेसंडकीन्याईहोताहै तिस
कोप्रणशुकजाणलेवे ३२ जिसघोडेकीसंधिजोडस्थान
भग्नहेयाहै सोभग्नसंधिघोडाकहियाहै लगकेअंत
वाकडुराशास्त्रकरकेकरेहोयांसिद्धनहीहोताहै ३३
वंधनकरकेवा चोटलगनेकरके वा डिगनेकरके य
© Dharmartha Trust J&K. Digitized by eGangotri

खिसकजातीहै संधिस्थानतिसकों रोहिणीसंधिमुक्त
कहतेहैं १ तनेचोडेयोंकों असरोगकेकहेहैंन १४ वात
पित्तकफरक्तकुपितहोयके स्नवकेपिछलेपासेपांसी
मांजेकेउपररोगहोताहै सोनाडीमार्गविषें प्रवेशकरके
वडीपीडाकोपैदेकरताहै १५ तिससेस्नवकीसंधिको
छुणनहींदेता अरुकालारोगहोजाताहै अरुस्पर्शविषें
गर्मअरुचोडेकोंदमज्वर संताप दाह चैली भ्राम मंदाग्नि १ ९
एकछिद्रनाम स्नवकेगिडेहोयतेहोताहै औरस्नवकेजो

एतानितरगाणामेंस्नारोगानिविधनेचैषां १५
पित्तास्रककफवाताः कुपितारोगोमस्पार्श्वशी
र्धैन स्रोतोमार्गगतास्तेजनयंतिवेदनांतीव्रा ११
छिद्रसंधिदुःस्पर्शःरक्तकृसोथवाभवन्मलाः
स्नासोज्वरोभितापःस्वेदासामामंदाग्निनावे
व १६ छिद्रःछिद्रस्सपतेनछिद्रसंधौचक्रवा।
लिकाग्रंथिःकठिनस्नपार्श्वशीर्षेग्रंथिस्त
विडाकोत्तेयाः १७ छिद्रसंधिगतारोगाह्येते
योदारुणासमाख्याताः छिद्रस्रचक्रवालिवि
डालिकावेल्तीयेन १८ आदौक्रियात्तशिरा
सेधामूत्रमेकुर्यात् क्षीरतरुत्वग्लेपान्सुशी
तलान्कर्मेनस्रैव १९ मंदोवस्तिनसंविश्रा
वपिच्छिलैचैव यावत्पक्काभिताश्रयरक्तव
रोविनिर्गतस्यात्.

डविवें चक्रवालिकानामग्रंथिगंडहोतीहै वहुतकर
डी औरअंडीकेसिरउपरगंडहोजातीहै तिसकोंविडालि
कानामजाणलेवे १७ स्नवकीसंधिविषेंप्रामहोयदेत्रय
रोगवहुतदुःखदायककहेहैंन छिद्रस्नचक्रवालिकाविडा
लिकातीसरीकहीहै १८ तिन्होंकेहुदेसावहिनाडीवेधक
रादेवे अरुयोक्षीरतरु वडीवड पेपल पलाख वैंत वा पारस
पिप्पल इन्होंकेसिकडीकालेपकरावे औरयेशीतलक्रिया
हैसोकरावे अरुसीलगमपल्लकारीयां नसवार रुधिरहुगना

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
टी॰
२२२ अरु पिछलेवस्तियोंकहिहै सोकरावे जितनाचिरप
कीनहि यह पाकजावे तोकठाके अरु हमसेखूनिक
सदाहै तिसकारणते एहरोगयत्नकरसाध्यहै इतितरु
लेगिनाध्याय: चोउ अंकेसवोकी वडीप्रकारकेपार
223 रोगहैं सोरोनरोंकेहैन एकसहजजन्मतेंहोतेहैं अरु
एकदोषजवातादिदोषोंकरकेहैंन सहजसोलांप्रकार
केदोषोंतेषोडशप्रकारकेहैंन ४॰ एकनीवपाणि उमक
ज्वर: इन्द्रपादी कंडेवक: उत्क्षिप्तनल मंडूकी वाह्यसन्नता

तस्मादेतेरोगाउपायतः:कालसाध्यास्तु इतित
लेलगिनाध्याय: द्वात्रिंशन्मादरोगास्तु द्विवि
धाजन्मदोषजा उसमाषोडशप्रोक्ताःविका
रैःषोडशापरे ४॰ नीवपाणिर्मसूरज्वरःइन्द्र
पादीलकंटवक: उत्क्षिप्ततलमंडूकीवाह्यांभ्य
न्तरसन्नता: ४१ वाह्यानोयेनिहृतास्तनथैवाभ्य
न्तरोन्नता रोमांतेषुप्रथमसंहृता उद्धृतास्तथापरा
परे ४२ उद्धृतायेचसंहृता हीणास्तथगोवहि
दीर्घवलिव्रिगोयेवकपालतनकास्तये ४३
षोडशैतेसमुत्पन्नास्तरोगानिहिताज्वराः दोष
विकारान्वक्ष्यामि पारानाषोडशापरान् ४४
पुनःज्वरोभिन्नज्वरःस्तथायश्चकंटवकः
मंडूकनाभिदर्भोवहृडोदंतपदस्तयः ४५
करीरफुफुसंतस्थचर्माकाभिस्रावकेसाही उ
त्क्षिप्तोउद्धृतस्तथापांशुज्वरोपरः ४६

भ्यंतरसन्नता ४१ रोमांतसंहृत वाह्योनिहृता अभ्यंतरो
न्नता उद्धृता ४२ उद्धृतसंहृता हीणसंहृत दीर्घवलि।
ज्वर: कपालतनक ४३ एहे षोडशसोलांसवोमें सहा।
जरोगकहेन अथवयेदोषोंकरकेविकारहै संवोविषै
सोकहनेहां सो होयसोलांहैन ४४ पुनज्वर: भिन्नज्व
र कंटवक मंडूको नाभि दर्भो हडो दंतपद ४५ करीर फु
फुस हणा अभिस्राव उद्धृततल पांशुज्वर ४६

© Dharmartha Trust J&K. Digitized by eGangotri

चर्मपाद मरुतल येहसोलांप्रकारकेकहेहैं येहरक्तकर
केहोतेहै अथवा खोटेस्थानमेंयत्नतेहोनेहै ४७ निरंतर
घोडयोंकोहोतेहैं जैसेकाष्ठादिकविनाअग्निहै अरुजैसे
पक्षविनापंछीहै ४८ जैसेदंतोकेभजेहोयसर्पहै तैसेही
पादोंकेरोगकरकेघोडाकहियाहै अवदोषजकेचिन्हलक्ष
णकहतेहै विशेषकरके ४९ जिसघोडेकेपुरातनखुरमें
नवीनखुर फेरहोरहोजाताहै तिसकोपुनखुरी याणलेवे
अरुखुरकेभेदतेभिन्नखुरीकहतेहै ५० जिसकेखुरके

चर्मपादोमरुतलेभविकारा:खलुषोडशा: शो
णितानिक्रमादेते उ:स्थाननीअस्थसनोपि
वा ४७ अविविक्तस्यवाहस्यदोषाउक्ताभवा
नितिहि यथाग्निरतुपादानो यथापक्षीविपक्षक :४८
भस्तदृष्टोयथासर्पः पादरोगीतथाहयः दोष
जानांतलिंगानिवर्तन्तेनविशेषतः ४९ न
वः खुरोयस्यखुरेपुराणमभिवर्तते पुनःखु
रीतिविज्ञेयोभेदाभिन्नखुरोमतः ५० तल
मांसोद्गताश्चैवकंटकसमोपमाः ग्रंथयः
कठिनायस्यज्ञेयः सोश्वकंटको ५१ यस्यदो
षप्रकोपेणमंडूकीहृपतप्यते अंगुष्ठेनतमे
यस्यमरुभूतेतलमध्यगा ५२ मंडूकतापीविज्ञे
यासाध्यातेनचिरोत्थितः कंटकक्षणरश्मा
वातलेयस्यभिन्नानिवै: ५३ अभ्यंतरविपच्येत
सुचारतनपरास्तसः

हेठमासकामहत्तकेपक्षकेसमगंडकरडी होवे सो
घोडाकंटककीजाणे ५१ जिसघोडेकी दोषोंकेकोपक
रके मंडूकीपादतलविषेसंतापहोवे अरुअंगुठेकरके
नवेनहीलेवे अरुपादतल वहुतकोमलहोवे ५२
उसकोमंडूकतापीजाणलेवे सोयदचिरकेनाहोए तो
साध्यहै अरुचिरकेअसाध्यकरहैहैन सोकंडेकरके वापा
ण्यरसाथ जिसकातलभेदकोप्राप्तहोवे जिसपयते ५३
जिसकाखुरकेवीचमेंपापावेवेसोसुचारतपदकहेयाहै

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
२२८
224

जिसके पदके तलविषे मासके अंकुरों करके सारे व्यापत
होवें सो करीरतरक कह्या है ४० व्रातादि दोषों के कोपते
जिस घोडे का पादतल पक जावे सो फुफ्फुस है अरु फुफ्फु
सके समम ंडूकी कहि है फुफ्फुस नाम कहते हैं ४१ जिस
का पादकातल कठिन मार्ग विषे घोरेउ या जावे सो छुष्ट
तल होता है जिसकी मंडूकी ते वहुत रुधिर निकलने ते ४२
जिस विषे सो जे की न्याई योउठिया है पावतल सो उद्धूततल
है जिसके पादतल विषे पामशील करे सो पामखुरक है।

यस्य पादतलं सर्वं करीरैर्मांससंभवाः। व्याप्तं वै
तिस्समेनाहुः सकरीरतलो भवेत्। ४० दोषप्रको
पात्तु तले पच्यते यस्य वाजिनः। फुफ्फुसस्य व
मंडूकी फुफ्फुसं तत्समुच्यते ४१ मार्गेन्नु विषमे
वृष्टःस्तले छुष्टतलो भवेत्। शोणितान्निष्क्र
माद्यस्य मंडूकाः सकलाभृशं ४२ उत्तिष्ठति य
थोच्छूना सेन्तु द्धूततलो भवेत्। पामस्य सततं ले
यस्य स पामखुर उच्यते ४३ तलमांसक्षया
प्राप्ति चर्मपादतलो भवेत्। मृदुवसूननाय
स्य पादाः समृदुपादकाः ४४ हिंडिवीचापि
कीटभी केणी वा सावकी च यः। एतेषां लिंगि
नाध्याये लक्षणं समुदाहृतं ४५ मर्दनस्तव
रायेषां रोमानेस्याततिस्मृतः। मृदुवश्चर्मपादा
श्च उद्धूतावलिनाश्रये ४६ उदरस्यकाभिन्नखुरा
क्रष्टिका सतन्त्रताश्रये ग्रन्थितरोत्रनाश्चैववाह्या
हृतनामलयेव ४७

सके संवके तल
या है ४३ अरु जि
हे ठन मास के क्षय होने ते जिसको चर्मपादतल कहते हैं
जिस घोडे के पाद कोमल नर्म अरु उथे होवे सो मृदुपादक
कह्या है ४४ हिंडिवी चलिकी टभी केणी आस्रावकी ३
नों के लिंगिनाध्याय विषे लक्षण कहदे हैं ४५ जिनों के आव
रण करयुक्त संव है अरु रोमान स्थान विषे अंतरगत है जे
अरु मृदुपाद चर्मपाद उद्धूता येवलि नये हैं ४६ उदरस्यका
भिन्नखुरा क्रष्टिका सतन्त्रना ग्रंथितरोत्रना वात्यहना ४७

© Dharmartha Trust J&K. Digitized by eGangotri

इतने पाददारोग असाध्य कहे हैं अरु बाकी के ये पाददारोग हैं इन
तिनों विषै तैलताप स्वेद विषै सेक हित कहे या है ४८ अरु
ये इनकी चिकित्सा लंगिताध्याय विषै कही है सो सब इहां
वी करे गो का शृंग की त्वचा दग्ध करके अरु भलावे दे फल ४९
इनों विषै मखीर रला करके इस करके पाद तल विषै लेप क
रावे सर्जरस शाल स्यपके क्वाथ करके थोके चर्म साथ सेवा
विषै वमन करावे ५० हरड बहेडे आमले खैर कथ इनों को गो
मूत्र के साथ क्वाथ सिद्ध करे अरु तिहि क्वाथ विषै तेल को

एते पादविकारास्तु असाध्याः परिकीर्तिताः शे
षाणां पाददरोगाणां तैलतापोहितो मतः ४८ य
दुक्तं लंगिताध्याये तदिहापि हि कारयेत् गो
विषाणत्वचं दग्ध्वा भल्लातकफलानि च ४९
तैलेन सह संयोज्य तलमस्यापलेपयेत् स
र्जस्पन कषायेण हर्णौ वयेदुपानहौ ५० त्रि
फलाखदिरसारैश्च गवां मूत्रेण साधयेत् त
स्मिन्कषाये पक्वं स्यात्तैलमभ्यंजने हितं ५१ तै
लं चोत्तरपानं च देयं मांसे च खादने पंचमूल
कषायेण शालिर्वा त्रिफलारसेन ५२ क्वाथेन त
स्मिन्मयोदद्यान तैलं विपाचयेत् कल्कपथ्य
समायुक्ते मेभि गोमूत्रसयुतः ५३ प्रियंगुक
टुफलैलो प्रदेवदारुहरेणवः मधुके च हरि
द्रे द्वे विडंगमरिचानि च ५४

पकायके मालसके वास्ते हितकर कहे या है ५१ अरु उपरं
तपान के वास्ते तेल देवे अरु खाणे को आमक चा अन्न
वा मांस देवे पंचमूल लघु का क्वाथ कालीवेल हरड ब
हेडे आमले अग्निमंथ ५२ तिस क्वाथ विषै दुग्ध पाय कर
के तिस साथ तेल पकावे मालकंगुणी को फल लोध्र
दिआर समलवीज मुलठ हरदल दाल हरदल वायवडी
ग मरिच इनों के कल्क करके गोमूत्र मिलाय तेल सि।
द्ध करे पहे तेल मखीर साथ उत्तरपान नाम तेल सेवो के

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ सभरोगवालेघोडेकों पानवास्ते देणेयोग्य है ५५ वाता
टी॰ दिदोषकोनाशकरताहै अरु देहकोस्थिरकरताहै बल
करताहै प्राणोंकोवीहितकरैहै अरु इसकेसेवनकरते
२२५ होयांभोजनदाणाइत्यादिकलूणसेहै परहेजमत्यागे ५ ९
अरु छिन्ननलघोडेकी चिकित्सा योमार्गछिन्नकीहै सो
225 यत्नतेंकरे ५७ पुनःखरादीनांचिकित्सा अथभिन्ननल।
वालेकी औरपांशुखुर औरमांसचयकिआवपनाणा ५८
योचलताहोयालंगाताहै अरु अडीकरकेचलताहै अरु

यत्नतोऽस्य समायुक्तं तैलमन्तरपानकं। प्रदेयं
वातिनोशस्तं सर्वपादविकारिणम् ५५ दोषा
पहं स्थितकरं बल्यं प्राणहितं मतं भोजनं ल
वणात्येहं सेवेतस्य विवर्जयेत् ५६ वत्ते छि
न्ननलं वाजि कर्मणा पथ्य यत्नतः ५७ पुनःख
रादीनां चि॰ अथ भिन्नयस्य तु नलं समति पांशु
भेवेद्वमांसचयः ५८ गच्छ लंगितमाप्नोति
पार्ष्णीशीर्षेण गच्छति वैद्यजनैर्हि कठिनो
भूमिपांशुखुरी सेष कीर्तितो निपुणैः ५९
पांशुस्यादतस्य हस्तकस्याविशेष्य मस्तवे।
ध्यानं लजावशिरान्नलनापः कीर्तितः का
र्यः सर्वक्रियाकथिता प्रशस्ता स्नेनवोत्त
याविनिर्दिष्टाः ६० पांशुखुरचि॰ अथ वह
नोदोषांधानि विषमे शर्करा पथ वायस्य ।

येमार्गकरडाहै तिसकोछोडदेताहै सोवैद्यवालेयो
ने पांशुखुरीकहियाहै ५९ पांशुपादवालेघोडेके
पादकोंसूद्करके फेरपादकेहेठकीनाडीकोवेधक
रे औरनलविषे योसकदेणाकहियाहै सोदेवे अरु
योसमनलरोगविषे चिकित्साकहीहै सोसभइसवि
षेकरावे ६० इतिपांशुखुरचि॰ अथयोघोडावहुतबडा
मार्गचलनेहोयको अथवारोडेवालेरस्तेचलतेहो
यकी मडूकीपादकानल सबकाथलासनसहोयाहै

© Dharmartha Trust J&K. Digitized by eGangotri

नवमंडूकनापिच्छोडेनूपानकरकेयोएवंविषेंचिकि
त्सा नलेनाप पादसेक इत्यादिक्रिया योलतितध्याय
विषकहीहै मंडूकतापसो सभकरे इतिनलपादरोग
चि॰ जिसघोडेकीस्कंधकेयोडकीसंधि वहूतनमीजावे
नेरछीगीहोवे सोवायुकेकोपकरकेहोतीहै सोघोडा
नतकुष्टिककहेयाहै सोसंधकेअग्रभागमेवडेडुखकर
केडुरताहै ९२ एवंप्रकुंजिकोख्या इसनेघोडाप्रकुंचिका
ख्यकहेयाहै संधिकेसंकोचहोनेकरके जिसकापाददुर
दाहोइआथरडेंदाहै वहूतपीडाहोतीहै तिसकारणक

मंडूकनापिनेनेतुरंगेतत्कालातनतोस्यएवै
कः नलतापःकर्तव्योयःप्रोक्तोलचिनाध्या
येमंडूकतापः एवंनलपादरोगचि॰ नाम
यतेयस्यस्कंधेकुष्टिकुसंधिशमीरकुपितः
नतकुष्टिकःसवाजीगछतिकृच्छ्रेणयेण
एवंप्रकुंजिकोख्यागात्रसंधिप्रकुंजनात्प्रोक्तः ९२
परिव्हास्यमाणपादस्तेनाख्यातोयनेसततं ९३
एनानिरहस्तसमीपस्यारोमानेकुष्टिकासमुद्
वेषु येत्रयःप्रकोटकसंज्ञास्तेवाजिनांप्रो
क्तः ९४ नेत्रेकुटिनेप्रलेवाभ्यातुसवेदनेय
स्य उभयेपिदिग्रहणेपसतत्पषनेचीसमाख्या
ताः ९५ एतेप्रायोपिरोगाअसाध्यनृपाक्रि
यातथाप्येषांकार्यासर्वेहृन्चैवेद्यैरोमान
योग्यस्थिरे ९६

घोडावहूतनलि सोहोजाताहै ९३
एरेत्रेष्ठिगोडीहस्तकेपास अरुरोमांनमें प्रकुष्टिका
संवसंधिविषेंकूचेगिटेइनांविषे इनांत्रेथीयांको प्र
कोटनामकहेयाहै घोडेयाके ९४ जिसकीयांनेत्रांकर
डीयांअरूपीडायुक्तदिखसकदियांहैन डुखदेहांयांकेव
हीयांपीडाकरे यदटोनोंइसतरांदेखीये नवतिसघोडे
का उपजेचीकहियाहै ९५ यहेइननेरोगअसाध्यवाले
कुहेहैं नटवीइनांकीचिकित्साकरे आदविषेंकूचेगिटे
कीयांनाडीयांविषेवैदकरावे अरूरोमांनकीयांनाडीयां
नेरूधिरकढावे ९६

© Dharmartha Trust J&K. Digitized by eGangotri

पा०
हो०
२२९

226

महा हरदल वाल हरदल अरु जेउ के पलास के बीज
कुठ सरेयां खल वावडिंग चित्रा अग्निमंथ हरवेगडी
ला तिल ८० तेल मज्जी चर्बी मठा १२ सिर घृत रक्त
ज्येउ मदिरा लूण सैंधा अकदेपत्र उपर देकरके इनांको
बंधन स्वेदन करके करावे १८ बेर कुलत्थ यउ कसीर
बिल्वकथ इनां के क्वाथ करके चतरवे घृत तेल पकावे
तिस करके घोडेको नसवार भोजन पान मालस बुद्धिमा
न विधि अनुसार देवे १९ यह इनां उपायों करके स्वेदना

मागधानसी हरिद्रे बीजानि शमी पलाशयोः
कुष्ठं सर्षपकिण्वविडंगानि चित्रकं चाग्निम
न्थतिला ८ तैलं मज्जवसादधिघृततैर्वेदं
चूर्णं स्यात् लवणं अर्कदलान्तरितं स्यात्तस्र
वो स्वपनाहनेनतत् ९ अथ कोलकुला
त्थयवाः कासमर्दो बिल्वपेषिकाश्चैव स्या
ज्ये च मूलमेभिः क्वथितैस्तैलं पचेद्धीमान् ११
तस्मात्तं नस्यं भोजनपानभ्यगे पुरापयेन्म
तिमान् यथेवं नस्वेदोस्मादग्निकर्म परमा
क्रिया कथिता १० वाह्रविदारणे लेखाभि
र्विंदुभिः कूर्चकपृष्ठिके अग्निकर्मकृतेनभक्ते
पूर्वोक्तं प्रतिपानकं ११ तेदेवबहुशः पुनः का
र्येनस्यकर्मणि वाजिनां एकचक्रे भवत्येव
स्वस्थीयस्यप्रकोष्टकी १२ इति प्रकृचप्रकोष्टचि

हो तो अग्नि करके दागली कपुआवे पहले अष्ट उपा
य किये है २० वाहु औ विषै रेख करके दाघ का
गावे अरु गिरेसवें व मथि विषै विंह करके द्रम्य करे
अरु अग्नि कर्म के कीये उपरांत भोजन देवे फेर यो
पूर्व विषै कह्या यो पान है सो देवे २१ अरु तिस विषै
फेर घोडेयां को बहुत नसवार देवे अरु प्रकृचक अरु
प्रकोष्ट रोगवाला राजी होता है २२ इति प्रकृच प्रकोष्ट
चिकित्सा ॥

© Dharmartha Trust J&K. Digitized by eGangotri

सेर घृत तेलादिनस्निग्धपदार्थपाकहोनेतें दुष्टरक्तक
रके ये दुष्टव्रणग्रायजंघाविषें पादसंधिविषें रहतेहैं
सोश्यानरुकनामकरकेकहेहैंन २२ मिलतहोष त्रिदो
षकरके घोडेकीजंघासवही हैरसको अरुसर्वंगेरतैंवा
लगिलेहोजातेहैं सोपहेलक्षणकरें सोदुष्टदोषतें उलू
कविषें देखीदहैंन २४ जिसकोपूर्वेलक्षणहोए सोघोडा
उलूकपादकहेयाहै अरुजिसकीजंघासोजनअरुफोडेकर
केयुक्तहोवे अरुज्वरकरकेयुक्त सोघोडा श्लीपदीकहिया

स्नेहविदाहाद्रक्तेन संप्रदुष्टेन येव्रणाड्ढा
जंघासक्रुष्टिकास्रवसति श्यानारुकसंज्ञास्ते २२
संनिपातदोषेण जंघाश्रवति सर्वतः क्लिन्ना
रोमाणि यथोक्तोलूकस्य संप्रदुष्टानिलक्ष्यते
२४ यस्य स उलूकपादी तेन विकारेणकीर्ति
तो वाह शोफस्फोटैर्जंघेस्य संज्वरैः श्लीपदीप्रो
क्तः २५ एतेषां वेध्या स्नेहकूर्च रोमान्तक्रुष्टिका
स्थिताः छिन्द्यात्तृणान् प्रदुष्टान्देहाच्च संशो
धयेत्ततः २६ प्रपुन्नाडकबीजानि सर्षप
मूलान्येतानि सूक्ष्माणि चूर्णानि गोमूत्रमर्दिता
नि तत्कुर्याद्धन्मर्दनं वाप्य २७ करवीरस्यतु
मूलं स्नुहार्कमालती प्रवालसंयुक्तं विल्वं
करवीरगलेपयेत्कषायेन तेन सततं व्रणंचा
स्य २८ कषायंनीरत श्वेतामूलानि च साधयेन्म
तिमान्॰

है २५ इनांरोगांवि षेंवेयकरावे छिद्रकेघा
यकोउष्णकोदग्धकरे त्यागोंकरके २६ हेडमाकेबीज
सरेयां सरत्यार इनाकोमहीनकरे गोमूत्रमिलाइके मर्दन
करे घोडेको २७ गडीलेकीजड अरुथ्यार अक मालती इ
नांकेपत्र विल्वअर्कगडीला इनांकालेप अरुइनकेका
थकरकेधोवे निरंतरघोडेकेघायताई २८ अरुली
रवृक्षकेमूलांकाकाथबनावे प्रातकालविषें गोमूत्र
साथ कटुतणपानकाभ्नेदेवे २९

प्रा॰
ह्रो॰
२२७
227

कुठ हिंगवावडिंग मरिच यउखार करीपथर पंजलूण
हरताल मनशिला पडे १० इनांका चूर्ण करके कौडे ते
लसाथ मालसवैद्यकरावे अरु यासमका खाणा कौडे।
वे अरुयाकटुमर्पि चूतएवंकहैयाहै सोपानकेवास्ते देवे ११
इतिस्यानरुकादिनांसामान्यचि० उलूकपादवाले यौडेका
पहिलेरुधिरकढावे फेरअदेहलेपभेदहितकारहै त्रिफ
लासोनोहरदलोंका १२ मकडेके लाणके सिकड अरुपत्र

पत्तागोमूत्रसमायुक्तंदेयंपानायकटुत्तृणं १
कुष्ठहिंगुविडंगमरिचंतथायवक्षारकासी
शलवणानिचहरितालंमनशिलाचैव १०
एभिःकटुतैलयुतैश्चूर्णैरभ्यञ्जनंभिषक्कुर्या
त् ग्रासमःपुष्कोदयःकटुसर्पिश्चैवपानाय ११
स्यानरुकादीनांसामान्यचि० एकावसेकमादौ
नरगस्योलूकपादिनःकुर्यात् पश्चाद्धिनःप्रदे
ह्यस्त्रिफलारजनीसमायुक्ता १२ नक्तपत्राणिक
रंजस्यपिप्पलीगौरसर्षपाः सैंधोरजनीपिप्प
लीमूलंवृषस्यपत्रंत्रिवृच्चैव १३ वहिस्तक्त्वीर
घृताववाचसेचूर्णैनैस्ततःस्यन्तोः लेपोगोमू
त्रयुतैःपुष्कप्रतिमर्दनंकुर्यात् १४ ग्रासवपत्रवदि
रयवासकर्णिकभाजांजनैर्गुदंत्वगाभिः त्रिफला
निंडुकफलपंचमूलस्यहितैस्तमपिष्ठैः १५ का
थितैस्तुगवांमूत्रेणतत्तास्मिन्वचनगुलेकाथ
तैलेसमस्यकविपचेस्यानांभ्यंगेप्रदेयंस्यात् १६

मथें मजी सरेयां संउ हरदल पिप्पलामूल वासांकेपत्र त्वची १ १
त्रिफला दालचीनी उष्य वेंच इनांकामहीनचूर्णकरकेगोमूत्रसाथ
लेपकरावे और इसकीसकोमर्दनवीकरावे १४ अमलतास
खैर पवहनसालभेद कुंभाम्भैनहूत माडी दालचीनी त्रिफ
ला कुचले पंचमूलकेतव इनांकापीसकरके १५ गोमूत्र
विषेकाथकोड निसचारगुणकाथविषेतेलहकीनरांपका
वे सोतेल पान अरुमालसकेवास्ते देवे वैद्य १६ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

त्रिफला निंबपत्र पटोलपत्र इनांके काथ विषे सिद्धं गौरि
नीहोइ और छेउ मखीरसाथ और मखां संउ मिलायके खोण
कोदेवे १७ उत्कपादवि॰ गंडीला सूर्यफुल्ल सोंचल साग
सहांजना कौड लोध्र विज्ञ मञ्जकेलण मघां कांई अशोक
वत्त मरिच १८ देवदार् काथाकोटी वसमा नेत्रवाला मरु
आवासा रक्तिका अग्निमंथ गंडीला १९ पहेसमभसमभागव।
गावर मसीनपीसनु गलाकरे तिसकल्ककरके चारगुणाते
लसिद्धकरे पहेतेलचाउ विषेदेवे मालसकरे पहेचायके

त्रिफलानिंबपटोलेक्वाथेसिद्धंक्षुभोजयेत्गुह्म
न्मधुसर्पिःसंयुक्तामागधिकाशृंगवेरयुतं।
स्यात् १७ उत्कपादवि॰ करवीरसूर्यवल्लीह
यमित्रुरोहिणीलोध्रैः चित्रककरंजपिप्पली
काशीशाशोकमरिचस्तु १८ सुरदारुकाक।
माचीनीलीपत्रैलवालुकासहितैः कटुफाल
नकवासाकाकदन्ताग्निमेथैश्च १९ सममा
गैस्तुसुपिष्टैःकल्कैःपक्वचतुर्गुणंतैलं मत
द्वयेणदद्यादभ्यंगेनपूर्णाशु ४० खदिरोरि
मेदवल्कलत्वचांक्वाथेनतैलपीमान् सर्वेमू
त्रैःसरितैतमथायसेस्थापयेद्भांडे ४१ नक्ति
नूत्रिपंगुरुकुष्ठमागधिकाचित्रकतथालोध्रंसु
रदारुकणामूललवणसिद्धार्थकाश्चैव ४२ ग्र
भूतरक्तसबीजंपिप्पलीनिंबस्यैवपत्राणि सर्वे
कल्कंकृत्वाविनिक्षिपेदायसेभांडे ४३

फुडाने वाले बहुत गुणकारक कहेया है ४० खैर लघुखैर
को गडु दाल चीनी इनांको काडे नेल विषे बुधिमान् पहेस
भगोमूत्रसाथ निसन्नू लोहेके भांडे विच पायके स्थिन करा।
केराखे ४१ अरु जिसविषे फलफरंग मालकंगुणी कुठ म
घां विज्ञ लोध्र देवदार पिप्पलामूल सैंधालूण सरेयां ४ २
हेडमादे बीज निंबपत्र इनांको पीस करके कल्क बनाय
करके समनांकों लोहेके भांडे विषे पायदेवे ४३

© Dharmartha Trust J&K. Digitized by eGangotri

निसकोंसनगाडीरखें फेरवारंवारलेपन करावे तवकंड
खरक योवर्णारोगकाविरोगहोना ददरी दारुणक कुष्टमे
दइत्यादिक औररोगोंविषेदेवेतोनासकरदेताहै अरुस्था
नरुकविषे वहुतगुणकारकहैयाहै अरुभोजनकेवास्ते ।
निकसुहसुंगी सुंठमरचोर घेउसाथदेवे ४५ इतिस्थानरु ।
कचि० एवंपादरोगाध्यायः जिसघोडेकीगुदा अपणेस्था
नतेचलतहोइदी जेरकीतरांलवकदिहै अरुयोगुदा ।
कीवलीजयहै सोडुलडुलकीन्याईलवदीहै येत १ घोडे

समगात्रेषुलिप्तेन भूयोभूयः प्रलेपनं कंडूविव
र्णतापामाददुदारुणकादिषु ४४ अयमेव
समाख्यातास्थानरुकस्याप्युपक्रमः भोजनं
निकसुहांश्च सविश्वामधुसर्पिषा ४५ इतिस्था
नरुकचि०। एवंपादरोगाध्यायः स्थानाभ्रष्ट
तगुदंजरायुरिवलंबतेन्नरोगस्य वलयश्च गु
देहूतालतेतेडुदाभासाल्न १ वातोद्भवे ।
विकारे गुदभ्रंशमाहुरश्वानां अथवापिनेपा
गुपवतितेदापितेजविघात २ एवंभ्रष्टंत
गुदंपयसाप्रक्षालयेत्ततः पश्चात् स्थापयेत्स्व
ते स्वकोसेप्रवेशयेन्मधुघृताभ्यक्तं ३ ततः
प्रोतेनानवमेणाहृतेक्वातेविदकुमस्थंवसा ।
मनातिवेगप्रणदेसनरेवत ४ प्रवेशयित्वा
तद्दस्तविदंतत्रैवकारयेत् नेणाकार्पासरज्जा
वातत्तस्लसेचयेद्दृढं ५

यांकायोगुद भ्रंशरोगहै
सोवायुकरकेकुहतेहैं अरुयोपित्तकरकेगुदापकदीहै
सोपित्तजगुदाभ्रंशजाणलेवे २ यवइसतरांगुदाभ्रंशहै
वोपे तवगुदाकोदूधसाथधोके फेरवोसकूंतविषे
स्थितकरके फेरमखीर घेउसाथमलके अंदरविषवाउ
देवे पीछेतेमहीनवस्त्रसाथलपेटदेवे अरुविन्नोगुदाके
मरवकेवरावरवनायके उपरदेदेवे फेरसतावीवाहरनानि
कलआवे ४ प्रवेशकराइकरके वस्त्रकीविन्नीरखके तार

© Dharmartha Trust J&K. Digitized by eGangotri

नारकरके वा कर्पासके पातेकरके वनदेवे फेरगुदाको
सेचनकरावे ५ जिसने वायु मलसवेकरके वोउभागे
ग्रहणकिहि और भासल गुदाके हेठकास्थानहै तिनोवि
षेविद्धकरके दाहवरउकरावे ६ जितना विरगुदास्थान
नेवलतनहै उतना विरपरेउपायकरे ग्रहस्थानकालवि
षैगौकाडुग्धकाउके ठाडाकरके पिलावे सोविष्टाकोवी
भेदनकरताहै ७ ग्रहहमारे दिनविषे निरूहकाथकोप
ककारी गुदभ्रंशमैकराउवे ग्रहस्थानवासनवस्तिमे स्वे

यथावातनपुरीषाणि प्रमुंचति मुखं हृदयः
क्लिभालसभागे गुदाहये ज्ञापि विद्धभिः ६
यावत्संभ्रंशप्रपने पायुस्तावद्देवसुपावरेत्
पानायगवांक्षीरंशीतं स्याद्धिप्रभेदनस्या
प्रातः ७ अपरे दिवसे कुर्यान्निरूहणं वै गुद
भ्रंशे अनुवासनेचसर्पिर्वातनहरैतौलमंत्रु
तैस्सिद्धं ८ तैलेनामलकं वा प्रद्दापयेद्योग
शान्तये गुदपाकेन कषायैः कुर्यादास्थाप
नेभिषक्मतिमान् ९ देयाश्चपयोवस्तिः स
मापृतः सौर्हमर्पिर्मापा येग्रामेनाद्यनेवाले
नेतवीजयेन्मसायाने १० तमस्माश्चविजा
नीयान्मूत्रपुरीषनयः कुर्वते इति गुदभ्रंश
चि० योनिभ्रंशाख्यनन्येयच्चातिभारपीडिता
स्त्रीमलानाञ्च:

हकीपक्ककारीविषे छतवानहै औषधीड्पमाथ्यसिद्ध
करकेदेवे अथवा आमलकेतेलकीवस्तिकरे रोगकी
शान्तिवास्ते गुदपाकविषैवीचनवैद्यक्काथकरके
आस्थापनवस्तिकरावे ९ औरदुधका घीउ मखीरपाय
केवस्तिपक्ककारीदेवे येकरघीउ ग्रामसदाणकाना ग्रह
णकरे औरसावधानहोके ढुंवकोनाकोले १० गुदलि
यपक्कावबीनहिकरे तवतिसकोअसाध्यजाणे ११ इति
गुदभ्रंशचि० गुदयोनिभ्रंशविषे योगुदाभ्रंशाकीचि
कित्साहै सोईकरे योघोडावडेभारकरपीडितहुयेसा०

© Dharmartha Trust J&K. Digitized by eGangotri

भा.
टी.
२२९

युक्त होय औ है अतीसार न गेरियां खासरुम वहनतलें
रा है रोमखेड़े होय पुछावलहका अविरेका अरुना
सांको खेड़ीयां करता है ११ भारप्रीडित तिसने जानके
नवचोड़े नू प्रपिक्र करणे वाली यावाता हैं तिनां करके
भलकावे अरु पीत द्रव्य वंदना दि तिन्हां काले पकावे
औरगिहे वस साथ पलेरके पवे चौरीयां साथ कोले १ १
रसनरां धीरजदेके वारस्त्रंगा कीयां नाडीयां ते रुधिर नि
काले औरगुड़ साथ सत्तू खुलावे और मखीर साथ दा

पुष्टिर्तिभिन्न रोमांसुरक्तं प्र्रेकुरुते कासाङ्
ल्लिमरप्रस्य १२ तेवाभि: प्रशांताभिर्वाजिन
माष्मास्य शीतलै: प्रदेहेत् वैलेनाहेणतत:
सम्मेहृते वीनयेद्यजनै: १३ पर्वचममाष्य
शिरावतरंगता: सविसाद्या सक्तून् गुडसंयु
क्तादद्यात्ततांस्वममधुना १४ कसेरुकंमधुस
युक्तं प्रदापयेत्क्षीरसायाहृमथपाने क्षीरश्रा
स्मृत शीतेसशर्करमधुसंयुतं दद्यात् १५ का
लानिभट्टकाष्टेरानाकाष्ममर्यरेणुकाभरि
ते उत्पलिनीकल्कयुतक्षीरेणाजेनकथि
ते १६ शीतंमधुशर्करया पिप्पल्या संयुतं हि
तपाने कल्पवपेतिका नांयकथितेतत्र्योयो
कथ्य १७ भा.रा.विषाणचि. अनभितेनाभुहो
तेरगमोवाम्लानेस्थैः।

ग पिलावे १४
खकामदि
अरुयो कल्पविषेंड गयाहै सोमंजास मेंमखीर साथपि
लावे अथवा रुधकाउके खेउमनीरमिलायके पीने।
कोहवावे १५ वेरदिग्यार मुनका कसीर समालावीज
कमलनूपिवा इनांकाचुगदा येउडुपसाथ काढ़करके
वेआहो पद मखीर खेउ मदापायपिलावे तोहितक
रहै अरुयोपितकल्पविषेंचिकित्साहै सोसभइस
विषेकरावे १७ इतिभा.रा.विषाणचि. योचोडागरमी
धुपाविषेंमुखेंनेवहनचलायाहै तिसको परसा

© Dharmartha Trust J&K. Digitized by eGangotri

अरुद्मवज्ञनहोयाहै जिसविकारकरकेघोडा वडेकंठस
रकरकेकरलाताहै वाकिलदाहै अरुपछावलालरंगदाक
रताहै निर्वलहोजाताहै परयोल्काभिघातुविकारहै इस
नेवडेयत्नकरकेजीवताहै अथवामरजाताहै १९ अग्नियेसें
वधिहोईदुसाध्यहै येसेसर्पविषयुक्तस्थितहोवे तैसेही
देहकेविनाशवास्ते ऐसेहीमूर्छितृह्षकरकेयोडेयाहोय
घोडाहै २० मूर्खबुद्धिरहितपुरुषपहलेअपनेआपकोनाश
करताहै फेरघोडेकोहननकरताहै जिसकरकेइसीघोडेको

तस्यस्वेदःश्वासस्त्रजायतेतेनदोषेण १८ कण्ठ
नेकंठेनभृशंरक्तमूत्रप्रमीहतिदीनः योल्काभि
घातपषःकृत्यजीवेनजीवति १९ अग्नियेथात्र
वृद्धःसर्पोदुरधिष्ठतोविषेवापि देहविनाशा।
यभवेदेवयोल्कात्वमात्रतः २० एवंहत्वातान
तनरोगान्निहंतिमूढमतिः तस्यैवमानदेहस्य
वृत्तोमोहतोव्याधिः २१ एवंतस्यहताकास्या।
कारयेतशीतवारिपरिषेक शीतेनकर्दमेनप्र
देहनवीजनेनैव २२ चैलेनार्द्रेणततःसहतदे
हस्यवक्तेमोक्षणवीजीतस्याथ पानयोनेनन
भूयात्प्रलेपनमपिधाकुर्यात् २३ सलिलविभा
गमिश्रमसृग्णकणामगावेरमेयुक्तान् गतमोह
स्यतपानंदद्यात्क्रमनाशिनंश्रेष्ठं २४ दाह्वाप
हषकानिचत्तोहदतीरंवशर्करासहिते ।

रुधिरछुडाणाकहेयाहै २१ फेरछुतमाथमालसकीपहोय
कैठंडेजलकेसाथस्नानकरावे औरशीतलचिकडसाथ
लेपकरावे औरपवेकरफोले २२ अरुगिलेवस्त्रकरकेदे
हकोपलेटकरके फेरफोलेदेहायकोरुधिरमोक्षणाकरै
औरसोपाणीकरकेघेउधोयकेलेपनकरावे २३ जलत्र
यहिस्सेपायकरके मदिरासेठ मत्रोपायके मरतहोय।
देघोडेकोपिलावे २४ मनकाफालसेमखीरइथखंडके
साथपायके परैपानघोडेनाहहमरैदिनदेनेयोगपकहे औरहै

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ टी॰ २३० 238

और मुलहठसाथ दूधकाढके एवउपायकेपिलावे चन्द्रवैद्य
इसकरके योउसंतापवी सुखीहोजाताहै २८ काकोली क्षीर
काकोली मुलहठ मजीठ पद्मकाष्ठ नागकेशरफूल खस इनोंका
क्वाथबनाइकरके ठंढाकरके वस्तिपिचकारी योडनाईदेवे २
औरतित्तिर अरुमृग इनोंके मासके रससाथ भोजनखुलावे
औरवायुवालेस्थानविषे सीतलजगाविषे तिसकोस्थित
करे अरुघासकेवास्ते दूवाका खवलकी या घोडेवास्ते हित
कारकहैयाहै २८ इतियोक्ताभिघातचि॰ ज्वरघोरकठिनहै ति

अथरेहनिदानंवेश्रमापहंपानमथाय २७ नी
रंमधुकेनघृतेशर्करयायुतंअपानाय दद्यात्
रुगाय बुधः सुखमेवलभतेचिरं २८ द्वेकाको
लीमधुकंमंजिष्ठापद्मकोत्पलमुशीरं पभिः।
क्वथितंशीतंवस्तौ प्रदानमथमपाय २० अथ
तित्तिरमृगमांसैः कुर्याद्रसभोजनंप्रवातेच स्था
नेशीतेचभवेदूर्वायवसेहितावासे २८ इति
योक्ताभिघातचि॰ घोरः प्राणहरोवैज्वरः शरी
रंप्रतापयेयस्मात् तस्मादभितापइतिकीर्त्ति
तोवाजिनांनिपुणैः २९ तस्यस्थानेशीतेनाल
निकोष्टेचमस्यायोर्वधः अवगाहजलेशीते
घृतेनतैलमर्दनंयत्नमतिमान् ३० अथचंदनादि
गणांगवीजयेनवापिनालचूतैः देयचनाव
लेप्यस्यकटुफलंतीरसंयुक्तम् ३१

अरुप्राणोंकोहरनेवालाहै अरुदेहकोसंतमकरताहै ति
सकारणतेचन्द्रवैद्योनेघोडेयाको अभितापनामकरकेज्व
रकहैयाहै २९ तिसकोस्थानशीतलवारिये अरुनाल
कोष्ट मलनाडीयांका वेधकरणोकहियाहै अरुशीत
लजलविषेंन्हालना और घृतकीमर्दनकरावे चन्द्र
वैद्य ३० अरुचंदनादि शीतलचिकडकरके अंगोंविषे
लेपकरावे अरुपतेकरकेफोले रेपकरेहोपकी आ
दविषेदुग्धसाथकायफलदेवे ३१

© Dharmartha Trust J&K. Digitized by eGangotri

मलर मनका फालसे पीसके हूपमखीरसाथदेवे अरुनव
वाकेरोगवालेको काढके ठंडाकरकेपीलेवास्तेदेआवे १२
कठ अरुयव पढेसीतलदेने अरुभोजनबी ठंडादेणा अरुयेसी
तलचिकित्साकहैयाहै सोसभकरावे अरुयोसर्वविषेखीर
वस्तिकहै है सोकरावे १३ और पंचमूलकेसाथ सिद्धहोय
लोउ मेहै तितर हनंदेमासरस चूनमिलायकरके इसके
साथभोजनकरके वोराजी होजाताहै १४ अरुहरेवास
डवो और यो सनके वासहै सो खाणेवास्ते देवे अरुयो वो

पिष्ठाम थुकं सांद्रं क्षीरेण परुषकाणि मधु
चैव नरो हे षसन्तपानं दद्यात्सपरिश्रुतशीतं ११
कषायवांश्च सुशीतानां द्याछीतानि चैव भक्ता
नि शीताः क्रियाश्च कार्याः सर्वीक क्षीरवस्ति
श्च १३ अथ पंचमूलपक्केलावकपाशकेल
तितिरसेस्त घृतसंयुक्तैर्भोजनमेवं कुर्यात्स
खीभवति १४ हरितं यवसं हरिद्वां दद्याद्यवच्चा
सद्यं नैव किंचित् अभितापपरितोगेन ल।
वये हैयपेय त्रेवं १५ इतिज्वराभितापः यस्य
नरकेपित्तप्रकुपित्तंमूर्ध्नं सुखानतोनस्य:
सहसानरगस्यभ्रंशं प्रवर्तते कामसमानस्य १ ९
अनुलोमंवा अवति हिगुंदंननरगस्यमूत्रमु।
नेवा कुपितेश्शोणितपित्ते समास्त्रयाद्वाद्रू।
मस्तर्थम् २

जा अभितापज्वर करकेक्षीणहै ति
सकोफाका अरुलङ्घनाकुरावे चतुरकदेवी १५ इति
ज्वराभितापवि० तिसघोडेकोरक्तपित्तकोपकरके ऊर्द्ध्वग
तिहोके रक्तगदेहोय घोडेकेमुखअरुनासाते वहनतनिक
ले १६ अरुयथार्थगुदाकेरस्ते वगदाहै अथवामूत्रहोके
निकलदाहै रक्त पित्तकेविकृतहोयदै घोडेको पढे
लक्षणहोनेहैन १७ सारेदहतेलहू मुखकेरस्ते आ
के वहनतबाहरआवताहै योरुपिगुदाकेरस्तेचलताहै

भा॰ सो सब एकरसाध्य है अरु यो सुखेनें चलता है सो यत्नकर
टी॰ केसाध्य है ३८ यो रुधिर दोनों मुखें अरु गुदा ते चलता है नि
२३१ श्चय करमरता है इस विषें कोई भ्रम नहीं ये साध्य विषें कारण
कहे या है सो कहते हैं ३९ जिसकों जल विषें न राखे और सो
जल के साथ धोते हों पद्मन की मालिस और गिलाव सहउप
रदे के पत्ते साथ फोले ४० चिटा चंदन दुबो न्हाहा मजीठ मु
लठ कौलडोडे खस तिल सत् चावलें दाखा टा नड वेंत के उ
प ४१ परण काली वेल अग्गण तीरहुत्त वडी वड फवल

सवे पारीशश्वनतमेव हने नायानि शोणितं वहु
गः रक्तमपानात्साध्य वदनाद्याप्य साध्या त्ति ३८
श्यागछन्तु भाभ्यामारयती नरनाशि मेदहः
साध्यस्यत यत्कार्यं तदहंते संप्रवक्ष्यामि ३९ न
स्य सलिलावगाहः स्याछतधौतेन सर्पिषाभ्य
गः चैलेनाद्रेण हृनस्य वीजयेत्तालवृंतेनश्च ४०
चंदन ह्रीवेनतामंजिष्ठामधुकपद्मकाशीरैः
तिलमसूकशालिपिष्टैर्नलवेतसवेजाग्रैः ४१
परउशारिवाभ्यां त्तीरितरुतकावालशुकैः सो
नामहितैः पिष्टैः प्रलेपनं कारयेन्मतिमान् ४२
त्तीरदधितैलोदकसंयुक्तैः त्तीरिणां कषायैस्त्त
परिषेकादातवाप्टथक्प्टथक्तोगशांसंर्थ्वे ४३
दाक्तापरुषककाश्मर्यपिप्पलसाधयेन्मति
मान् तेन परिषाग्रारसं शीतमधुसंयुतं देय ४ ४
लोध्रचंदनमधुकेन लिनानुत्पलान्युशीराणि॰

पलाश पारस पिप्पल इनों के छिलके अरु कोमल पत्र ल्यावी
इनोंकों पीसकर के वृद्धिवान लेप करावे ४२ दूध महा चाउ
ले दे पाणी के साथ पीसकर के तीर हूनों के काथ करके
भिन्न भिन्न सेचन करावे यो हे रोग हरकरणे वाले ४३ दाख
फालसे कसीरहे फल इनोंको काढके वैद्य चतुर सनिका
लके ठंडा करके मकीर पाय पिलावे ४४ चिटा चंदन लोध्र
कमलनाल खस नीरलकी जड़ कालिवेल उग्गण-

© Dharmartha Trust J&K. Digitized by eGangotri

पाईदेफुल सिंवलदेफुल ४९ तिनांको चाउलेकेफलोप
साथपीसके मखीर मिसरी मिलायपानदेवे इसकरकेर
कपित्त चोडेकाशुद्ध होजाताहै ४८ शालिवा समनी वा सठी
के चाउलोंदाआटा सहेकेलड्डूकेसाथ मखीरपायचटणी
देवे ४७ सिंवलदेफुल कमीर कालीवल जाहा इनांकेचा
उलोंदे पाणीसाथपीसकरके मखीरपाइकेपिलावे ४८
इसकरके चोडेकेरुधिरको सतावीशुद्धकरदेताहै ओरह
यकीवस्तिपळकारिफअवे अस्नायकेवास्ते घवलकी

ह्रेणारिवेन्नतेनवायानकीशाल्मकीछुथं ४९
नेदुलोत्तपिष्टैः लोड्रसितासहितंचपानं एतेन
रक्तपित्तप्रसीदति मे प्रतिवाहनां ४६ ह्रंलीस्त्र
णाहृवाशीलानावाथ्यष्टिकानांवा शाला
हिनासंमिश्रलेहमधुसयुतंदद्यात् ४७ अथा
णिशाल्मलीनांश्रीपर्णीपर्णरिवातयानेता पि
ष्टानेतुलतोयेनपाययेत्लोष्टसंयुक्तं ४८ एते
नापिप्रसारक्तमेवप्रसीदतीमाशु देयस्मपा
योवस्तिहेवायवसहितावासे ४९ रक्तपित्तवि.
अपचारैः सर्वोक्तैः पित्तसक्तपित्तंकफेनरक्तेन
सहमूर्छतेनतनुलचिनीयनेवेनुरंगस्य ५० त्व
क्मांसोन्नलटगपवतस्पनायनेमूर्छाशीर्णाः का
यपक्वाः स्फोटाः शीर्यन्तेवैप्रभिद्यन्ते ५१ तेपीड
यतिस्पर्शभिन्नाक्लिन्नाः प्रस्रवंतस्त्र भवंयंति
ततः प्रचुंरमड्डर्वेलोरक्तमृजीच ५२

डुवांदेवे चोडेनाई इतिरक्तपित्तचि० ४९ एवंविसर्पयोकहें
कुपथ्य तिनांकरके विकृतपित्त अरुरक्तकफसाथमिल
घाहोया सोचोडेकीत्वचा विषे प्राप्तहोके चोडेके तिसकी
त्वचाअग्निकरदग्धहोयेकीन्याई निरंतरफिसजाते हैं अ
रुऐहविषे फोडे एकके विस्तारकरफटजांदेहेन ५१ सोव
हुतपीडाकरते हैं तिनांको वडते हैं तिसकरके सोवहुतनि
कलहोजानाताहै अरुमग लालकरताहै ५२ ॥
भिन्नहोके आईगिलेहोके वगदेहेन

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰
टी॰
२३२

अरु वद्धतलिसा होजाताहै इसमकरताहै पहेलक्षण वि
षुत्तिसरोगकेकहेहैन योचोडियांकोकुहिस्राहै तिसकी
चिकित्साकहतेहैं ५३ क्षीरवृक्ष वडी वड रुवल पलाष वे
त इनांछिलकउरके सीतलजलविषे सेर वतरवेघ इससी
तकाथकरके तिसकोसेचनधोवनकरे ५४ दुध तिल सा
ली वयष्टसार इनांकोमठके इसकेजलविषेपीसकुरके सा
रेदेहविषे वारंवारलेपकरावै इसका ५५ भसावे गडोला ना
गरमोथा औरवृक्षांकेकोमलपत्र कुहारे मुनका सतावरी

क्षामोदनं यं ख्यातिति विषुत्तिसरोगः स्मृषः श्रो
क्रमरंगमाणनस्यचिकित्सांप्रवक्षामि ५३
क्षीणतक्षीरीणरुत्वचंसभणीसीतेनिवासये
त्सानः शीतेकषायेणानेनकारयेत्सुपरिषे
क ५४ तोरंतिलापयष्यानिषणकस्महर्षितेन
तः पिष्ठा शोवेशरीरकुर्यात्मुयोभूयःप्रदेहमि
म ५५ भल्लातकेकखीरंकशोरुकेक्षीरि।
णाप्रवालानि खर्जूरमदृकाशतपदीपि।
यालीतेनहू ५६ इक्षुरसेनसंयुक्तेपिंडैचैतव
निःस्तकुंभे रजनीममकांमधितपानत
सेप्रदानयम ५७ निर्वीतितःपितप्राकृते
वैवृसरक्तिक्तरगाः हतनगौरिकचक्रयांदभ्माग
सर्वकायस्य ५८ कथितैवेयप्रवालेपैय
सामभुनाचसंयुक्तस्यापि वर्णप्रसादजननंकु
र्यादभ्यंजनंवास्य ५९

सचां सवीर ५६ अरुगन्नेदेरसकनेपीसकरके इनां।
कोंधुणके भांडेविचपाइपकरानरखीछोडे सोचोडेन्ना
इपिलानेवालेदेवे ५७ सोपितकोहटायके गैससरवेप
छावकरताथा तेसाहीकताहैयोडा औरसारेदेहविषे
गेरिचेउसाथ मर्दनकरावे तिसको ५८ वोडकेपत्रों
करके अरुदूधसवीरसाथसिद्धकिया होयादाह्युत
तिसकीमालसकरेते वर्णरंगकी सुंदरताकोकरताहै।
ताहै ५९

2-232

© Dharmartha Trust J&K. Digitized by eGangotri

रूप भस्म सैंठ मुलहठी मजीठ इन्हें उपाय के भोजन खाणे को दे
वे अरु घास वास्ते ड्वा देवे ९० इति विद्युत्तिमचि॰ योद्यो
डा अग्नि करके जले तिसकी जो यह चिकित्सा करणे योग्य
है पान वास्ते विशेष है अरु घृत पिलाना अरु घृत लगाय देवे ९
भोजन करके घृत उपाय के मालस कराव अरु मठा सत्तू घृ
त पाय के लेप करे शीतल प्रदेह कराव और सब शीतल चि
चिकित्सा कराव ९२ तैसे ही गेरी के चूर्ण करे और सब रेयां के
रस का लेपन कहिया है और सब शीतल ही चिकित्सा क

नीरोदनं च पेयं वा मधुसर्पिःशर्करा कणान्वितं के
भोजनं मधु दातव्यं यवसार्पिशस्यने हृद्वा ९०
विद्युत्तिमचि॰ दग्धोऽग्निना च यो स्तम्भसार्पि
न चिकित्सितकार्य्यं पानाय विशेषे यत्नश
स्य घृतं च दापयेन्मतिमान् ९१ घृतपीतेन ना
स्य गाढं तेन दधि शक्तुभिर्भवेल्लेपः शीतैः
प्रदेहैश्च रूक्षः शीतास्सर्वाः क्रिया कार्याः ९२ त
था गैरिक चूर्णेन चूर्णैः सर्वपरसस्यत अपले
पनं स्मृति हि शीतेन सर्वं हि कारयेत् अग्निदग्धचि॰
वातात्पित्तात्कफाच्च सन्निपातात्तथो विपर्यया
त् औषधीगंधात्मनसा संभ्रमादष्टमः प्रोक्तः ९४
अष्टविधः एवं ज्वरः परिकीर्तितस्तस्या
रम्भ पृष्ठात् सम्यग्न्यानं रूपं चिकित्सितं वक्षे ९५
अथ कारणैः स्व वायुः स्वैः स्वैरेव मारुतः प्रकु
पितः स्थानाद्दृष्टः प्रपद्यते वायने कायं ९६

णवे ९३ इति अग्निदग्धचि॰ वात पित्त कफ सन्निपात अरु
विपरीतता ते औषधीयों की विपरीत गंधि ते मन करके सं
भ्रम कोप ते अष्ट प्रकार के ज्वर कहे हैं ९४ अष्ट प्रकार के ज्वरः
ज्वर जो है यां को अष्ट प्रकार का कहिया है इनों की उत्पत्ति
निदान रूप चिकित्सा कहते हैं ९५ वायु अपणे कोप के
कारण करके कुपित होके ऊर्ध्वगति प्रकृति ते अपणे स्था
न ते ऊपर जाय करके शरीर को पीडित करता है ९६

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ अरु जठराग्नि इनोंकरके विषम होके संधियों जोडोंको ढंडे
हो॰ करता है पिरभार अरु शोल पेडपडी यां विषे पीडा अरु नेत्रों
२३३ केकोण स्थान सजजाते हैं ६७ यासवडे क्लेशकर खाते हे
थोडा विमन होके चलता है इनालक्षणकरके वायुने होय
ज्वरको जाणे ६८ तिसकारणते आदविषे घृतसाथ मालस
और फाकादेना अरु प्राणोंके विरोधके निवारणवास्ते देह
शुद्धिवास्ते व्रतकरावे ६९ दशमूल पटकंड इदसिंदा होना
कालिवासा जीरकाकोल्ली भरवंड अनाव यउ क्लस्य इनोंका

233

उष्माद्वैनेन विषमः संधिपृष्ठांसशिरोग्रहं च
भंसते खलशरवेलोचनरूटेवहृयते ६७ कृ
च्छ्रात्वाद्दतियवसंगक्ष्मतइमेनावाजी एवंवि
धैर्लिंगैर्ज्वरमनिलसंभवंविद्यात् ६८ तस्मा
दादावंधोगेघृतेनपुरकाबलवंनप्रोष्ठे प्राणा
स्यानुपरोधेनकारयेन्मार्गशुद्धये ६९ दशमू
लमपामार्गपुनर्नवेसहचरंपयस्याव गोक्षुर
ककोलानिवयवान्कुलत्थाश्चतोयेन १० निः
क्वाथ्यतेनभागोद्वौभागौसर्पिषोरसाभागाः
क्वाथस्यचत्वारोभागाःक्षीरस्यचत्वारः ११ ऋषभ
कजीवकरास्नाकाकोल्यौहेतपद्मकमनन्ता
छिन्नरुहाशतपुष्पाशालसदारुमेदेद्वे अ
मधुककुकलीरशृंगी संभारसर्वेमदारुकल्पपक्वं
तुलाविपाचयेत्घृतमेषः प्रकीर्तितःस्वरः १२
सर्वानिलदोषघ्नः सर्वज्वरनाशनोविशेषेण

जल साथ क्वाथ करे सो हिसे बाकी रहे ये उ इक भाग क्वाथ
रसचार भाग दुध चार हिसे पावे ११ जीवक ऋषभ रास्ना
काकोली क्षीरकाकोली पद्मकाष्ट वा कमलडोडे आहा ग
लो सोंप चीड दिआर मेदा महामेदा १२ मुलट ककड श्रृं
गी यहे सम कटक करके पकावे पेहू घैइ नस्लेह के हेया हे १३
सो घृत सभ प्रकारके वात विकार अरु सभ नरों के ज्वरको
नाश करता है इसते लकरके मालस मंत्रोगो त्रेक रावे सेकदे
वे १४

© Dharmartha Trust J&K. Digitized by eGangotri

संठ सोंठ ऊटकटारियां मुंढा वच रेंमणा राउआ वाविडिंग सम
कूटलूण सैंधालूण १५ कांजी मदिरा गोकामूत्र तिल वृहत
पंचमूलका काथ साथ काढे अरु वो चेपाथ दूधीनंणाम
थनकरके छितुवासन वस्तिकरावे अरु निर्वात वायुरहित
स्थानविषें स्थितरखे इसप्रकार वातज्वर सम होता है १७
वस्तिपञ्चकारीदेवे सीलगरमकरके १८ आस्थापनवि
धिकरावे फेरघोडेको वेहून स्नेहकरके अनुवासनव
स्तिकरावे अरु निर्वात वायुरहितस्थानविषें स्थितरखे

पयेनाभ्यक्तांगं विमर्दयेत्स्वेदयेच्चैव १४ वि
श्वामित्रकृष्णसर्षपमागधिकावचारास्नाः
मदनफलानि विडंगं ताम्रं सैंधवं लवणं १ १
मल्लिकामूत्राणि च तैलं पंचमूलानि निःक्वा
थः एभिःखजेन मथितैर्वस्तिं दद्यात्स्वेदोस्सम्यक्
आस्थापितेन पश्चात्तरं मनुवासयेत्तत्स्नेह
तैः स्थाने च निवाते स्यात् एवं वातज्वरं शमयेत् १ २
पित्तेकुपितस्थानात्स्वीयैः कारणैः सकंगास्य
कृत्वेज्वरं ततस्तेन दह्यते श्वसितिसंततः १८
प्रस्विन्नः सर्वकायः सतृष्णग्रीवश्चतामांतस्यं
मूत्रे लोचनयनकुंटेहारिद्रलोचने चैव १९ प
वेविपैत्तलिंगे ज्ञानीयात्पैत्तिकज्वरं धीमान्
नस्यास्थाने शीते शीतानाम्आलेपनानी सु: २०

इसप्रकार वातज्वर शाम हो जाता है ११ एवंविधें कहे यो
कारण है तिनों करके कुपित होके पित्त अपने अस्थानते
बलकरके घोडेको ज्वर करता है तिससें दाह श्वास दम
करता है १८ और सारे देह विषें रसा होता है अरु काठीन ५
हे जाती है और हड्डने रणीव फूलवो होती है अरु नेत्रकोण
विषें सोजा अरु पीडा अरु अति हरदल के रंगके सम पी
ले होते हैं १९ इन्हों तरां के लक्षणों करके पित्तज्वर जाणे
वैद्य तिस घोडेको शीतल स्थान अरु ठंढे लेपण करा
वे २०

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा॰
ह्रो॰
१३४

234

हीरवृक्षोंकूं सिकर करके जलके घडे विच भेडे निसकर
केपित्तज्वरके युक्त छोडेकों सेचनकरावे पीवे ग्रौरकांजी
साथ वा मदिरासाथ सेचकरे ९१ ग्रौरदाहके नाशके वास्ते
निंबपत्रकी झगके साथ तेलवड्डन ग्रेष्ठ है ग्रौरसो जराके
साथ पीनेहोए घृत मुलठी करके युक्त लेपकरे ९५ वडाख्या
लेकवराव र जलविषें स्थितकर छोडके मस्तकविषें चिर
काल सेचनकरे इसकों सत्तू मखीर खेड खंडके साथ देवे २२
मनका द्राक्षा कसीर कासीवेल हीरकाकोली जीवक

हीरतरुत्वक्चूर्णं संपानीयघटे विनिक्षिपेते
न परिषेचयेत्स्वरात्ते धान्याम्लैः साथवा सुरया २१
दध्ना निंबफेनेप्रलेपनं दाहनाशनेश्रेष्ठं श
तधौतेनतैलेपो घृतेयष्टाह्वयुक्तेन ९२ व
लोमात्रेशालिले स्थितं चपरिषेचनं येच्चिरं
मूर्ध्नि सक्तून्मधुघृतयुक्तान्सशर्करान्ल्याप
येत्तस्य ९५ द्राक्षामधुकमन्तोग्रोपर्णिका
रिवांपयस्याच जीवकऋषभकमहाद्धिऋद्ध
हीहीरकाकोली ९४ विषमुस्तसचेपिष्ट्वाज
लेनमधुशर्करासमायुक्तं पतस्मानायहितं।
पित्तज्वरेदाहसमने ९९ कुशाकाशेक्षुना
लानांमूलानध्यशारिवावयस्याच मंजिष्ठा
लांगलिकाचंदनकाश्मर्यपरूषीका ९८ य
ष्टीमधुकमधुपर्णीनालीपद्मकेसालपर्णानेता
व पतस्यसापिष्टावल्लिमधुशर्करायुक्तः ९ २

ऋषभ मुस्ता गलो काकोली ९४ मपकमलमूल नाये १
नांकोजलसाथ पीसके मखीरखंडके साथ पित्तज्वर दाह
केनाशवास्ते हितकरहे ९९ दर्भ काई नड इनोंके मूल
कालीवेल गलो मजीठ कौंचबीज चिटाचंदन कसीरफ
ल दारु ९८ मुलठी वीरणकीजड पद्मकाष्ठ सुरकणी ब्रा
ह्मी इनोंको इकट्ठा साथ पीसके मखीरखंड पाय करके पल्ल
कारी कराये ९०

© Dharmartha Trust J&K. Digitized by eGangotri

अरुमधुरऔषधीयोंकरके सर्ईसाम माषपर्णी मुद्गपर्णी
काकोली क्षीरकाकोली जीवक ऋषभ मेदा महामेदा मुलठी
इनोंसाथ घृतसिद्धकरके अनुवासनवस्तिदेवे अरुजांगल
मृगपंखीयोंकेमासकेरससाथ भातमतीप्रमाणकाभोजन
देवे अरुचायदुग्धदेवे ८८ इतिपित्तज्वरचि० थोडेकोंरसके
रोपतें अरुमधुरअम्लरसकेखोनेहोयको अरुकफसभाव
वालेको अरुव्यायामफेरनेबिना कफकरकेवसंतऋतुविषें
ज्वरहोताहै ८९ तिसकरके आलस निद्रा शरीरभारा अरुचि

मधुरौषधैश्चसिद्धैःसर्पिर्भिश्चैवानुवंकार्यं जांगल
रसैश्चशालिनंपाययेन्मात्रयाहितं ८८ पित्तज्व
रचि० अस्वप्नरससंजातेकफप्रकृतेमधुरान्ना
दीनिसेविनश्चास्य अव्यायामश्रमायोज्वरश्च
संजायतेकफजः ८९ तेनालस्यनिद्रागौरवमरु
चिर्भवेन्मुखस्रावः अग्निक्षिप्रालोमः पिपान
पःस्वल्पकर्णश्च ९० मुस्तपाठाकटुहरीतकीकटु
रोहिणीशक्रीच सुरदारुकणाफलिनीचित्र
कमय्यवाजिगंधाव ९१ पिचुमंदस्यपत्राणि।
साधयेद्वारिणारसस्तस्य पाययेत्पोषमादाय
दापयेत्सोदूरंसयुक्तं ९२ मुखेकठगतान्रोगान्
कासास्त्रिहारणकानमेवासश्च कोष्ठगतश्लेष्मा
णंमंदाग्निंज्वरःकफजं ९३ घरपोफात्वा।
नकफेजिह्वास्तंभगलग्रहच्छर्दिश्च ।

अरुमुखतेंजलवगना औरअतियांअसुपानोंकरकेभरी
यारहतीहै अरुतपतप्रियलगतीहै कोष्ठिलेस्वरदाहै ९०
मुथरवटलवेल कुठ देवदारुकेबीजर कौउ गिलो हि
आरमचो प्रियंगु मालकंगणी चित्रा असगंधन ९१ निंबके
पत्र जलविषेंकाढे यव चौथाहेमारहे तोमरवीरपायके
पीणेकोदेवे ९२ सोमुखगलकेरोगकास सभप्रकारके।
सिंहारणक अरुकोष्ठगतश्लेष्ममंदाग्नि अरुकफ
ज्वरकों ९३ अरुछेप्रकारकेसोजे वात कफ जीभका ।
जडहोणा गलरुकनाणा वमन हृद्रोग आमवात परमसा
दिकाघसमनकरदेताहै ९४

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
टी॰
२३५

235

निंब प्रवल पटोल इन्नोंके रस विषें त्रिन्नके मुंगीखाणे वास्ते
देवे मधा आद्रक मखीर होउ साधारलायक करके देवे ९५ औ
र कौउ मखीर साथ देवे और कफज्वर विषें यो कटु पिंडी क
हिहे सो देवे अरु चाय हाणापानी पहेसम और के नाश
करणवाले देवे ९६ इति श्लेष्मज्वरचि॰ दाह परसा भ्रम सु
गीरहकउजाना निद्रा मूर्छा व्याकुल थकेमा इस सुखेते
लालावगणीया तृषा विद्वोषी मलमूत्ररुकजाना ९७ इना
लक्षणां करके चतुरवैद्य असाध्य सन्निपात ज्वरजाणे इस

त्रिदोषे ग्रामवातं के शमयसे षष्ठल्लाद्यः ९४
पित्तुमंदपटोलरसे सिंदुम्नाद्राक्षभोजने दद्या
त् मागधिकाविषघुतांम्रुतिस्रुतान्सोदमपि
बेत् ९५ कटुकामधुसंयुक्तं दद्यात्कटुपिंडि
कां ज्वरे कफजे यवसत्वोदनपानानि दापये।
त् श्लेष्मशमनानि ९६ श्लेष्मज्वरचि॰ दाहः
स्वेदः भ्रमो निद्रा मूर्छा श्रमस्तथा खाः लाला
स्रावमलस्याभो हो विन्मूत्रयोपश्च ९७ लिंगै
रेभिरसाध्यज्वरं ब्रुयः सन्निपातक विद्यात् अ
थ चिकित्सानोनाकार्या सा सिद्धिमकेन्मात्र ९८
सन्निपातज्वरः स्तनोच विपर्यासात्ज्वरोय
स्मापजायते औषधीयंषुभावात्तुतयोलक्ष
णमुच्यते ९९ विधुनोति शिरोमर्ध्यं श्वासः
श्च जायते रक्तेन स्त्रभवति हारितं वापि।
मेहति १० फलाति कठेषद्रिवीभत्रोगाय क्र
मः विज्ञानमेतत्तु तेनैव विविपितपज्ये १

कीचिकित्सान हि करी जिसतें सिद्धिन हि होनेते ९८ स्त
नके विपर्य करके यो ज्वर है अरु औषधीयांकी दुरगंधि कर
यो ज्वर है तिनां दोनोंका लक्षण कहते हां ९९ सिर को वा
हनमारता है अरु सुस्लक जाना है अती लाल अरु पीला
पक्षाब करता है १० अति कोण विषे पीडा अरु अती तेज
लधाव गोमचाउहो जाते है बलवत भारा पहेल लक्षणा अरु
ने विपर्य करज्वर के ये असे ही औषधि गंधज ज्वर के हैं १

© Dharmartha Trust J&K. Digitized by eGangotri

पंचक्षीर द्रुम मुलठ अर्जुनवृक्ष निंब इनोंकेसिकड
जलविषें क्वाथकरे प्रातकालविषें वैद्य घोडेको उठाय
क्वाथसेन्हावले २ फेर सुनावर नगर प्रियंगु सरेयां खे
स वच वरोजा चीडरस चंदन वा वाला इनोंको महीन
पीसकरके स्नानकरायेहोय पश्चात्घोडेकोलेपकरादेवे ३
कसीर काकोली वा स्याली मुलठ कालिवेल जिह्वा
साख क्षीरकाकोली ४ इनोंका कल्क उगदावनायके
मखीरखंडकेसाथपानकोदेवे येउकाकोल उपद्रेउ

क्षीरिद्रुममधुकार्जुननिंबमंदानांत्वचो
जलेक्वथिताः उत्थाप्यभिषकप्रातस्तेन
कषायेणानुलेपयेत् २ ततःशताह्वनगर
प्रियंगुसिद्धार्थकोशीरवचासमेत ग्रीवे
ष्टकंवालकमेवपिष्टानैःस्नानमात्रेनरा
गंप्रलिपेत् ३ काकमर्याश्चयवसांयष्टीम
धुकंचशारिवानंता मर्द्वीकाचैवभवेन्ना
मैवक्षीरकाकोली ४ कल्ककृतामधुनाश
र्करयासंयुतेपाने सोऽद्गक्षीरयुतानंयाव
कमथभोजनंदद्यात् ५ इत्तविपर्यासोष
धीगंपवृत्ति. अनभिज्ञेनाश्वस्यतुमिथ्या
व्हेलसमुपर्येमाणस्य संजायतेप्रकोपोदो
षास्तेनास्यकुप्यंति ९ संसर्गवाद्यायाः स
सर्गेचाप्यगाढतस्याश्व संजायतेज्वरोयुग्म
मानसवीतितोश्वस्य ७ अभिभूतस्यतुकोप
नशांतनुमेवंप्रयोजनयेत्स्वे.

मखीरला यकर।
केघोडेकोखानेकोदेवे ५ इतिइत्तविपर्ययोषधिगंयन्न
वृत्ति. अनभिज्ञ घोडेकोसारकोनहिजाननेवालेनेमिथ्या
हारविहारकराइहोय घोडेको दोषकुपित होकरके घोडे
योंकोससर्गज्वरकरहेआहे जिनोंकेसाथसंसर्गमिलाय
होनेते घोडेकोसोईमानसज्वरकरहेयाहे ७ अरुघोडाअभि
भूतज्वरकेकोपकरकेयुक्तहे तिसकोपीरजदेकेप्यारदेवे

© Dharmartha Trust J&K. Digitized by eGangotri

सर्वविधि और पित्तज्वरविषैं यो पानक है न सो सम करा
वे ८ अव कृतस्वोड श्राउपचार गंध धूप देवे चोडको इमा
दि उपायकरि इसप्रकार मानस ज्वर सम होजाता है चो
डेका ९ इति मानसज्वरचि॰ दंड सोटा पत्थर इत्यादि को
के प्रहार चोट लगनेकरके और रथके माहोनेकरके
योज्वर चोडको होता है सो संरभज्वर कहेया है तिसका
लक्षण कहता हो १० तिसकरके थकेमा त्रषा मूर्छा
शोषता चेतान हरणि देह श्राकउजाण कडफडी सि

पित्तज्वरोपदिष्टानि दापयेचान्नपानानि ८
आचोपचारैर्लव्ये गंधैश्च धूपयेचैनं एवंच
मानसो वैज्वरः शामयाति निरंगस ९ मान
सज्वरचि॰ दंडादिभिः प्रहारैः श्रमेनाजाय।
ते यस्य संरभजः सउक्तलक्षणान प्रवक्ता।
मि १० तेन आम्लत्रसा मूर्छा शोषाथ्रमस्त।
ध्यासभः आक्षेपकः शिरोरुक गलग्रहश्चापि
तस्य जायते ११ लेपनस्यचूर्णेन कारयेत्ती
रिखुन कल्केन पित्तज्वरोपदिष्टान तु श्चिकि
त्सा प्रकुर्वीत १२ पलाचंदनपद्मकं मंजिष्टा
मधुकमसृनसर्पिः क्षीरविमिश्रपक्वं मधु।
लेनदापयेमाने १३ आम्रमनीलागलिकी
वयस्याशारिवाचगोपयसा तिक्ताथ्यतन्म
शीतंपानं मधुशर्कराधिकं १४ संरभज्वरचि॰

एवमष्टानां ज्वराणां चि॰ध्यायः

रपीड गलरोध ये लक्षण होते हैं ११ वड वडी हेवल पलाश
वेनु इनोंका कल्क चूर्ण लाय लेप करावे और पित्तज्वर विषे
यो चिकित्सा सो सम करावे १२ लाचीया चंदन रक्त पद्मका
ष्ठ मजीठ मुलठ इनोंके साथ दूध मिलायके चोउपकावे
मखीर लायके पान देवे १३ सरकांणी लांगल गलो का
लीवेल इनोंको गोके दूध करके काढ़े ठंडा करके मखी
रवडपायके पिलावे १४ इति संरभज्वरचिकित्सा॰

इति अष्टज्वरचिकित्साध्यायः

© Dharmartha Trust J&K. Digitized by eGangotri

मुनियोंने छेप्रकारके सिंहाणक कहे हैं एक वात पित्त कफ स
न्निपातज रक्तकरके आगंतुक रूपसे हैं जैसे १५ सो जो पीड़ा अ
रु जलवगना अरति है और नीरजलकेसम और फेन करग
युक्त नासनेवगना अरु चोड़का सिर गर्मते भार रहना ते वाय
का सिंहाणज जानना १६ दाहयुक्त भारासिर वड़ा गर्म
अरु रोगरतहै अरु काला अरु पीला सीउ तिसकरके पित्तसिं
हाणयुक्त को ठाकहेया है १७ यो सिर मठे अरु स्वेकी न्याई
है श्वेत और सिरभारा और खेग मंदाग्नि जिसको होवे तोक

वातात्पित्तात्कफाच्च सन्निपाताच्छोणितात्तथैव
आगंतुकाः षडेते प्रोक्ताः सिंहाणका मुनिभिः १५
शूलप्रलाननयनः शुद्धांबुसमानफेनिलस्राव
नरोगोरुस्समूर्द्धा मारुतसिंहाणकी प्रोक्तः १६
दाहान्वितेन गुरुणा शिरसा नमहोष्मणाश्रत।
श्लेष्मा स्रावेन कृष्णपीतेन पित्तसिंहाणकी प्रो
क्तः १७ स्रावो दधिसंनिभः शिरो गुरुत्वं तथा
भवेत्कासः मंदाग्निता तु यस्य कफजः सिंहाण
कस्तस्य १८ मूर्ध्नि स्वेदः कायः कंठत्वच शिरसि
मसयोश्चैव मारुतकफजे चैवं चिह्नानि केवलं ज्ञेयस्म
तिमान् १९ देयः कटुचूर्ण घृतं सर्पिः पानाय सर्व
रोगघ्नं शोधेच्च मसयोश्चैव वेधयेद् शिरेतस्य २
प्रथमं त्रावन्नमान्कटुमृद्धं श्चैव कल्पनिर्दिष्टा
न् हातिशाकं च पिंडं गोमूत्रयुक्तं च कटुचूर्णं २१

कफज सिंहाणक वाला चोड़ा कहिया है १८ वात कफ
दोनों सिंहाणकों विषें सिर गल त्वचा मस्तक मन्या कंठना।
ड़ीयां सेककरणा परसाउ आना अरु पित्तके विषें त्र।
हिवात नताकरावे १९ कटु चूर्ण साथ घृतपान वास्ते सभ
रोगों हरकरणेवाला देवे पड़पड़ीयों कियां और गलना
ड़ीयों विषें वेधकरावे अरु नसवार प्रथम तीक्ष्णनसवा
र पश्चात् कटु मृदु यो कल्पस्थान विषें कहि हैं और हातिश
क पिंड अरु गोमूत्र साथ कटुचूर्ण देवे २१

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
२३७

और कटुसर्पि कटुचूर्णके साथ पानके वास्ते देवे १ऐसे प्र
कार वात श्लेष्म चोउंको सत्तावी शम होजाते हैं २२ वाव
डिंग मुलहठ मंजो तेल पवतृन युक्त १नोको वैद्य जलविषे
सिद्ध करावे तैसे ही कुंडे आरीकारस २३ सहित तेल अरु
सेंधव लूणके अरु तैसे ही सैंधालूण तेल गोमूत्र साथ स
बोलसकर के चोउंयांको २४ कफ अरु वातोद्भव विषे सिरो
विरेचन हित करे है पृहेंचयन सवारी वाण्डकार योसिंहाण
है तिसकों नाश करे है २५ और वात पित्तके हरने वाली या

दद्यात्कटुकसर्पिः कटुचूर्णसमायुतं च पाना
य एवं च वातश्लेष्मा च शाम्यतीमा पूर्वाहान् २२
विडंगयष्टिकाकाणाः सतैल पवानाचिताः
तैलेन साधयेद्भिषकः तथा निदिग्धीकारस २३
सतैलसैंधवाविततथैव तैल सैंधवं गवां
मूत्रसंयुक्तं सबोलमेव वा जिनो २४ कफेन
मारुतोद्भवे हितं शिरोविरेचनं एतानि श्रीणि
नस्यानि वातसिंहाणकं विनिघ्नति २५ अपरं
नस्यं चितयं मारुत पित्तापहृवते अपोउंगकं च
हृतिनिशायुगं कणाद्रुकोपलवविल्वसैंधवं २ ९
घृतं सतैलं सदारुयष्टिकाः पयश्च संयोज्य
विपाचयेद्भिषक् २७ अनापयस्तैल घृतेन्द्र यो
जितः सजीवनीये पृडवद्विपाचितैः २८ नस्ये
त्रिमे मारुतपित्तनाशनं रंगमाणाम्रविधिभिः प्र
कीर्तितैः २९

चयनसवांगकरनेहा स्थलकमल केउ आग हरदल २ मंजो
वरल वेलके पत्र विल्व सैंधालूण २६ घृत तेल दिआर मुल
ठी इयपाय करके वैद्य स्मको का ३ २७ और बकरीका दूध
तेल दोउके साथ मिलाकरके अरु जीवनीयगण करके सो
करते हैं पालक भेद एहे साग माषपर्णी मुद्गपर्णी काको
ली क्षीरकाकोली जीवक ऋषभ मेदा महामेदा मुलठ इ
नं साथ होलि ओंचाटके पकावे ऋषियों ने वे रच सवारी
चोउंयाके मारुत पित्तके नाशवास्ते कहिया है न २९

© Dharmartha Trust J&K. Digitized by eGangotri

वातसिंहाण अरु पित्तसिंहाणविषें इनोंकरके सिरवि-
षे निरंतर लेपकरावै वैद्य अरु सीतलविधिसभकरावै
पैन्हाणकी विषें हितकहिहै १० नसवारी सीतल मा-
त्रौरके साथ करे योकटुवर्गकटुचूर्णविषेंकहेयाहै ति-
सकोपीसके तिससाथतेलपकावै ११ गोमूत्रकरकेमि-
लाय तिसकरके श्लेष्महरकारनेकोहितकारहै मघां
सुंठ मुथा मरिच दिआर १२ इनोंकोगोमूत्रकरकेपीस
केतेलकाढे यहश्लेष्मरोगविषेंलावणतेलकहेआहै १३

वातसिंहाणपैत्तिके नस्तिरः स्वेदनाभिलेपनं प्र-
दिहे भिषक् क्रिया च सीताकतेपायानि हाण-
किनां हिताः १० नावनानि च शीतानि मधु-
शुक्तानि कारयेत् वर्गकटुकचूर्णेन पिष्ट्वा
तैलं विपाचयेत् ११ गोमूत्रेणाभिसंधीनेन
न श्लेष्मणि हितं भवेत् पिप्पली भद्रमुस्ता-
नि मरिच देवदारु च १२ एतानि पिष्ट्वा तैलं च
गोमूत्रेण विपाचयेत् एतत् श्लेष्मविकारेषु ला-
वणं परिकीर्तितं १३ नासां प्रक्षालयेद्वापि क-
काथैर्विविधैर्भिषक् गोमूत्रेणाथवा निःक्ले-
दस्तेनोपशाम्यति १४ खादने च यवान्नेया
यूषैश्च यसंहिते एवं मार्गेण कथितं शालि-
होत्रमतं शृणु १५ यवैः कोलैः कुलत्थैश्च ते-
लं च कथितं भिषक् वातसिंहाणके कुर्यात्
स्वेदं शिरसि मन्ययोः १६

नासांको धोवै नानाप्रकारके काथोंकरके वैद्य अथवा
गोमूत्रसाथ धोवै तिसप्रकोष्ठयोंक्लेदसीउरै सोइसकर-
के शाम होताहै १४ खानेको यव दे वे अरु छायसकारा हि-
त करैहै परिचिकित्सा मार्गमुनिने कहिहै अब याशालि-
होत्रका मत है सो सुणो १५ अरु वात सिंहाणविषें यव
करके कुलस्थरसकरके वेरोंके काथसाथ तेल करके
काथोंकरके सिरविषें गलनाडीविषें स्वेदसे कर देवे १६

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
२३८

कालीवेल दिख्यार चीड मुलठ १८ मिर दो स्रोत एक म
छकेलण कोगड ककडसृंगी ३७ इनाकरके नेलपका
य नसवारपान अडवासनवस्ति पेहेतेल इनो विषेदेवे
मात्रा प्रमाणकरके फेरवारंवार देणोयोग्य है ३८ इतिवात
सिरहाणचि॰ पित्तजसिरहाणमें यो सर्वविषे सीतक्रिया
कहि है सोकरावे अरुआमलेकेरसविषे सिद्धकरके सुं
गी अथवा त्रिफलेकेरसविषे सिद्धमधौरचोउरलायके
भोजनवास्तेदेवे ४० इतिपित्तसिरहाणचि॰ वायविडंग

कालानुसारिवादारुसरलेमधुयष्टिका पुन
नवेकरंजगिरिकर्णिजेश्रृंगाणि ३७ एभिःसै
लेविपक्कस्यात्रस्यपानान्नवासने मात्रयादे
यमेतस्माद्भूयोदेयास्तुथैवय ३८ वातसिर
णचि॰ पित्तेशीताक्रियाकृत्वासर्वमस्तकेप्र
योजयेत मृद्वीकामलकैसिद्धानथवात्रिफ
लारसैः ३९ मधुसर्पिसमायुक्तान्भोजनार्थे
प्रदापयेत् ४० पित्तसिरहाणचि॰ क्रिमिरिपु
रहितेवलेगौरसिद्धार्थकोशीरगोमूत्रयु
क्तानिसर्वाणिपिष्टानिवानोद्भव रजनीयु
गलमधुनेसैंधवेश्रृंगवेरं कणाचैवमेहर्णागा
धेनमूत्रेणपिलानर ४१ हंहतिपुगलमधुन
एमेहसिकातारमाजेविडंगानिपिष्टानि
वसेणमूतानिवक्षेमनसिरसिगनासुरो
गतेनासिकाकंठमस्यांच ४२

यमणीयो दोष सनीसरियां रवस पेसमगोमूत्रसाथपी
सके वातनसिरहाणविषेनसवारदेवे हरदल दालहरद
ल सेंधालूण संठ मघां इनोकोगोमूत्रसाथपिसनविषे
नसवारदेवे ४१ कंडुआरि कडुआरा हिंग मनसील्तार वाव
डिंग बकरीके पलाशसाथपीसकरके वस्त्रसाथछाणा
के प्रेषाजसिरहाणमें देवे सिर छाती नासा कंठ इनो वि
षेस्थितयोसिरहाणहे निसको हरकरनी है ४२

© Dharmartha Trust J&K. Digitized by eGangotri

इनांनसवारांकरके घोडेयोंके सिंहाणकों चतरवैद्यनाश
करे पैहेनसवारा वात पित्त कफके सिंहाणविषे भिन्न२ देवे
जिनांघोडेयांको सिंहाणरोगन्नकामकनारहै तिन्हांकोनस
वारदेवे कफजविषेनसवारदेके जलविषेनाहिंडुआवे ४४
फेरवायविडंग मुलठ दिवार नेत्रवाला देदणदानेकीजड
इनांकोपीसके सिंठतेलकरके नसवारदेवे ४५ मन्सागल
नाठीशंख ७३७ड़ी मध्या इनांविषे ३काष्ठिपोटलीसाथसे
कदेवे औरसालगीहन गजभक्ष थाव इनांदेकाथविषे रि

नस्येनवेद्दंति सिंहाणकंवाजिनांनिश्चितं।
बुद्धिमान् एववातेन पित्तेन कफेनचदृश्यक
यक् ४४ येषांसिंहाणकाःसंतितेषांनस्यंप्र
दापयेत् ततःकफांतरेनस्येदृष्टानोएववगा।
हयेत् ४४ ततोविडंगमधुकंदेवदारुवेलवा
लकं दंतीचपिष्ट्वातैलेनवनस्यमेभिःप्रसाधि
ते ४५ मन्याशंखललाटेषुस्वेदश्चोत्कारिका
दिभिः शालकीयवनिःकाथैःसिंहाणस्या।
प्रभोजयेत् पिप्पलीविश्वसंसृष्टान्संपकांक
पूतपिषा ४६ श्लेष्मसिंहाणवि॰ दोषत्रयः
प्रकुपिताःसर्वेतैःकारणैरश्वरोगस्य कुर्वंति
सन्निपातकमेवसिंहाणकंघोरं ४८ नेत्रंतत
स्फुरितेतदृश्यतेपीतकंतथा रक्तंस्रवतितथा
प्युष्मेणामांदःसरक्ताच ४९ दुर्गंधिस्रावाभो
नानावर्णाश्चतत्सवंति गात्राणीचसर्वाण्य
पिसन्ययेतेशीतलेचरंति ५० खुलावे ४९
ब्रकेसंगी
मधुसे ३ मवीर घेउमिलाकरके ४७ इतिकफसिंहाणवि
एवंविषेकरहैयोकारणहै तिनांकरकेकोपयुक्तदोषसन्नि
पातकसिंहाणकडलरकदिकरतेहैं ४८ तिसनेनेत्रहरे वा
पीलेदरवोटदरे अरुलालस्रवदेहै अरुफ्लेष्मयणानेसालचा।
नाहै ४९ अरुदुर्गंधिवालापाकवाघुर अनेकरंगोवालाश्र
वनासांतेवगदाहै अरुसारेअंगसन्नजोदाहैं अरुसीतल।
होतेहैं ५०

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा. ह्रो. २३९ 239

तिसविषें सभचिकित्सा कह्याहै जैसें सा हविषें दि ति
टिडें हती है यों इसकी चिकित्सा करे सो राजाके तवेले
का स्वामी होजाता है राजा तिसको अर्थवाला करता है ५१
तिसके शाख मध्याके विषें नाडी नाडिवेध करावे रुधिर
विकारको दूर होय पिटे पाणीविषें स्नान करावे बुधिमान् ५२
रक्त चंदन रसोत सिंटकामूल पुटकंडा कडे आरिकडी प्राण च
नपुष्य गडीला बिल्ल मूरकनी असगंध इनोंकरकेतिलतै
लपकावे ५३ तिसकीं नसवारदेवे फेर कल्कविषें क

अश्विन् क्रियास्तु सर्वान् संति हृनेव भस्म
नीवहविः तस्यचिकित्सां करयो हेलान्तपो।
यिभवेत्मनी ५१ नस्यतस्रवेमन्येवेश्वेता
लाश्विनेन तथाशिर शोणितदोषविमुक्तंज
लेनमगाहयेत्ततः ५१ श्वेतामूलकि।
णिहिंहैवृहत्सौपुनर्नवेहैतु बिल्व — रा
स्रोगंधातिलतैलंपाचयेद्भिः ५३ न
स्यंततोद्द्येक टुमन्त्रोस्थभोजयेकल्याका
न ५४ पश्चकल्पगदितमतः सर्वप्राप्त
याहाजी ५४ सन्निपातचिकित्सा अ
प्र प्यमोणितंप्रकुपितएवीकैः पतिकेतर
स्य तेनस्नावोरक्तः प्रवर्तते रक्तजतत्र ५५
नस्यदानामधुकमरिचकालानुशारि।
वाशीता।

कटुमधुककहिहै सो पुखावे तिसतें घोडा राजी होजा
ता है ५४ इतिसन्निपातचिकित्सा अहपित्तत्तविषें
कहैयायोकारणहै तिनोकरके रक्तकुपित होयाहा
घोडेका रक्तजसिहाणहोता है तिसविषें रुधिरवग
ताहै ५५ मनका मुलट मरिच · · · · · · श्वेत
वेदन कमलनाप वीरणादीजड नारदाण मध्यो
काकोली इनोंटकल्ककेसाथदुग्धपायके चतुर

© Dharmartha Trust J&K. Digitized by eGangotri

वैद्यचूतसिद्धकोर योजयोऊसेवनकोर रसकरा
केयोगमूत्रलेनूलभदाहे ५९ क्षीरवृक्षकेसिकउ
कटके जलसाथसेउकरके नवीनभांडेविचपाइक
रकेरावे ५७ एकरात्रस्थितरावे तिसकाथकरके सि
रविषेंसेचन सिरस्नानकरावे ५७ आमलेकेरसविषे
सिद्धभंगी मद्यो विचपाइके औरसकोरचेउविचरा
लाइकेभोजनदेवे ५८ इतिरक्तसिद्धाणाचिकित्सा

उत्पलपृश्नीरदाडिमसमागधिकानवपप
यस्याच पिष्टैः कल्कैः सर्पिक्षीरेणसाधयेत्।
येन्मतिमान् नतुस्नानोनुसेवयेस्नातमेव
प्राप्नुयाद्धानी ५९ पभियाद्रस्मात्क्षीरीत
नरूत्वकसलिलाकांधारयेनवेभांडे रात्री
स्याप्यकषायोणानेन तं सेचयेच्छिरसि ५ २
आमलकरसेसिद्धानश्रम्लेविषपिप्प
लीशुक्तान् दद्याद्भोजनार्थं संसृष्टान्तो
द्वसर्पिष्मान् ५८ रक्तसिद्धाणकचिकित्सा
काष्ठलोष्ठाकषाघातैः शिरस्तापतितस्या
वा नाडीव्यापत्रिदोषैर्वातस्यस्रावः प्रजाय
ते ५९ वक्ष्यमाणकपत्राणि विदारीपाणिभ
द्रकेकाण्ठेयदनभृंगी च नतै गसूरसामपि ९०
तेनास्यभंगास्वेदेन निर्वातेस्वेदयेच्छिरः कु
स्यापामार्गविडंगेमधुकस्यदारुसर्षपाम्ल ९१

काठ पत्थर ढीम कोरडाइत्यादिक सिरविषेंलगानेकरके
नाडीव्यापत नष्टर त्रिदोषकरके वा तिसचोटके स्रावशि
रसेजलस्रवणो ५९ तिसको परणदेपत्र स्मालि निव
मषभृंगी तुलसी ९० तिसकरके मालसकोरहोपको सिर
विषेस्वेदसेककरावे मद्यो पुंडकडावायविडंग सलठ दे
वदिआर सरयों मूस्थर ९१

© Dharmartha Trust J&K. Digitized by eGangotri

शा. हरदल दालहरदल इनांकरके सिद्धकीये तेलकीनस
हो. वारदेवे त्रिफलारसविषे सुंठीपिनके तेलकरके मुंडमदी
२४० आदकसाथभोजनवास्तेदेवे ९२ आगंतकसिंहाणचि·
पाककेरोगकावडीदुर्गंधिवाला औरलालकाला माडेरं
गदातेलकेरंगदा कायके समरोगकासुतेअरुनासांते
यावगे ९३ जिस सिंहाणविषे मखी पडजावे अरुसुवे
तेदुर्गंधिआवे अरुवहूतखासहोवे मोहा लिसाहो ऐसे

हैनरजसौपिष्टानेतैलं साधितं नस्यं त्रिफ।
लासिंहाणमर्द्धान्कुसासौतेलेन शृंगवेरेण मा
गधिकासमुक्ताम्रदापयेद्भोजनार्थेच ९२ आ
गंतसिंहाणचिकित्सा श्यामसावातिदुर्गंधोर
क्तोनीलोविवर्णकः तैलवर्णकषायोवासुख्ला
नस्ताश्रयःस्रवात ९३ माक्षिकाश्चापिलीयंते
दुर्गंधिवदनंतथा खासोल्पोभृशंदीनोय
स्तमस्यविवर्जयेत ९४ इतिसिंहाणकाध्यायः
दोषास्त्रियाप्रकुपिताःशोणितसहिताःसमी
रणोद्भूताः मांसाते च श्रोतसिकानीतिकांतः
प्रलीयंते ९५ दोषोऽध्वनतोघसमासज्ञा।
लेसमाहृणोत्पत्ति एवमसोप्रचारकनामा
थैरोगःप्रोक्तः ९६ अथरोगनरोनराहाकि।
तानेथे दंतानीभिवरैः

घोडेकीचिकित्साकरे ९७ इतिसिंहाणचिकित्साध्यायः
वातपित्तकफरक्त एरहे कुपितहोएरहे वायुकरके प्रेरितहो
पदे नेत्रनाडीमार्गद्वाराकरके कनीनका नासा अस्तीका
मध्यस्थान है जिसके समीपविषे लयप्राप्तहोके सोदोषो
करके उत्पन्नमांसजाल घोडेकी अस्तीको रोकलेता है
पदे प्रवरकनामकरके रोगऋषियोंनेकहेयाहै ९९ अरुहे
दले उपरलेवर्त्मकेसाथ अस्तीको खोले चतुर फर·

© Dharmartha Trust J&K. Digitized by eGangotri

पालीकरके धोवे खवेहाथके साथ उंचीकरके कनी
नकाको सज्जेहाथकेसाथवडे ९७ अरुदोषअतीकेको
णको शुद्धकरे फेरमहीनसैंधालूणकाचूर्णकरके मखीर
हूतकरके अक्षीयांऊपरवन्द्रदेवे टलीकरके श्रीर आमले
कंवलकेछिलकेजलकेसाथ विसेखणनिर्मलकरहै ९९
अरुइनोंके सीतलकाथकरके अक्षिधुआवे श्रीरगोके वक
रीके दुग्धसाथधुआवे कालयंत्रकेसाथवंधनकरेचेउको ८०

तोयेन ततः सिंचेत् विद्वान्वोलिप्यवाहमेल्ले
न ९७ विंघाहतिताहल्लेनपोथये है कति
चौतन्न सैंधवचूर्णेन ततः आश्नाविचूर्णयेन्नय
नमक्षु ९८ चैलेनववश्रीयात्संचूर्णेलोद्रम
पि चा आमलकोद्भवरयोस्त्वचः सलोयाखुड
खलेत्ताः ९९ शीतकषायेणानेन शोचये
लोचने वास्य गोजावीणांतीराणिकालयं
त्रेणयंत्रयेतत्र ०० यंत्रवनीतेनेनहितर्पणा
महोताम्लघ्यानसं अभयासैंधवसदोकुला
सितमरिचपिप्पलीमूले ०१ लोद्रघृतेसि
प्रातःसायंचैवाजयेन्नयने तालीसपत्रमा
सीशीतशिवापीलदारुतगरेश्च ०२ काला
नुसारिवाकुष्ठचंदनेभ्र वशामलोशोः
पिष्टैव्यानननेत्रनसपुकेः लोद्रसैंधववि
मिश्रैः ०३

यंत्रकरके हल्दीतरांवं येहोषको अक्षियोंमें तर्पणं
अरुतसवारदेवे हरोड सैंधवलूण संड मचा श्वेतमरि
च पिप्पलामूल ०१ इनोकोमहीनकरके मखीरसाथ प्रा
तःकालसायंकालविषे अक्षियोंविषे अंजनसलाईपावे
तालीसपत्र छड़ गउी मसली पील दारुहल्दल तगर १ १
कालीवल कुठ चंदन नख समभागपीसके मखीर सैंधा
लूणपायके इसकल्ककेसाथ ०३

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ त्रामेका अरु लोहेकाभांडेलेपकरे छायाविषेसुकावे
टी॰ पवसुकजावे तो फेरमहीनरसायपीस अपासुकावे १७
२४१ त्रामेकेपात्रविषेंघसके अंजनी विषे सलाईपावे बुद्धिवान्
वैद्य जिसघोडेको पहेअंजनपाणीकरके पटल काचअं
जन वर्त्मरोग रक्तजरोग पिटका मांसचय मांसवध जाएए
पहेसभनाशहोजातेहैं अरु दृष्टिनिर्मल सौम्यस्थिर रहा
तेहैं अरु योमहीनवस्तुहै तिसकोवीदेखलेताहै थोडा १८

नाशायसंप्रलिप्याथभोजनंतेनकल्केन छा
याशुष्कंपिष्टंमधुनापुनरानपेननस्यादथ १७
शुभंनृनांअपाङ्गेणाक्षिप्रजयेन्मतिमान् न
हिपटलंचकाचोनेञ्जनकोनापिवर्त्मजारोगाः
नवशोणितजारोगानचपिटकानामपिमांस
चयः दृष्टिर्विमलासौम्यास्त्सम्यक्पिपिपपम
सौवाजी १८ अंजनमेतन्सततंप्रदीयतेनृय
नयोर्यस्य भल्लातकःस्वदग्धोमधुयुक्तोंजने।
हितश्चास्य १९ दृष्टाञ्जनःश्लेष्मपटलेचैवार्
बुदेचकाचेच शेरवास्त्रुपानयोः खलमन्त्रसि
द्धाचसेवयेदंकं २० निकामकृष्णशहितासा।
याह्नेभोजनेनचास्य इतिप्राकारचिकित्सा ·
काष्ठकषायूलोष्टाघैर्नेत्रंयस्याभिहन्या।
नेत्रस्य: २१

भल्लावेदग्धकरके माखीरपायके अंजनीमेंसलाईपावे घो
डेको १९ कतकीदारुश्लेष्मकहिहै अंजनविषे पटल अर्बुद
फोला काचको हरतीहै शेख पुडपुरी अस्त्रुपानविषे वेध
करके रुधिरनिकासे २० योनिकम्मकहिहै सो सज्जा।
विषेभोजनदेवघोडेको इतिप्राकारकचिकित्सा जिसघो।
डेकेनेत्रविषे काष्ठ छमककपा कोरडा लोष्ट ढीमचूतिका
इत्यादिकश्रोरकरकेलगे २१

© Dharmartha Trust J&K. Digitized by eGangotri

जिसकों अस्कपात वह्नत अवें सोजा और लाली होवे सनाही नेत्र विषे लगऐ करके घेउसाथ घोडके सि रमईन करावे ८० अरु अग्निपर सेंचन थोवए करावे घेउकरके वा दुधकरके दालहरदल का यफल मुलठी इनां कों सम भागों करके वकरी का दुधका उके पीतल करे ठंडा करके मखीर मुलठी साथ पिलावे अरु तिसविच छोलके

नस्यास्रस्रवनिषु स्वथपथु स्यानत्द्रष्टि रागस्य सद्योभिहते नेत्रे शिरः समभ्यज्य। सर्पिषा घस्य ८० परिषेकं नस्ते नेनाही रेणाञ्जनवा कार्यः दारु हरिद्राकटुफ फलयष्ट्यांगैः संयुते पयस्याजे ८१ अनशीतं मधीयात्संयुतं तोइ मधु। केन नेत्रचयन्नवनीतेन दृष्टिपरि। षेचने समुद्दिष्टे ८२ कटु शोथयुतो त्यात्नशोणितविस्रावणं कार्य्यं चेले नाद्रेण तनो विलेविनाचावमुंडनेशस्त एवं काका परिषेकाः हुतेन पाचनेन च। दातव्यं ८४ प्रतिलन्नचिकित्सा॰

मखेणयो करे आहे सो अग्नि उपर सेंचन केवास्ते करेया है ८२ यदअस्ती विषे पारेक अरु सोना क रके मुनहरोण नव रुधिरनिकालणा करेया है केर गिलवस्त्र करके वंधन करे लेवके दोष को अरु पलेटेनो घ्रेहगुण है यो सर्वविषे परिशेक करे देन सोहुतविषेपकाय के देणयोग्य है ८४ इतिप्रतिलन्नचिकित्सा॰

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ टी॰ २४२ पित्तकेदुष्टहोएपर्यंत अक्षिकेनाडीद्वारविषे फोडुंएनीयां
तवहरीयांवा कुकुडकेअंडेकेसमवर्णवालीयांहोतीयां
हैं ९७ नेत्रकीकेसारेपासेरोकलेतीयांहै तिनांकर
केनिकसेपायोजलहै तिसनेछुरकहोतीहै पहेअंड
तारनामरोगकह्याहै इसकीचिकित्साकरावेचतुरवैद्य ८५
वर्त्मपक्ष्मकेमध्यविषे योपिटकाफोडुंएनीयांहैं तिनांको
शस्त्रकरकेफोडनेवढे फेरघुटकरे सैंधवलूणमहीमधी

पित्तेयदाप्रदुष्टेवर्त्मनःस्रोतसुजायतेऽ
स्यपिटकास्तुहरिताः कुक्कुटाण्डोपमास्तथा
वा ९७ आच्छादयंतिदृष्टिंःत्वातस्तत्तुना।
शजायतेकेतुः अंडतारसकथितःप्रतिक
र्मसमाचरेत्तस्य ९८ वर्त्मांतरेतुपिटकाः
शोथाः शस्त्रेणमूलतश्छित्वाः सैंधवचूर्णे
नततः शोणितेनहर्षणेनकुर्यात् ९९ मधु
कोत्पलकिंजल्कपद्मचूर्णेनततःसकटु
फलेवदनेतथालोध्र आमलकरसेनैत
न पिष्टाकल्कीकृतमेव ८० तेनततनवा
शःरवेलिप्ताघर्षितशोधयेत्क्वाथं मुष्कचूर्णे
नमेतस्मादनेनमेवमधुसंयुक्तं अंडतारवि
वर्त्मःस्रोतोगतरक्तेतापयतिनयनम
स्यर्थम् ९८
सकेतिसकरके
उपरवधूरादेवे ९८
अरुमलठ कामलकीयांनरीयां पवहूतकेचूर्णकर
के अरुकायफल वेदनरक आमलेयांकेरसकेसाथ पी
सकेसमभकल्कबनावे ८० तिसकेसाथनेत्रांमोयांसर
इयोलेपकरके छावासकावे मकाकेसहीतचूर्णकर
केमरवीरसाथसलाईपावे इतिअंडतारविः अक्षियांकेमा
गेहारविषेरक्तआमहोकरके अक्षीयांकोवहुतसंताप
करताहै ९१

242

© Dharmartha Trust J&K. Digitized by eGangotri

निसकरकेनेत्रविषेंनिकसेपानलसोगुल बुलेकीमा
ई कालाफोलाहोमानाहै सोम्बहिकोंमललेनाहै श
हलालरुधिरसमस्रवतनेहैतनतिसकरके ९०
बुद्बुदरोगजाणकरके पहेचिकित्सकरावे अर्जुन
हत्तकेसिकउसश्रोकहतकेसिकउ मलटोयहेसम
वराबरउवलविषेकहै इसकेशीतलकषायकर
केवीउकेनेत्राकोंधुआवे ९१ नेत्रवाला छइसरदीस

नेत्रजलसुतुद्यामेक्षणांवैबुद्बुदेभव
तिनत्राहणोनिनेत्ररोकेचाभुपरिव
नेनेनेन ९० बुद्बुदमेवेत्रानाक्रियामि
मोचास्यकुर्वीत कुंकुमाश्वेकमधु
कत्वचः समभागामलडरवलेहाण ९१
शीतकषायेणानेनमेवयेलोचनेषु
सु पलावालकमांसीपुष्पेशिरिष
स्यमधुकेच ९२ कालानुसारिवाम्रा
नम्रामलकाः प्रवालानि सर्वेसमन्
यान्सलेलमनेशीतेकषायमारा
य ९३ मंजिष्ठामाधुकाद्वेशाः पिष्टान
द्वेवसेयोज्य ॥

रोहिकेफलमुलटी ९२ कालिकेल नम्यनीलाथो
था आमलीकेकोमलपत्र इनांकोंजलविषेशोउ
केकाढेफेरठंडाकरके लेवे फेर मजीठ मुलट इ
रदल पीसकेविव इसकेमिलादेवे ९४

© Dharmartha Trust J&K. Digitized by eGangotri

भा°
टी°
२४३

जिसविषैवोरुपावे फेरसभतांकोंकाउरसुदरमांउवि
षैपवकउछोकोंववउनेवालाहोजावेतोवुद्धिमान् उ
नारलेवे ५४ जिसकरकेप्रहिमै अंजनकरेनवहुउ
दरोगवालाभोराजीहोजानाहै औरत्रिफलाकेर
सविषैसिद्धमंगीघृउ मधांमध्वोरकेसाथ्यलोगोंको
देवेसाहितकरैहै ५५ इतिवृद्धदावि° वायुश्रुककफके
कोपतें अहिविषैकष्टकेसमउपकाचनामरोगहै

द्यात्तैलेवपूर्वेणसर्वेतन्त्राणायेषुभेभांडे
सिद्धं दुग्धपलेपनेत्तांबावतारेषमाः ५४
नेत्रकांतिनयनःसुखमाभातिदृष्टी
तरगः त्रिफलामहाघृतेनाविषक
णाद्यैःसंयुक्तः ५५ वृद्धदारिकिन्ना
भावेनकफप्रकोपात्काचोवेकाचम
क्षिभ्यानयने स्वेनोचापीनोवारको
वानायनेस्वमा ५६ नेत्रकेनेनयनेतो
वेवायुप्रवर्तनेमनते नवशिरावेयद्या
मेमाषालाल्पानेषु ५७ पटेउमधुक
पद्मकलोभ्रोषोगाराणिदार्करमनोव
आमलकानिवर्पिष्टानतेनगोहोद
केविपचेत् ५८

सोचिटाकाधोला प्रधवालाल
वोरकोंरोनाहै ५६ जिसकरकेनेत्रकेउपरविस्तारहो
वेहै तिरंनरवहुलनउघु वृगहेइन जिसरोगविषै मर
न्याधारव अमृपानरनोकोंघा नाडीया वेमनेपागवहै ५७
परस्ता मुलहठ पद्मकाष्ठ लोघर वीरणहित्निउदाल
हरदल आमले इनांकोंघोसकरकेरसविषै सवीर
विमपाव कैपकावे ५८

तिसविषैवेदोषपावे फेरसभनोकौकाढेअदरभांडेविषै
पवकरछोकौचंवडेनेवालाहैताबैगोभुत्रिमान उता
रलेवे ४४ तिसकरकेअद्विमे अंजनकरेतव बुवदयै
पड़ैयारिसेकअद्विकेउपरकणीकरकेअद्विकीपीडा
अरुकाविइनोकौ नाशकरैहै गोकादंतसगदरण
कादंबरनकाअंजनहुनकेसायपावे ४५ औरा
ऊटकाअरुगोकेकुतेकेदंनमरिचसैधालूणइनो
काचूर्णमखीरकेमहिन सौअंजन कावकेहर
ताहै इतिवानकावचि· यौकावगोमेदमाणिके

पथ्यपारेषिकःस्याद्रनायहः कांचनाश
नःकथितः गोदंतेभसगदंतेअंजनेतु
नसंयुक्ते ४५ उष्ट्रगोश्वदंतामरिचा
निसैंधवंचसंचूर्ण क्षौद्रेणसमायुक्ते
नदंजनेकाचेसशामने ४६ वानकाव
चि· गोमेदकमणिरावर्णःकिंशुकव
र्णोथमुकवर्णोवा शिखिचंद्रिका
सवर्णःकाचःसंप्रतिकीर्तेयः १
सर्वोत्मानस्पर्शगवेष्यापानेसमद
केसैप मधुशर्करयाभिष्यकल्के वा
त्रापमाणाभ्यां २ मधुनिशालयोतेन
द्वनेनवैकारयेत्सदर्दन॥क्षीरेणानसम
क्षिप्यालेपयेवटलसोचाम्प २

समरंगवालीहै वाटहूहैकरंगसमहै तोनेकेरंगहै
अथवामोरके परके समरंगहै सोपितकरकेजाना १
तिसविषैपरवैविषैनाधीवेपकरैयाहैसोकरावे अरु
पानमखौरजलकादेणकहैयाहै अरुमखीर खड़के
अरुसाथगायमाता वननामा काकलकमगदरदेव १
अरुशिरकेऊपरसोजलसाथयोयादाहुनकालेपक

© Dharmartha Trust J&K. Digitized by eGangotri

गवेमस्तीरकेसाथउपकोनेग्रविषलेपकरावेघोडेकी २
दालहरदल मलटगलोइनाकेटोटकरकेजलविषे
इनोकाकाथपववीण्या हेसारहेनोपुणकरकेफेरग्र
मिकेउपरबालेइहेव निसको ४ यवकइछोकोलेप
हेगलगेनिसकाग्रननकरेपेनककाबविषे घोडेयां
केनेत्रमेंसमकियाकरणकोवहूतनेष्टहै ५ कमलश
खरमेंमलोपरमलटीगेरीमिलाकेसमभागग्रामली

दारुहरीहामधुकेहिमवेखंडखंडश्रम
लिले काचेनपादशेषेपुनरग्रेसाथ
पेनेन ४ राठुपलेपेनानानटनेनेषे
मिकेनेवाहना नयनेषु कुर्याद्दम
क्रियांमन्नके ग्रेहे ५ उत्पलमांखरसा
ननतोयपहार्द्दगेरिकोतिसेः सम
भागैरामलकीरसापिष्टैः लेपः शिलां
लिपेत् ६ शुष्कननयोनोंजनसहि
नेभयःसेपषयेन मेहंग नयनामये
येनवारम्पेतिकेवकनेहिमे ७ काव
वि॰ प्रथदोषपरिवरमांसखुदोनं
समाहराणान् नस्पटलेजानोपानेन
वहूनेवहरणम् ८ विधानवत्मानिनलोव
नेवविनालपडुवेरवे: सत्थायंगाविधापरिसमग्रालाकपा
नपुलः ९
केरसाविषेपीसकोनिनंकारकेमिलाकोलेपकरे ६ यव
पे घोडेकोग्रहिमेमला३पावेग्रहरमकेजोविषेविहिनहै
इनकाबोवे॰ दोषवानादिवरेहोय मामकोप्रकटपिपु
कोग्रावणाकरलेनेहै सोपटलजाणो निसकरकेवो
णा वहूनग्रणुवगानाहै ९ ४॥

© Dharmartha Trust J&K. Digitized by eGangotri

तेसांविषेंवर्त्मपक्ष्मकोंवेधकरके अक्षिकोउपरवि
षैविस्तारे - - - अरुस्मरकरकेअपांगअ
क्षिकोउपरकाभागतिसकोवेधकेफेरअैसे मालाका
सरमबुसाथबुद्धिवानदेखे तिसपटलकोभेदकर
केक्षिले कनीनकानकरमलीनरोगैरमुनकरके
शस्त्रकेसाथपटलकोसारे कोउतारलेवे ९ फेरम
हीनसैंधवलूणकाचूर्ण उसकेऊपर बुरुरदेवेअक्षि
विषें अरुवेउगमलीरकरके मर्दनकरके टलोकर

इत्थाभिनावैनेविलिखेयदाकेनीन
मथसमाकपरिमृज्यशास्त्रणतमम
उरेमपटलमथसम्यं ९ सैंधवचूर्णन
नतःश्लेोमावि चूर्णयेत्रयनमस्य
वेलेनचवधीयान्संमर्द्य हौइसर्पि
षो ११ हरितालकुकुटोउकपाले
काञ्जलपिकेनशंखेन निडकवीमा
निशिलादेनाव्हमसमचूर्णये हौदि
एमेशक्रमेननमेनसारिषचनेपयो
मिश्रं आमलकमद्भोजनार्थमा
ज्यकरणामेपुनेशाले १२ पटलंदिवि
वानोनूतेयमेनेत्रेमंबीपानेपदाश्रम
श्रवणौहसनंनवाम्प्रोक्तासनदापुरे
सावो १४

केउपरनेवशीदेवे ११ हरतालकुकुडके
अंडेटे काजल समद्रगग शंख कुवलेमनशिलाऊरका
दनरनांकाचूर्ण मलीरसाथ पहसल्ला रहे अरुदहके
साथनेत्रोंकोसेचनकरे पावे अरुआमले साथमुंगी
तिसके मदांचेरेसाथभोजनकराविंदं श्रेष्ठहै १२ इसिप
टलविं वाधकरके उठापाहेयापीमनग्राकेसीकिया
होके यवनलवीउगमपानतिरंतर श्रवणदरे नेत्रनेसो
परिश्रमाबीरोगकहेपाहै १४

© Dharmartha Trust J&K. Digitized by eGangotri

परणीजडनइकोजइनिलसेवेयांइनांकोकुटकेसी
नलपाणीकेसाथ शक्तियांविषेसेचनकरावे १५ मा
लतीफुल गडीलेके भलवराबरआरकुट येइमरवी
रके सहित जामेदेम्रुलोहदेभांडेविषपायकेसि
नगवे १६ इसकरकेअंजनकरणेतेंनेत्रदहिवालेहो
तेहेंनपरिस्रावीवोडकेसमांचेकेसाथमुद्रसंगी
भोजनवालेसेअष्टकहिहै १७ परिस्रावीकि॰ इत्यादिविषे

पंडेस्पनलस्याव मूलानिनिलाः सर्षपाः
शुक्ताः पनष्टोनाभूतनेत्रपरिषेवने
कार्यं १५ समनाकवरोरस्यचूर्णाणि
समानिकुष्ठमिश्राणि साग्नेलोहपुता
निचनास्नापसेस्थापमेभाटे १६ पंते
नांजितनेत्रस्यदहिमानजायतेपरि
स्रावी शौरीहूतस्तुकामक्षापथ्यभो
नेनेसत्ता १७ परिस्रावकि इत्यादिवन
स्यापटलेनवकोयानुपवर्तनेचाम्नुवन
पवनक्षमास्तःपश्यानियोनेवतूपाणि १८
तेसुख्यपसमस्थेनयापिकुर्यात्सांकृपा
नामुप शंखाभुपानयोस्ववनुपयेमसयो
ग्यांसे १९ शंखसमुद्रफेनेनमीनप्रापालि
नेइला सनपा प्रतापिटमपनाननेदंनेनंदापयेत्सति
मयाजः २०

नेत्रकोंपटलवोनहिं मुकुचाववीनहिं स्र
वनमुचावीनहिमगवे नेससमवखाप्रकारकेअंजनदो
नाहै तिसकोंग्राइशक्तिपुकोनहिं देइवात १८ सोसु
ख्यपासकेइयाहै सोससुध्यपसाध्यहै नहवी पहे
लिकिस्माकरइसकी शंखवइपुडीयां अनुपान सयार
नाकोंयानाइगांविषेवेपकरावे १९ शंख समुद्रफेन
मनीटपालिकेवावल इनाकामहीनपीसकेसवीरसाथ
वनइमलाईपावे २०

© Dharmartha Trust J&K. Digitized by eGangotri

और शीतल परिषेक अरु लेप और शीतल क्रिया करे
हृतन सबों के साथ आमलक रगड़ लोण को देवे २१ मुखमें
पित्त स्थान को फोड़ के वायु कफ पित्त को आम होवे
स्थित होने है न २२ अरु रेया होया वो आंखि लिखेता
है सो स्वरूप को न देखना अरु सेवा को उठे करता
है इसका नाम नायंप्रोक्तिक कहिया है २३ जिस को
इस वां विदे मस्ते हृतनके मेड़के साथ घस के वैद्य

अथशीतैःपरिषेकैरूपचारैःप्रदेहये
त्पिप्पलीहृतनिम्बान्धयादमलकम
ज्ञोथ्य २१ मुखेपित्ते स्थानान्स्रुतःस
मीरःकफपित्तेषुवेगेननःसर्वे चलः
स्तोतसमुगतारहिप्रकोपयतिहेति २२
सेतोन्मोलिननुयनांरूपाणिनतोनय
प्रणालिरगः उद्वेहेरतेयादोमायप्र
तोत्मसोमाक्रु २३ नस्थानतनस्यमृदी
क्रस्माघतानिभ्रेवमारिचाति हृतेन
इनपिह्यानिदापयेन्मातिमाम्भेषः २४
मातीप्रवालयष्ट्यालोध्रकणाविम्ब
गोरिकैःपिष्टैः पद्मोमधुसंयुक्तैरेनन
मेनजिनेवापन २५ नायंप्रोक्तिचिकित्सा
वायुःकुपितःस्थानात्सक्समादापयचलषो
प्रामः नेत्रेरमकेमनेकरोतिपिटिकांच
नेत्रयम २६

मलायपावे २४ मालती कपड़ हरीड़ लोद्र
मधु गेरु गिरि मुलट्टी मस्कीर साथ पीसके पद्मांजन अ
अनुगुण करे इति नायंप्रोक्ति चिकित्सा २५ नायविकृत
हो के अपने स्थान से रक्त को साथ ले कर आंखि में आगमरो
नाई निमककरके आंखि लाल अरु शोज अरु फीड़ गीधा
करके पक होती है वो रस की २६

शा॰
टी॰
२४९
248

रक्ताभिस्यंद में लाल अश्रु बहते हैं नेत्र बहुत अरुण पित्त
कोपा रेखा दृष्टि के पास होती यों कहैं २७ शुक्तियां अभि
स्यंद शुक्र देख कर के टर इच्या कर के नेत्र धोवे अरु शी
तल लेप करे निरंतर २८ नागर त्रिफला चंदन त्रिफला
न सेंधा मिर्च शंख नाभी पीत चंदन इनों को बकरे दे
मूत्र कर के पीसे २९ यह अंजन नम खीर वैद्यक के साथ
पावे तिसको संगी आमले सोथ सिद्ध हुन पाप भाजन

अथ रक्ताभिष्यंदा इक्षुर्वा शुभवनेने
त्रयेषु गास्यः शोणितवर्णा स्नुषेहमासा
घ्नापते २२ अहेगताभिष्यंदे दृष्टावे
नेऽस्मारभेकर्मः अथशोनेलेपादिदे
होनेः परिषेचयेस्तने २८ नागरंत्रिफला
चंदनं सतनं शंखो शालनाभि समाङ्गुले
कालानसाभिवा वैवपेषये इलस्थेरा २५
कृपोदंननमेतन्नं सर्वरोहेभ्यां पिबा
वास्य आमलकैः सहसिद्धं स्याहानहे
तमेस्तनात्यात् ३० नेत्राभिष्यंदावि
कफमारुतजो यतः सितवर्णः स्वत्रेतन
विरल्मः शोफसीवतोपमध्येषु श्रष्य
नेष्पदमानस्य ३१ स्नेहम्नंजनकोवेदा
मूनेभः क्रिमिः समास्यानः नेनास्यजा
यमाभेनरश्नपेनसकलंखेनेत्रे ३२

टीका ३० इति नेत्राभिस्यंद चि॰ कफ वातु करके एक नीव॰
होता है त्रिफला वर्ण रोगरक सूत्र कीन दको न्याई मुहीन
नेमजल के मध्य विश्वम कौ कार बचा हलदा दारवी दाहै ३१
नेमे नेत्रविषे प्रजोत हुदा है अमा पढ़ इस नकनाम है
वेद मा की त्रिफला के समान मिक है या है तिसको सो
नी पावे इद कहने है तिसके लेपदे अति लहना नाहि नेत्रोर

© Dharmartha Trust J&K. Digitized by eGangotri

रेहोतेहै १२ जैसेप्रानसमेसत्त्व बदलकरकेचंद्रमाका
चित्रप्रादनकरेगाहोवे जिसकेथोडेहोतेहै उपरांत
पंचरात्रिनहिलपदा अथवासतमेदिन पहलेपटल
विषेमंनदेषीदाहै सोसतमेदिनमेदिनविषेपकपट
लेने इसारे पटल पडदेविषे जाताहै १४ मंजनपहले
पडदेविषेसाध्यहै परंतु इसारेकावीहटदोहै पवनी
सेरेपडदेजावेनदवी उपायकरे १५ चिकित्साकरदे

प्रातःप्रातरमेननवधेशौवरंजनिकरविं
वे सोलस्नाह्योविराद्रेपंचमेचनरूपयने १३
प्रथमसमाहायकः प्रथमेपटलेमरूप
नेनेन सम्माहोमसमाहान्यपटलेपटलेस
मावराते १४ प्रथमेपटलेप्राप्तेसिद्ध्य
तिमेंजनसथाहितोयेपि प्राप्तेपत्नस्य
मीयेनस्यादपिकारयेत्क्रमं १५ त्रिपम्पा
लोपिकर्मागतःकालः पटलेभवेवन
येन पवेनामामेत्रेजगालेगाववसमहरे
लिपे १६ सर्वेनिपीड्याविवन्म्या
विधायवलनोवास मूर्ध्विमानये
दष्यलंकंकेनपरिमार्जयेद्दृशम् १७ प्रा
सादिसेनयत्नेसयोत्रिनेविस्तरनेभिषक
कुर्यात् येगहेननेयेमनः समाक्रमपनिस्य
लेकृत्सा १८

होयकीवीपडदेविषेगेयदेसीहा
काणहोजानाहै ऐसेमंजमातीपोविरजाणकेसमा
धी शामकेसाथकरके इरकरे १६ ...

शा
हो
२५७

247

अपांग के पास काले अरु सुपेद के मध्य विषे वेध करावे वल
ना होय यो मे जो देनिस को स नावी श स्न कानी हाग अग्रभाग
हे सो वला टे वेचने रजिस मैं नेत्र को शरविषे वा घना होवे वे
ध करने हो या वाडे के इसके हर की नरो विधि के करे होय
अति नेत्र की धार सनावी चलनी है ५० तिस जल धारा के
वेग कर के मं जन नेत्र सनावी बाहर निकल जाता है वेध क
रके नेत्र को जल के साथ धोवे बन्दर वेध ५१ अति को मलो

किंचिन्नवांगास्त्रिनवपक्वसंधिमन्नो नरे वे
धं मंजनस्मनसंधारनः तिग्धशस्त्रेन नत्रोन्नतो
दयान् ५२ नयथा तुणात्रलोवनको धवा
हृथ्यानेत्रस्य समथोविधेन नयने धारा
यतो शोग्रमायाति ५३ तिर्गच्छति मेजा
लेन वारि वेगन वैविध्य विउस्पनमोनेत्र
नोपनसावपनतः प्रात्तः ५४ वेहणाव
वधीपानस्त्रुणोहोइमपिभ्मो पद्दोमधु
कष्ठशीरमनिश्छपमकेषारवेव ५५ सु
रदारुश्रेष्ठीकेमधेनिटपवपनस्नसा
पपमामकर्ष्येनयोनविस्नाविनेननानि
ष्प ५६ नस्मादिमेचनेस्मामवोहृपाहृ
व नानीसयमगेरिकनगोरेः मधुकेनस
युनेः प्रविष्टेः ५७

रवैरोसे भर के कपडे साथ वेधन करा देवे मनल व बीरए
रो न इस मोटपम काहु के पार ५८ दिध्रार कमल मु
हेडा होयवे निन्य इस के साथ भ्र थ कर के
थ अहिपुन्नाव मानविषे सांपुकाल मे नलीय रगरीन
गार मुल दोरनाको मर दीन पीस कर के वेरा मखीर
इमाथ अति पोवे ५९ ॥

हिंग्वार मुलट वेदनकायफलकालीबेल बीरलाजरो ४५
नरव कुट छड़ॆउगुड़ी छलीशाकमलकीयां नरीयामसी
रा यहे मठेसाथपीसकेकल्कबनायके ४८ इनांकेसा
थ ओमकापाग्रलिवदेवे छायाविषेसुकावे फेरमरवो
र·साथपीसकेग्रनन्नकरावे ४७ त्रिफलारसकेसाथपिस
ल्मेगी मलोर षड्गोमिलाकेखुलावे रसकेउपरनग
तिमनकेविषयेचिकित्साकहिहै सोचननैवैयकरावे ४८

स्रहैणामिषुहृन्नामिश्रैमलंदेननेत्रयोक्कुर्या
त् सारदाकमधुकवेदनकटफलकाला
नसारिवोग्रेणैः ४५ त्राह्नलवेकुष्ठमां
सीमेलवाप्यकेसरेवेव यष्ठिःसघेउरो
कैःपिष्टैर्देआवमिश्रैलैःकल्कैः ४६ लिंग
नन्नास्तुभाजननमेत्रेछायाविशुष्कैव ४७ः
भिष्टैवेतन्तोर्इकार्यमंजनेत्रास्य ४७ स
ह्लाविफलाभिर्घ्नभोजयेन्नोइसर्पिषा
श्रनत्रयेधातिनमध्यपाक्रियानोसमाव
रेन्मात्रिमान् ४८ इत्यौनेत्रवषत्रमसदत्यां
मेत्रोसरोमवतिनि ४९ मनोचि· हीनावे
कल्पयवानायतेयम्नालकानपेन
गेगुनत्रालकाउत्क्रोगेनयनोऽवमसा
ध्य ५० नत्रामाध्योक्रियाकार्यायेनानद्य
भेवइनो मलानकेमदयाषिहेनदेनने
मधुना ५१
ग्ररुवापवासेडुबाखवल ग्ररुडन
हेषतकेभमदेवे नवमेनरोग बालाचाइसरवीहोना
है ४९ इनिमुनयि· होनीग्रलवापकविषे जिसकेनाल
काइहोवे सोमनत्रालरोगहै सोग्रसाध्येहै ५० योनिस
कीचिकित्साकरेसोग्ररुषमनष्या स्वामी हीरेकाग्रन
णीहोनानाहै विषमरदारहोनाहै मलावे नालके
पीसके मलीरकीसाथ मलाइयावे ५१

मैंध्यालगा गेरीअंगुष्ठमध्यांगुलीरखनेसेकेसिकउसमुद्रफेन
अरुगेरुकेदंद ऊटकेदंद अरुवाल रनोंकोमहीनपीस
केवैघघोडेकोअंजननपावे अरुस्थितिविषैवैपमंजनाल
कोसमनकरताहै ५३ इतिमंजनालवि घोडेयांको
वणवापदेसप्रकारकाकहेयाहै पकशरीरवातादिर के
प्रकोपोंसेकरकै ५४ अरुदूसराआगंतु कहायादिसति
दग्धताशादकोकरकेआगंतुकवणवाप चनुरोंनेक

मैंपवैगेरिकअंगुष्टीमागपिकालीमेकालवा
वैवनत्रोदपिनःकेनोगवोहृदशनाघ्रघा
लाघ्रः ५२ एभिःस्त्रलैर्णिर्ष्टैरजनमपहा
रयेद्भिषककवाम ग्रलेणवैयश्रोहितःसश
मनोमंजनालस्य ५२ एवंमंजनालविके
त्साध्यायः द्विविधव्रणोद्दयानांशारीरागं
नवस्तथा दैहा शारीरोवानाद्येःशोणित
युक्तैस्त्रिभिर्दोषैः ५४ शस्त्राग्निरस्मायैदे
याद्यागंतवोव्रणानिप्रोताः अग्रपलक्षण
मेतेषांप्रतिकंभवदवतेनधुना ५५ वेदना
वैराराद्भकेनभोजनेनाथवाउहेन न्ता
पेतेनरगाणामव्रणानादोषोरूक्ष्मात्प्र
५६ विगम्रचवास्मरोपिकस्मास्मावी
घवानमःपकघः लोहितनीलसाको
घाणस्तापिनोरुवोन्नेयाः ५७॥

हुयाहै अबरनोंकेलक्षणअरुउपायकहतेहैं ५५ वेदा
हनतेलादिकपथ्यभोजनरहितपवनेने औरक्षककरके अ
घातभोजनकेविहनहोणकरके रक्तविहनहोणक
रकेवडियांकोदोषकर शारीरव्रण स्तावीहोजाताहै
जिसकामलमत्रनेपाशाण पथरकीगंधआवेअरुकठे
रकोलेरगहाजलवगेभेसाव्रणवाप कापुका नालोति
सनेलाल अरुकालारसवगेनोपित्तकानाणे ५८

© Dharmartha Trust J&K. Digitized by eGangotri

पीड़ा मस्तक वा गाढ़ा रहै अरु ऐसो ही वाह पक्के है सो पित्त रक्त
मिले का जाणो रक्त में रक्त अवदाहै अरु सम रंग होवे
तो संनिपात तें जाणो ५८ यो व्रण स्वेत रंग कोमल छ
वे थोड़ा अरु थोड़ी पीड़ा होवे सो कफ जन्य व्रण जाणो २
तो सब मैं कौ यो अठ प्रकार कौ यौ गति यो कहियो
है ५९ यो पक्का नहि निसका नहि निसको शोफ
विलय वठा यदे लाम्भ रे को शोथ के पकणे कौ हो

लेदी मौघीदा हो शोणितागमो न स्याम
मस्यकारकता वो मर्वं गुणाः सेवेषा
तेमयः ५८ येतेषां दशावो तेनेयामे
दने दनकफन्नः वनेषां मर्वं भोगाजय
स्त होमसमारोमानाः ५९ प्रतिदयसा
स्ववथ्याः सर्वं प्रातिलापनेननः पश्चात्
कुर्याद्दाहमानेव पथ्यावलयाचने
वैद्यः ६० पक्के व भेदने स्यान्नतोव्रण
पक्रमः समादिष्टः सर्पिषैष्वहृयानो
नणाच्चुपारेपीटनेशामे ६१ अल्पासु
रवेगालिंनेकटिनेवसकेरद्वणामि
घात्मांसमकुरेल्पश्चकेइघुवतिणसं
शो धं देनोरसोनमषपश्चटोमरिवा
निचिक्रकेकुहे ६२

पक्के को निसको वैद्य निश्चय
करि पकावे अरु पक्के होय को फोड़ देवे वी करावे ६०
निसके रागन पीवलिणाय क्रम विधि करे पोहे सोकरे
पीवो रैकी संधोयो इविधि यासहै निसको दवा पुकमुज
करना अरहे ६१ अरु यो व्रण छोटे मुख वाला है अरु
नाड़ी ना ग्रावगरा रहितो है कारो है सब के बाला ओसेव
णकौ मरके मुज करावे अरु यो वायमूलमके वं करयु
कहै अरु इहा निकमनहै निसको देवर के माय मुजर कैर

© Dharmartha Trust J&K. Digitized by eGangotri

श्रा
टी
२५१

24p

हैं दलदारण्योमसरेथां फुंडमनिविबसिद्धाकुष्ठ ९२ हरद
लदाल हरदल इनोंकालेप संधिकीयाकी ग्रणीयोंका
नाशकरहै इनोका नगदा पहेश्वे श्रेष्ठ विपिनलूणति
लश्चल्पकारकेमूश्रमदार इनोंकापनयोनेके प्रवाणवा
लाहै सिद्धार्थादे तेलवा औरतेल केवललूणकेसाथ ९४
वैयने तिनोंके प्रकारो वाप्नेयहे बेधनकरणवाश्यम
केहोयदे भेदकरे फेर हरदल ग्रहणमलूणमैथा ९५

हेन रक्तमोक्षेण मोविनाशनेदेथि पिटका
नां पचानिके एवमेवापवलवणानिति
लान्सेथ वमनानि ९३ ह्यपि सम्यकुर्या
दुपनाहंते पाचयो स्वयथोः सिद्धार्थैर्घै
श्चामैस्यलेनालल लवणांसम्यके: ९४
उपनाहः कर्त्तव्यः स्वयथूनांपाचने भिष
कजा पक्केभेदनमुक्तं तेनांगेनप्रागारप्त
मलवणेल ९५ विष्क्रेणांकसुमाश्र
येक्केवं पिवमर्दनलवणं दनोगनिलेश
संशोपनेजणालांक ९६ पंउपमकः
ल्कोव्रणकशोपने रपणम्प्रः मधु
पकं सम्यक्कोनिवपत्रान्निलोद्भवः ९७ पि
ण्डःसंशोधनः प्रोक्तसरगणानांव्रणेषुच
मधुसंपवद्दीनायपिशंनिवनिलोद्भवः ९८

इनोंकोंपीसकर्कै घायविषेभरदेवे औरमलेपश्लिकरके
निवलूणमें धाविलिसबार हरुपादाणोहै नरुनिलइनोंके
पत्राकापाकल्क हेसोबापकोशुद्धकरश्रकृ यपरकोंउ
हलीविषेश्रूहै निवपत्रतिललूणमलौरकापिंडम
गदा चोइयांकेसाथके शुद्धकरणेविषेकहेयाहै श्रुके
मलौरलूणोयोंविना निवनिलेकाकल्क श्रोणके साथ
इरणोविषेशुद्धकरणोविषेशुद्धकहेयोहै ९८
रोकसंशोपनकरे योश्रणोविषेकहेयाहै ९९ पत्रणके २ स्नु

© Dharmartha Trust J&K. Digitized by eGangotri

[illegible]

© Dharmartha Trust J&K. Digitized by eGangotri

भा
प्र
२५०
250

सर्वांमरिचसेंधवावडिंगहळदउगडीसबाद पोगोवरका
हरदल नीलाथोथा मनसिली हरकलदालहरदल तेली
सपत्र वायविडंग इनादालेपकरे १४ दियारकातेलकि
लौ छडउगडीपहे व्रणकीपांसखोपाकौ हरकताहे
तिलसरसोरल्लणग्रकचेडोमांसकोवधावताहे १५ हाल
धूपलोपर हरताल मनसिलाकूटलाल पथीमालते
पीनपुष्पा प्रनाग गेरु मोदैया इनांदे रसोकरके १६

सुवर्णविडंगहिंस्रादांतीग्रहधूमशेवना
तुत्थैः लांगलिकारजनीइयतालीशैः
क्रिमिहृत्तैलेपः १४ स्नुदार्कतैलशुक्ता
मांसीव्रणमांसंकोनिवारयति तिल
सरलव्रणशुक्तसपिंमाषमवर्द्धयति १५
मर्जरसलाक्षकसहरितालमनःशिला
कुष्ठैः लांतासवर्णापुष्पोषुत्रमामानिर्वो
समोरटरसैस्त १६ शनपुष्पाशोणटा
कांत्रियंगुमारवैः कनकतसमभार्गीरस
पभिर्विपाचयेत्तैलेसर्वव्रणरोपणांश्च
ह सोमांसेलानकुलस्यानव पटोलपि
चसर्दी पिप्पलीकूटस्नात् १७ दस्यान्
समैमसेतेलान्यावाव्रणरोपणाश्च्छा द
मौरहरिद्राद्वयानेलापुष्पमामतिश्रावैव १८

सोपनुलनागरिपंगुमारिच पदमभसमलेकरके तेलप
कावे सोतेलसभप्रकारके व्रणकोरोपणकरतेहे १७
मासमानिलतेलसभकूलथपटोल पत्र निंब मजा कोगा
इ इनांकोगइ इनांकोदरधकरके इनांकीस्याद तेलमा
थ पंगुरचाइमेको हरहै दम हरदल नालके इन
कीस्याई तेलपुष्क व्रणके रोपणकरताहे १८

© Dharmartha Trust J&K. Digitized by eGangotri

अरु ये गोंविषै वालनमावती है व्रणकों शुद्धकरै है अरु
अंगूरउठावती है ऐसे व्रणकरै है मरेया थोथा नलसी म
ठ्या त्रिकटुम सैंधवलुण एकसमभाग इनाकों गोमूत्र
मायपीसके वोडेयोंके घावके उपरलेपकरैए है व्रं
णकोंनाशकरना है १९ पवकोरकू अरुपीडा गोरहै देख
केसपणाकियानदकरावे २० इनिव्रणवि. जिसव्रण
विषैपाकस्थिनरहि है अरु चिकित्सानहिकोरि नव

रोमोरोमसंजननी मासोणधनी सेपली श्रे
ष्मास्वेपरसोनस्रसा फणेनकाया
श्चमलवणानिरोगेनवातोक श्रेहै गोय
व्रणुकानिपिष्टानि १९ पश्चह्यानांमलेप्र
व्रणेषुव्रणापरः श्रोमाकः केरराहिनमवे
दनश्चपकसेदोणाणायस्तु २० व्रणावि
किस्सा रूपास्थितप्रमाणाउरोग्शोर
कभविवाचेनेषस्यजननयतिनाडीन
स्मिन्त्रयोननिभामवेत्कोषी २१
मेवृतिमारुतडष्टानदर्ल्यानिमलेपरि
स्नावे श्राश्येनेसभूयः प्रपिहिताडुत्ता
भाम २२ श्राकुलाजानसमानेनमोमुख
ममलत्वचनस्य रंधीनरवक्लिगतामम
मेगान्नेदहस्तियानेनाडी २३॥

इसव्रणविषैनाडीनप्रर छोटीअंग्रादहरकीप्रभापककोश
उत्पनहोजानाहै वोडेके व्रणमे २१ सोवायके इह होत
नेथोडानैनिमेलारसन्नाडीमें प्रवहाहै सोनाडीव्रणके
रभरेयाजातांहै अरुपीडाहोतीहै अरुबुलवलेकीनाडोउ
डीहोजातीहै २२ जिसकामल सारेअंगकेसमानहै मन्न
केसमप्नवहै येनपुरंप्रसमल नासा ग्रतिकसंगहा सु
दस्थानविषैहै औरमत्राशयविषैओर मर्मस्थानके
दरनहिहोतीयां नाडीयां २३

© Dharmartha Trust J&K. Digitized by eGangotri

घा
हा
२५८
251

निंबपत्र पीसके नेलल्गापकाके रसकेसाथ ग्रण कोंष्ठ
उकरे कोमलनाडीस्थानकस्के पेग्रगडिकागासोयोंक
रकेवनरवेद्य उपायकरे ७४ खलग्रकादिजडविश्राम
ककेलएगाडीलादहनीकोसकउघरेकाधुमासेंधा
लूणमविच रनोंकोगोमूत्रकेसाथपीसकरके ७५ रे
नाकरकेगालीवनायकेमकायकेनाडीनष्टराविषेपा
देव पैरुगटीकानाडोकोहरनेवारकडकेसनाबीवा

पितुमर्दहलैः पिष्टैः सनेललवणीकृते
र्व्रणशोधं मत्री कृतेनपश्चाद्वटकाभि
रुपक्रमेत्ततः ७४ किणवाकेमूलविच
ककोनकरवीरसाउमनःशिभः युगा
रक्षमसेपवमारिवगोमूत्रपिष्टैः ७५
पभिंगुरिकोह्कवामसुकाशोतिपननोवा
— पंचतिरस्यनेवेहृगानप्रयोगाजिवसो
ह्विग्रे ७६ वित्रकञ्जुटकोविडंगैभेल्लानक
मोवमनिकाताचैः रनेनौहटालोगालि
कोवेनसकरवीरसूलेस ७७ ग्रश्ववीनन्क
करलैर्दतिस्तकैसतुनैःपिष्टैः नेलांवपा
वपेटस्मान नाडीव्रलाशोपणश्रेष्ठ ७८ उस्मी
मोववितमौवपोचोणायस्पवदृनेकोछ
कुर्यादिदमत्रानसपसेश्रोपंमेवेवरवोक्ते ७९

पवलापदेनोंहे ७६ विशागेरवावडिंगभलावेमीरचमञ्जोला
व हरदलदालहरदल नन्ली पेने गेडोला मोकडीको
पत्रदेतनहाणकीनडग्रोवणेवस्रु — करनोकोपोसक
रके रनोकेसाथ वनरवेद्यः नेलसिडकरे सोनेलना
डीत्रणकेंरोपणकरताहै ७८ पोत्रण उस्मेगपुलाशुक
है पोचलनेवालाशायपोवापुरवनानेकोवपाव
पाककास्थानको निसकोवडके शोधनयोग्यक
रुपरेसाकरावे ७९

© Dharmartha Trust J&K. Digitized by eGangotri

जिसजिसस्थानविषैंप्रगटहोवे अरुजिसस्थानविषैंरखा
होवे उसीउसीस्थानविषैं छिद्रकरै ऐसेदोषस्थिरनाड़
है ९॰ इतिनाडीव्रणाचि॰ वातपित्तकफरक्त विकृत
होके परस्परमिलकरकेबधेहोय वोइकोयायुम
भ्यानेकौविगाडदेनेहैंन जिसतेशोजाउत्पनहोताहै ४१
सोशोफरंघमस्खादि पाट कुतिपिटी कुखबत्तीवोड़े
के इनोंस्थानोविषैंहोताहै योसंधीयोंविषैंहोताहै

यत्रयत्रगतिस्रावउत्सेधोयत्रयत्रव नत्र
तत्रव्रणंकुर्य्यात्यथादोषानतिष्ठति ९॰
इतिनाडीव्रणचिकित्सा दोषत्रयःसर
क्तदुष्टास्तमेदोमांसंक्षितालस्य सह
शपानिसवंधानन ननस्तशोफाःग्रन्थाय
ते ९१ रोधकत्रुद्विद्वपार्श्वयोःक
क्षवंक्षसिहृदयानो संधिमागेषुतनोजा
यतेदारुणाःकठिनाः ९२ तितिरिका
कसवर्णाःपृथेतेच्चर्णिकाविलापरु
षाः मध्येचताम्रवर्णाःशरीरपीडाक
रास्मसभा ९३ नेवेदनापरोनोवाक्री
दृष्टरोमवालिदीनः मंदेखादतिपिव
तिचस्वरूपेनविरोतिचानार्थ ९४

सोबड़ाकठनहै दुखदायकहै ९२ अरुतितरका
ककेसमतलप रंग अरुप्रमाणहै चूर्णकाधूड़करके
मेगाहै अरुकठोरहै अरुवक्ष्कप शामेकेरंगकेव
राबररंगहै सोशरीरकोपीड़करहै बहुततिरंत
र ९३ तिसपीड़ाकरके सोइरोमपांचि खड़ीहोजा
तीहै अरुनिर्बलहोताहै अरुखाणपीणाथोड़ा
करताहै अरुदुखकरकेबहुतरोदन अथवा
शब्दकरताहै ९४ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
२५
252

शोजाभेदनहोयाहो वगनाहै वर्णोघडकरके भेरयाहो
याहोनिरंतर पहेवोडेकौवडाकाटिने पुंडरीकग्रहः
कहेयाहै ५४ जिसकावोउपायकरणेयोग्यहै जिसके
रकेस्रणांतिसकानारहै येशोजफटेनहि अरुपकेन
मनाहोवे येवगेनहि ५२ तिनांकोशस्त्रमाथपके फे
रनाईवेपकरहोयरानेकालेफेर ठेडेनलविषेनहो
वे अरुपाणीनापिलावे ५३ नारीउपायकेस्थिरकरे

शोफाः पक्वाभिन्नाः स्रवेयुर्नेवे व्रणाके
हेनाः म्ननने पवेस्रदाकरोताः स्रस्यपुं
डरीकग्रहः शोफाः ५५ नस्यापिग्रंनिकने
ष्ठेपेमान्रणमवामपान शोफास्रामेन
मिपेने नांक्षिपनिस्रवेमिये ५२ प्रक्षये
नांस्रशस्त्राणसिरावेधेदनेनरा शोने
टकेवगाहेनस्यापपेनपानविद्विनः १ १
रस्रापरोनमनोणेंस्रदाभ्रपः पलेपये
न् वचाचानिविघाकस्राम्रगवेरणस
पुना ५४ पानेहोदामवेरेपेनथामल
भेत्ररावे फाणिकटफललोधहोत्ता
लिचेरम्राकेरामपुकैः गुडस्रक्षकस्रपु
केः पानेनलमिस्रकरेद्स्य ५५ पाठा
मस्रकपग्रकाष्टफलिनीलोध्रानशो

अरुनरषा शुक्रकोफेर मिनीकाले — शोरिवा १
पकारहेव बंवे प्रनीस मचोगुरु इनोसाय हौंदासहित
मदरापानकोदेवे तिसकरके दोदासरवीहोनाहै ५४
मरुग्रा कायफल लोदर दारव कुहारे मनुटी अरु
इसनेकरके वोइकोस्नान करावहोपकोपानकेवा
स्तेदेवे ५५ वटलवेल मघार पदमकाष्ठ केगुणी लोध
र प्रलसीकालिवेल सेनीमेरपो वाकुचीचिफलानिव

© Dharmartha Trust J&K. Digitized by eGangotri

हरदलदालहरदल कोगऊ केमूत्रमांरी वीरणकोनेदस्
वी गलोटवामोठेयांकेफल मालकंगणी विडावड
साडी अरुण्या रहेमहीनपीसकरकेहलतलयके ९६
इनोंका लेप सबप्रकारकेशोजकोहरणेवालाक
हेयाहै अरु इनोवस्तूओंकरके उस्थमोथमिलाय
करहलतमेंडकों पकावे बनरेसुय ९७ यहहेपेगेसमहै
हकायोविषदेवे अरु सभतरांकेशोजेयांकोहरता
है अरु अग्निकोजगाताहै बलकरहै ९८ फडकड़ी

क्षेनामसंधपावाकुवीफलग्रनालिंवो॰
निशेवसकः हेमद्वेशोरमधुश्रवाफ
लग्रतालेनोवलीविडंके घटूयाचन
षेगहोमरूवकेस्र हेमः सपिष्टश्वनेः ९६
हूनमिश्रः प्रदेहस्तु सर्वशोथहरः स्मृतः
पलेश्रपयमाचेव हलनमेडविपाचयेत् ९७
स्वेदकार्ये तु सर्वे तु सपिरेतन्न प्रयोज
येत् सर्वशोकहरं तेन दीपनं बलवर्द्ध
नं ९८ सौराष्ट्रीहरितालेमनःशिला
रोचनाश्चकांश्च लोधंसैंधवंकटफ
लमरिचाद्विनशेरपानि ९९ समभा
गानि मानि सूक्ष्मचूर्णं विकारयेन्मति
मान् अवचूर्णनेत्रणानोंसशोथनरो
पणो श्रेष्ठः १००

हरताल मनशिला हरदल पाल सुहागा लोधर
सेंधव लूण कायफल मरिच एते सम भागलेकर
वैद्य महीन चूर्ण करके व्रणाबाय उपर बरुरे यह १
व्रणकोंशुद्धकरके घाव उड़ाताहै श्रेष्ठ गुणकर
है १०१

© Dharmartha Trust J&K. Digitized by eGangotri

मा॰
टी॰
१५२

253

दोदोषादिपान और मगो वेउमे चोमखीरके साथ
खाणकै देवे अरुस्थानशोनलविषैस्थितकरे अरु
दोरसहे वडोवडपालखरुबल मारसपिप्पलइनो
केमिकेडेकालेप्रकरणपाग्य है १ इतिपुंडरीकगृहीवि
किन्सा अर्बुदरमोलीहृथकभिन्नभिनदोषोंकरके
के चारप्रकारकी है कोइकवैद्यमनिकेवलरक्त
रकेएकप्रकारकीकहिहै. २ तिसकाकोषखजान

दोषाधात्वयमस्तुः स्युन्नामधुपिप्पली
पुक्ताः स्थानेवशोन लेस्थानतीरवकले
पनेकार्यो १ इतिपुंडरीकगृहीवाकि
न्सा पृथक्दोषविशेषेणचार्बुदंनव
नविधं केचिदेकाविधप्राहुः केवलेर
क्तसंभवे २ आको मर्बुदामाहुः को
शावानुग्राविकव्याने उष्ठव्रणेकालजी
र्णामर्बुदंपरिवस ने ३ नदासाध्येवि
जानीयात्कृच्छ्रासाध्यंनयत्नतः अ
र्बुदं विशेषणालेवायिनासमंततः
मनेणाणाभ्यं रभिन्नासिरारक्तेविमा वये
त प्रतिमाप्यांग्निनावेवमस्ग्रश्चेतिपात
के ५ पापोपिनाहृतनाभ्यक्तमवगासन
लशोभा १

रसकास्थाननहिसोअर्बुदकोहियाहै
अरुयोकोषवालीदृशोग्रंथिकहिहै योउष्ठव्रणविक
मकण चिरकालकरगोलाहोवाहै तिसकौ अर्बुदनाम
करमेहै ३ तिसकोअसाध्यजाणकोइकृच्छ्रसाध्य
यमकरकेमिटहै अर्बुदकोचवबोनेपछेदकरके
दहौनरा लेखनकरे वोउ ५ फेरतिसकेमध्यकोवे
पकोरनाडोलोयिरकहावे अग्निकरके सकसारेवे

© Dharmartha Trust J&K. Digitized by eGangotri

फेर प्रतिपानपिलायके चूनसा घृतदे हमलायके मल
विषे नारी डुबावे जिससे उपरंत लेपके वास्ते औषधी
यां ग्रहणकरे ८ चिरातरवी देदरण दारो कीजड मोक
शीशक समीपत्र साडीबेरकाली बेल कुरगाल २८
सिट ७ कलहारि विवडे तमाकिरायमानीपाती पर
ण रुखगडीलाकु बला कंगुल टम्बरु शोधनकरण
वाले पदार्थ हैं तिनोंके भिन्नभिन्नलेपकरावे और द्रा

ततोस्य लेपनार्थाय भेषज्यानि समाव
पेत् १ चित्रकं त्रिवृता दंती मानलेगाक
मेवच शमी सालोटवदरी व वासायना
पुनर्नवा ७ लांगली हयमाती वाकिना
तीवत्सकवच वर्द्धमानाग्निमंथो वसिंडु
कारावधोनथा ८ शोधनीयानि मूला
नि लेपनानि पृथक्पृथक् ताराणि
कर्मणा कुर्यादिद्वयोघ्रिक्रियोनतः ९
सर्वेदंत्याकिसा सिंहास्य वन रस्तृणगो
धाकेकम्रवादिय समास्थवमादीनि
यैत्रण प्रकाराण्यनेकधा छेदनीयानि च यः
सान्नमशाल्यं किंचिकदाचन १० ॥

रपानन करावे अग्निकर्म दागवर डली कर इत्यादिक क
रावे और दुष्टव्रणकि चिकित्सा समकरावे ९ इति
इतिदुष्टव्रणचिकित्सा फेर चिलग नरखचो प्रके
कपाड़ि इत्यादि मलको मार्ई और वो इत्यादिक जो
वोंके मरवके बराबर मुखवाले यंत्र अनेक प्रका
मे करके शोधन शल्य अंगविषे लगा होय है येसर्क
र के शाल्य कदाचित निकालना होवे

© Dharmartha Trust J&K. Digitized by eGangotri

सोशल्यपंत्र करकेउलावे मर्मस्थानग्ररुनाडीक्षे
उकरके सेविक्षभनेछिकणहोवेसोसिरूदेह सिरूको
हाउवे रुरघेडहेतिसकेसाथकरे अंगुलीकरकेसिरा
साधुसूह्मनाडीमासरनाकोंसमणसेलरखे अरुथो
शल्यवड्डनडगाहै तिसकोंगोथावोके मुखकीया
रघेडहै अथवा कंकपक्षीकेमुखकेसमहै तिसक
रके थाहाभाइतने रखहै पहेलागकरकेजिसरे

तेनवेणाविनहेदेनमेसासलाग्रेषिव
नेघेन विक्षंभनेवघंत्रेणसिरूदहेण
कारयेत अंगुल्यानेशिशस्नायुमर्मा
णिपरिरहयेन सोथामुखेनवागादे
शल्यंकेकमुखेनवा ११ गाहयित्वाव
निष्कासयेयथागममसर्मोपिन अनेनवि
धिनासम्यकहितंतकल्पसुरेत १२
शोतापांबिविधोरंघकरमध्यवगोडयों
हृतस्थेनेषुस्थानेषु सशल्यःस्याणमासु
यात् आहार्याणामानेनेषु सशास्त्राण
नेसेशयः गात्राणांगौरवंस्तंभःशा
सःकासोथवेपथु १३॥

ले वाहेयाहै असीरसेकरे ११ इसविधिककरकेसु
ताबीशल्यकोंबाहरकरे १२ येघुडघुडीवहीकण
केहेट रंधक्षेकोमे कटकेमध्यगलेविषे इनोस्था
नोविषेजेशल्यहैनसे प्राणकोंलनोहैन पहेकरहे
सिमाणरदहानेहै अरुमर्मगतहै तिसकेपहे
लेहणहेन देहभारअरु श्राकड नाण दम खंग
अगकंवण १२ मर्कविहीसीअरु वारवारउठणा
वोणा घकेसा देहहेरा प्राज भोमनरखणानहि

© Dharmartha Trust J&K. Digitized by eGangotri

होनाहै यहै मर्मपीडितजानो १४ शल्योद्धरणे अब
प्रनष्टशल्यकहतेहैं थोडेका जिसविषे वडीपीडा
शरीरमाकउजाणो १५ दाहज्वरतृषाकरउशोजाअ
हलक्कहस्थीनरोनहिनिकलना श्रुतपीडनहिहटणी १९
गिलानहिहोकेवगनाकरउ निसल श्रुतचापनहि
वडना ऐसाशल्यकोंजाणके उपायकरे वैद्य १६

मर्द्दनेस्वेदसंस्नेहनेनशोषमाने - पावेः
शने अश्मणांशोनगतंवेशोघस्याहार
वर्जने पचानेयस्यरूपाणितेविघात्म
मे पीडिते १४ शल्यचरणे प्रनष्टशल्य
विज्ञानेवाक्षिनेसेधवहते सशल्याचे
दनान्वीचागाउस्त्रभवनायुने १५ दा
होज्वरश्वतृष्णावयथुःकटिनसाथा
नसमस्पर्शनेनेरक्तंवेदनाकनशाम्यति १९
अक्रदोकाविनस्तब्धोक्रणेनामय
रोहति समल्पसेवेविज्ञायशनिकर्म
समाचरेत् १७ परिमर्दनेनशल्यंक्षेने
समायलतयेन् स्पर्शनेदहनेनपत्रलेप
येनकर्दमेनवा १८ विवाहेवाशयान
प्याउच्छ्वासोविषपानि स्वपथुःकटि-
नस्मासयोन उशल्यांविनिर्दिशेत् १९

शल्यकेशरीरकेथावेघसर्दनकरकेजिसजागाविषे शा
लरहेजिसकोदललेवे वुद्धिवाला जिसस्थानको प्र
णकोंनासहारसकेजिसजागाको विकरकेसथलेप
करदेवे १८ जिसमेंवायुनावगदाहहोवे अकसनेहोय
कोकेरजिसजागमेंसूवपरहलैंशकजावे अरुशोज
करती होवे इसजागविषे शल्यकोंजाणलेवे १९

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
२५५

जिसकोईका शल्य प्रगट नहि है तिसको वैद्य चेष्टापिला
वे अरुस्नेहवस्तिमज्जकारि उडावे अरुअस्थापन वस्ति
भेद सोकरावे सनावी तिसको जहां वडीपीडा होवे तहांवे
धन करावे २१ एवश्रोहस्थानकोमल अरुरोग अरुहोता
वे अरुटोल होनाव पक्के होय पको शस्त्रकरके वेधकरावे
पक्वणो सला १ विचिवेहकफरविकुम नाम यंत्रकरकेथ
मे उसको २१ अरुतिपंथके साथोतिस शल्यकोपकडे
निसरले योइ या देशास्त्र उसीरसें शालानिकलि अवय

हृतपाने च वर्त्मनि वदापपेशान्निनेभिभ्रक
श्रुतापपेन याशोत्रेनष्टशल्येनरेगम
यत्नाण्वे दनामोत्रानजेवम्पनाहयेन् २०
स्त्रेदैविवर्णाशिथिले पक्के शस्त्रेणभेदये
त् पक्षाहृत्यायथेमार्गेणप्रावेद्यंभेनेवमम
येत् २१ नेनयंत्रेणतच्छल्यमाहरेद्येतन
श्रुप्याने श्रुतरसोऽकियाशल्येमनष्ट्रम
णवानतः २२ यद्याशकाचव्याधाम
धावनप्रेषणेन्नथा कारानेरमणैवे
वध्योपनेश्लष्टेनथालेवनेवासलवन
भेमनननविमर्देनेकायचापिमधावेमेष
नेचापिपत्नेन एवनामोपेतेगल्यावध
नेवाप्यात्वतः उसाटयेनाकालेनमाको
पनक्षेतिरवेत २४

नष्टशल्यकी श्रोरवीकिनसासल
वोइकी २२ मैंमेवोतुल्याजाममञ्चमकरसके दौडावेग्रहकोय
करावे रौंगे उमालीलेवकुरडाके किलेलश्वनासनावीन
लविश्वनरणा उक्छेले रवहोवामिदाहोवे अरुमलपटेनिम
नगे होणसे बुद्धिमान करावे अथवाओडीमथनेमथुनकरावे २३
याशल्यश्रुतली करके पकड नहोवे घनईकरके वीनाले
णसेवे वहन उगावे तिसको फालकरके चिरकाल विष
उसीरसें शाम होयको आहरकरलेवे २५ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

इतिप्रनष्ट कपाहोयाशल्यकाग्राणना अध्यायः काट
लकडीफोमथपथरकेप्रहारकरके अरुस्थाननेति
लकपाणने अथवाचिकडवाले वायहूनकटिनमा
र्गविषेवडेवेगकरके चलनेमें अथवाशस्त्रकरके
वडाघायकरके ग्रीवा काडी गात्र स्दप त्रिक्क रिवम
कनावेवाभजजावे अथवासंधिजोडछुडकजावे २६
येघापकेसहितकुछकभजाहे स्थान अथवावदीर्ण
मरवाकेघाजावेडायका अथवायोजजेरी भूतवहु

इतिप्रनष्टशल्यध्यायः काष्ठलोष्ठा
भिघातेनोत्वेषयेमुवलिनमथवा कर्द
मेविषमेवास्यमार्गोद्दहनवेषनः २५
शस्त्रेणवानिपानेनवाग्रीवागात्रेत्रिक
स्तथा संसनेभग्नेवापिसंधिकार्ति
घातेनपिवा २६ सहकनभद्दग्नेनेवाविशि
दथवाप्यवदीर्णन जर्जरीभूतमथवा
नाभिनेवाप्यपवेशिन २७ अथवेकांड
गुच्छशस्त्रचिह्नं नध्यापरे यथेमहावि
धेभमुत्रेदूपानोपरेकीर्तितं २८ नयवि
किन्त्सावत्स्येपानेः पराम्रस्ममयमस्य
प्य स्थानेनिवेषयमामीनवृष्टीयावे
लगोभग्न २९

नचूर्णहोयाहै घोपवेगहरी
मई जाए २७ अरुयेपर्वयघ स्थानविषेनहिंयुडया
रहैघा घोशस्त्रलगाहै जिसकाचिह्नरहैपाहै येहम
टप्रकारकाभग्नचोडपाकाकहेपाहै २८ जिसमर्मकी
चिकित्साकहतेहां चोडकेभेजहोय स्थानकोहालि
दोलिमलेपने अरुजिसस्थाननैविसकेघाहदाहै
इसजागाविषेस्थितनकरके वमीविचटलीयांवेक
रकेदूखीमरा २९॥

© Dharmartha Trust J&K. Digitized by eGangotri

पा॰
हो
२५८

256

पिसकारसतने दारुणरोग मेहूआउ योनव इसकारउहो
तैहै तिसते क्षारयक्त दूधरनोकरके बहुतवार इस
कोपावे ३॰ मुलठी लोधर मंजूआपमकाहूमजीठ
बेरगादीजउ चिटाचंदन इनोंकोपीसकरके पानेहो
पहनसाथ रलायके बारंवार लेपकरावे ३१ अरूसहो
नतिलपीसके सोनलकरके पानापानहुन है तिस
साथलेपकरे भुकततनमनविषै पाववणपक्रमवि
हैविकिन्साकहिहैमाकरे ३२ यात्सिपिछ्उकोहैअ

राहाम्योभाषाणकाण्मान भेगेयुटा
कणःसैते नस्याकषायमर्पिषया
भिरभिषवयेद्द्रशः ३॰ यष्ट्याह्वलो
भ्रमधुकपद्मकमंजिष्ठाशीरचंदनैः
पिष्टैः पैनासमप्मापुक्रेभूयोभूयः प
देहासुः ३१ ममैसालिलैः सपिष्टैः पात
पौतैर्हिमालितेभेवेलेपः ततभस्मक
तेयाक्रियापत्रिणापक्रमेणमा ३२ वि
मिष्टमथमन्यतायपटमतुष्टिमानवै
पः क्षारपमोपितस्तसमिस्तमयस्यान
प्रपोयत ३३ मधुरैश्चमासमबूषैः स्वि
नोभोजयेत्पत्यापशीतैः माजाहोणा
दूषिपणमागाभोजनेवायु ३४ भग
सिज्ञानिरवेसीलोषुवरोगमेषुसरा

करभेजिहोहोनिसविषै भोरेकोंनलाविघंनादिस्माचे
वेप सबधनपकरपुक्सपिदारदो पत्यास्पानविषै
प्रापहोमानिहै ३३ तिहमधुररस्यकरमामसगूषोकर
केसेदहोनिय भोजनपरलाव शीतल प्रमाणनेकचु
कपटरहकेसाथभोजनदेवे ३४ भगंदरलिसमोरका
शकतुरकायोभगवनाहेसोवडेउरवकरकेमिउहो

© Dharmartha Trust J&K. Digitized by eGangotri

नाहै अरुजिसकात्रिक अंग स्कंद मोडे भजनानसो
नहीजीवता २५ भग्नवि॰ शल्यतंत्राध्यायः विषदोप्र
कारकोहै एकस्थावरजंगमहै स्थावरयोगनैहै अ
रुजंगम सर्पादिकोंविषहै दार्वीकर फिनगर एक
मंडलीहै एकमंडमंडलीवाले एकरेखावालेहै ति
नाकोविषक्रमनेदार्वीकरकोवातात्मकहै योमं
डलीहै तिनकीपित्तस्वभाववालीहै अरुराजीमंतको

भग्नत्रिकंवंशभग्नभग्नस्कंधानजीवंति २५
इतिभग्नवि॰ शल्यतंत्रेषुचिकित्सास्
थानः॥ द्विविधंविषमाहुः स्थावरम
थजंगमं तत्रस्वयोगस्थावरमकंज
गमसर्पपन्नगादिविष १ दार्वीकरा
भजेगामेडलिनश्चराजिमंतश्च ते
षांविषमाक्रमात्पित्तश्लेष्मात्मकेक
मशः २ दार्वीकरदष्टस्यतत्कोपसंभ
वत्यानिमारःस्यात् मूर्छावैवर्ण्य
सखावाद्वेफेनागमःश्वासः ३ दंशोपरु
षःश्यावःकाजिह्वास्यात्तापश्चकोणवालवे
अरुविविमिरमूर्छाकंपश्चपीडनस
मेडने ४ मंडलिनादष्टस्यतत्पश्यवाति
ह्वास्यतालदेनाश्र

श्लेष्मकहै १ जिसकोंदार्वी
करफिनगरडेशाकरे तिसकेदेहविषेपरमाहोताहै
अतिसारपश्चावमा ३ रंगकाहोताहै मुखसेफेनउगव
गदोहै अरुदमहोताहै २ डंकावालेस्थानविषेचौरा
करदूर्पोनाहोताहै जीभकालेरंगकीहोतीहै अरु
बालविखरजातेहैंन अरुविनदेरवीमूर्छाहदेविषे
पीडाअरुसाधिहीसोप हैललगाकहैन ४ जिसकोमंड

लीसर्पने देशकी याहै तिसकी जीभ छेदनकाले रंगकी
होती है अरु मस्तक नाल देन काले होजाते है पछावला
ल अरु दीन मोढा निबल होता है स्वास दाहशोजा
वडा वलवान होता है अरु दंशस्थानते अरु मुखादि
द्वारमार्गते लोहु परवहता है देह विषे परफट पडते है
अरु दंदमास काल होते है ६ राजिमत सर्पके दंशावि
षे रिंडकी किलणा पीडा मूर्छा लाला वगती यो है अ

रंकमंत्रं च भवेदंस्थानामश्वदाहस्त ४
स्यपष्टु बलवान् दंशे सोतेभ्यः शोणि
तं समुपायाति गात्रेषु मंडलानि काला
यथ्य दंतमांसानि ६ राजिमतादं स्य
तोष्टिकारू घने भवेदंते मूर्छा लालास्रा
वस्तु भवेदंशे शोफो कंठदंशंकोटन ७
हारिक्कविस्त्रस्यभवेत्तल्लक्षणः सवेशिरा
यमन्यश्वदाहस्त्रवान्यथे मेयषुमृ
वेपथुकतीव्रा ७ अन्नाताघसन्नाविष
लादष्टवगारिपुः सघोत्रान दृष्याहिंसन
लिंगैः सर्वेकैमनदर्षिजानीयात् ९
लिंगो नानादोषप्रजोन न अकाल्य सकोविदे
तु यः सर्वलमेचविषेहस्यानसमिषक
प्रक्षमयेन १०॥ टी॰ दंशस्थान विषे बहुत नकर दाहशो
जा ७ विषके देश कारके शमना टीयो आकउ जानीयो है
न दाहावहत समनोग विषै वरी पीडा ८ यो विष अ
जानै मेल्या हिंगे हावे अथवा शत्रने किसिनं राखुला
न तिसको निदाकरके माणलेवे ९ बुद्धिमान विष
के नाश होयविषअरु न हिंनगोदं आदि विषमें त्रवि

पायोऽइयोवैद्यमंत्रोंकरकेविषकोंनाशकरेसोवैद्य
श्रेष्ठकहेयाहै १ वासुदेवेति इसमंत्रकरकेहस्थ
वीजलसाथसेवनकरे अरुस्पर्शकरेयेहैविषन
हिविस्तारकरनी यहेयारणेमंत्रहै ॥

नमस्ते वासुदेवस्यं भूतं पराणिवेष
तेनसत्याः निहन्तिविषनागंनत्यंमेवैवधाति
पथना ११ भूमेरेनरमास्थायअत्रैनारिहे
णगमस्थता यस्यागमेननहन्त्याविषंन
ज्वगम्यता नेत्रलानमममतोस्वाहा
अनेनमंत्रेणभूमिवारिणाप्रोक्षोपस्पृ
श्यस्वाहा अरिहिवभक्षोविषेनकाम
मे इतिपरिघारणीमंत्र सुदर्शननमंत्रः
ब्राह्मणांप्रथमेवेदेननोवेदप्रजापति
नस्यैकाउहिरन्नाकन्यामातंगीनामउ
च्यते उच्चैःशिखरमारुह्यध्याननोदेवीनि
रीक्षते कोऽद्यनाकेनवादष्टःकेनवाभ
क्षितंविषं अहमेवविकिन्सामिविषं
नस्मभिकाहके मातंगीनामननचारे
विषनयोविषहतो वाधेवषनिरहणा
मिअहेश्वलानमममतोस्वाहा पक्षमननमंत्रः

प्रलणमिमि यहेसुमननमंत्रहै इसमंत्रकरकेपरेकोअ
थवानालकेपत्रकोवाष्पारमोत्रनकरकेविषवालेको
देलणमोविषवालाविषरहितहोजाताहै ॥

© Dharmartha Trust J&K. Digitized by eGangotri

हिमवंतस्मिति इसमंत्रकरके विषखोई होवेस्थावरजंगम विष
योनिकैः पढेमेसपढके स्पर्शकरेतो निर्विषहोजाताहै

अनेनमननमात्रेनालसनंवाभिमंत्र
येत् सर्वविषोवोजितसोनिर्विषोभवति
अथकुंभनाममंत्रः हिमवंतेणरवतेवं
दे गिरिरानेनमोनमे विषाणि नत्रनाथ
नेकोतैयिष्यामिनामतः विषाणिनत्र
नाथनेकोतैयिष्यामिनामतः सर्ववि
षंकोटविषंपद्मोमूलजंविषं पाहिष
नलदेतेषुपाणो कुद्दालकेषुच मृगा॰
लेषुच वृक्षेतेषु स्थलीषुचनदीषुच
पलाशेषुंभूषुवर्णेनेवृवर्णेनपाहिषं
मार्षिकेषुविडालेषुदर्देरेषुषगोपिके
शालपादीविषपत्रलजकालभकीटके
हाष्टकेदाकहलेवषश्चासीन्मानघंवि
षं समेनहरियिष्यामिनमस्कसकपंभवे
नालाकुलोमहाविषाउमाविषया
निका आशाविषाणिपकानहलसमपं
वेनेमिका

© Dharmartha Trust J&K. Digitized by eGangotri

ष्टा च कालकूटं तु नागो न मे स्थविशेषव
नः हस्तिकैः कुंडले कृत्वा दर्वीकरः
मन्तूपा स्वादेनो विषभक्षणिभिः ज
नो विषनाशिका प्रज्वलेनोपधेवाः
ल्काप्रदीना विषघातिका नोदेवाश्च
भिने दन्तीसर्वे व्रल्लभरोगमाः सर्वेस
मागता देवा इदं वचनमब्रुवन् य
स्वकस्थितं नाम्नेति विषं कुंभे हरेच्च
ति हन्ते विषं कण्ठपन्नगसंवेष्टनाधी
मना यन्ते नाभि मर्दनेनाभ्यां वेष्टक
नोविषं यद्विषं नखकेनागोकेवला
स्तनेन तथा यच्चैनैव सर्पैश्च यच्च
कीटपिपीलिकेन यत्र विषं दन्तेसर्वेन
मः पितामहाय स्वाहा अनेनमंत्रेण

© Dharmartha Trust J&K. Digitized by eGangotri

श्रा
ह्री
२५८

259

जिसकिसेकरकेवोडेकोंदंशकीयाह्रोवेनवपक्कका
वे अरुयोदंशकेवलेवाडेपासहे सोसन्नावीनाडेनें
रुधिर निकालदेवेवनर १ औरसेंधवलूणकरके
दंशकोंमलकरके इनसाथ अवीविषेंसेचनकरावे
छेदेदेवेनडकामूल वेंनकीजडअरुदोरघतपोंवों
कीयांनव वडवहीफेंवल पलाख पारसपिप्पलइनों

विषदंशपदिवं रूपोंऽपिनोवाभिमंत्रितनको
विषोनविषोभवति यथक्रोऽनाममे
वः येनकेनविदंष्ट्रस्यावाजिनःश्रुं
नमतेशिरोवामोत्तयेनत्विषमसीप
दंस्यपाभवेनुपः १ सैंधवेनाविम
र्याधमपिषाय्वसेवने नलवेतसेयो
र्मूलेहोगिनकपेषपत्न्मानिमान् म
धुमपिषोविमिश्रंकदंमधुकंसदेहो
य २ वल्कप्रवालमूलान्यश्वकत्रुम
शिरोषपिप्पलवाणा मिश्रालेपःकार्यः
स्तंनलेनेन्नपारिषकः आमलकला
हांसोंमजिष्ठ श्रीरनगरपष्टाह्वः ३
ननीपुष्टीवालमुनेःकुष्ठ स्यापिनसे
मिश्रैः ४ एवंमधुमपिमिश्चानसंयानेव
दंष्ट्रकेजोमान् ॥

केहिलडपीसकेमलोम
इनकेसहितविकरमाथरलायके प्रदेहलेपपदेहकरे १
अर्जुनवक्लसंगीरदवेनपुष्पवाला इनोंके छिलडप
वरनरंरनोंकोपीसकरकेलेपकरावे अरुइनोंकेसा
थनलकाररकेदंशकरकेस्नानकरावे ३ ४ आम
लेसालकडरगाड़ी मजीठवीरगरदीमड नगेरमूलही
वरदल हालरवदलवाला कटरनोंकरकेमरवोर १०

© Dharmartha Trust J&K. Digitized by eGangotri

वेडेरलापकरके नसवारश्रोरपानवालेचनरवै
घटैवे पहेश्रेष्ठप्रगदविषहरऔषधीहै सभनराकी
विषकोनाशकरैहै ५ मज्जीठकुठमनशिला वे
नौकेसिकड कै थकल हरदल दालहरदल हू
नमखीरकरकेपुग्के विषकेनाशकर येहयोग
कहेयाहै ६ मुलटी चुलेरी इनाकोपीसकर मखीर
साथपानैहै विषकेनाशकरैहै दार्वीकरसपंकर

पद्मश्रेष्ठोगदोविषाणांसर्वेषांविना
शयति ५ मञ्जिष्ठाकुष्ठोचमनःशि
लावेतालेलनकापिष्टैः रजनीद्वय
वृतमधुमिश्रैःविषनाशनोयोगः
६ यष्टीह्वतंडुलीयकमष्टभिःपिष्टै
विषापहंपाने दार्वीकरदष्टानाम
पाक्रियाहन्तव्यशाककथिता ७ गृह
धूमवचेपिष्टामूलमपामार्गतंडुलीय
केसर्पिः नस्येलोहेष्टगृहंमेडले
दष्टसविषासंशमनं ८ बलाकवी
नेलाहाम्रुटीमेववंलेववाहिवेषा
पाटाचित्रकमबेनापिष्टापानाघदेय
स्याम ९ पर्णापदंष्टानांनरेगणां
वाजिनैपष्टदष्टानां
के डेगवालेकोयहै
सारीचिकित्साकरिहै ७ गृहधूमावचचुलेरीका
मूलरसकेसाथचूनामिउ कीनसवार देवैश्रकम
खीरसाथइगउपरलेपकरे लोविषसमरोगिहै ८
इदपत्रोलायाचश्रुइसोवललचुयाव दिग्गनीपाढटलवे
ले लिजारनोकेपीसकेपानवालेदेवे ९ पालीपदक
रकेदशाकीपदोपमोरनाको मुकविषशुककेरोदेन

© Dharmartha Trust J&K. Digitized by eGangotri

शा.
टी.
२६०

260

निहोंकरकेवड़ेयाहोवें ओर विषवालेंकरके दंशकोरे
होएकीविषकेनाशकरणेकों श्रेष्ठहै ९ सेरयाहरता
ल मैढकीप्यर वेंनकीमिकडीयांकुठ इनोंसमभनाकी
रनकापान सर्पकी विषकों नाशकरहै ११ पीलेरं
गवालीचुलेरी कुटलेवेनिसकाजलकडलेवे अरु
इटत्रिगणालेवे इनोंकेहूनवोथाहैमापायकेसिउ
करे पहेवेश मूषक सर्पडंगकीये होयचोडेकोपानवा

अथैषापिरक्षानां श्रेष्ठो विषनाशनो यो
गः ९ सिन्धूत्थं कुष्ठरोहितालं द्वापिमल्ल
वेणलेखनं कुष्ठ पिष्टं समं च मूलं मू
षिकविशनाशनं पानं ११ ग्राहांयत्रा
नेसहेगणा पाडाभतं डलीपकं त्रिगुणं
नुपयः कमाष्टुनेनेनमहमापयेत् १२
मूषकोपद्रतोदेयमेनमानापवाजनो
यत्नु किंविहिषवामन्नवेमेनेनशा
म्यति १३ आगारधूमं कुष्टं वापिप्पली
वेवहणोयेन् कटुसापिषाचनन्नं
वैसधुनालोसदोपयेत् १४ पाणीपट
विषस्पर्दिष्टं ग्रामेविनाशनं यवाम
मेरलेमिश्रेयचोसमान्मकेविष १५

मिटेवेअरुयहरोरकोइविषहै सोसभरसचूनकरकेस
महोमामिहै ११ गरहकापमा कुटमवा सुंडपदेसम
हणाकार पहेसमभचेडाकारकेचडुना मत्वोरकेसाथ
मलकरकेदेवे १४ पाणीपटकोविषकेनाशकेवा
ले श्रेष्ठ गुणकरहै येरओरसर्प मरलावाले
विरकोडीयांवले अरुनिनोंकीविषश्रमसभा
वनालीहै निसकोहरकनाहै १५

© Dharmartha Trust J&K. Digitized by eGangotri

जिसवोडेकौंटंडेनलकरके उपरछिनकालेकरकेरो
मवालखेडे नाहोसा अरुरगारोकोपाजन अरुवालके
शशिरकेवाल रोमसहितवाल जिसकेउदपैरा १८ अरु
शोटेरसादिकेसाथ मद्दारकरेदेयां वोडेकेदेह विषैं
नालवे अरुस्कंदवाहुमननावे पहेलतलगप्रसाध्यके
कहेन ९ इतिविषनेर्वे अवरसायनयोगकहनेहैं
योरसायन जराबुढेपा अरुरोगहरहै जिसकरकेसद

शीतोदकावसिक्तस्य रोमहर्षोनजायते
यस्य संरूढ्यतेवहन्नकेशावालारोम
णश्वशोर्यंते १८ देहेनाभिहतस्यनवा
जिकायेनदृश्यतेयस्य मर्मस्कंधपक्षम
वेलिंगानेनाम्नसाध्यानि १९ इतिविष
नेत्रं धीमद्रसायनमुत्तमम् शुभं नेत्रो
वलीजस्करमायुषः परं शरीरस्नेहेंद्रि
यः वर्द्धनं परं रसायनेसर्वगुणोत्तरं हि
तं १९ भ्रांतिनुपवर्णानेननेवलिपलि
तविनाशनेनयामेधो नस्यप्रयोगम
धुनाममामनः संप्रवक्ष्यामि १९ भल्लात
कानिष.. क्षायेनथवलोहमेरनः द
यंशीनेयानात्पुरुवेकोहमस्यप्रयोगहै २०

रअवस्थाकोंस्थिरकरनाहै अरुतेजयानबलदेहबलप
राक्रमयान इनोंकोंदेनाहै अरुशरीरकामलउहमेरइंद्र
याणकेबलकोबधानाहै रसायनइनोंसभगुणोंकरके
सुभायमानहै १९ औरकांति उपवर्ण इनोंको उपमक
रेहै अरुपुष्टिकरहे औरश्वेतवालनेउरझोयां इनकोना
शकरेहै अबजिसकेयोगसेदेपनेकहनेहैं १९ भल्ला
वेदाकाथ अरुलोह भस्मरेहोंकरके पानवासेया
नोविषै शुद्धकरेहोयेथोडेकोंदेवै २०॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा
द्वी
२८१
281

समशीतक्रिया करे अरु भोजन के वास्ते मांस देवे अरु
शालि का भात इद मसूर हरन मांस भोजन देवे २१ दशांश
निपट्ठे विधि करे तिसके उपरंत योगराज पाक कर
दे सो कहते हैं भलावे औहि इनों का काथ करके पा
न वास्ते देणा पाय है २२ इसके उपरंत भलावे दशाद
शा दिन दिन प्रति खावे इस न रो बारा दिन पर्यंत मवे

शीतोपचारमारेवले कुर्य्यान्मांसेन भोज
नेरपान् शाल्योदनेन वापर्पसाघ्रकेमधु
मपिषादेयं २१ एवंविधेदशाह्वनतो
परंयोगमंत्रवक्ष्यामि भल्लातकानि वि
शान्काथेपानायदेयं स्यान् २२ भल्ल
तकानि त्रिंशन् काथ्येपानायदेकाथे
दशांतरेदापयेद्दिनानुदिने द्वादशा
दिनानियावन शर्वो के नैव मार्गेण
२३ एवं पिवनः स्नेहः क्रमश्चन्नायने
नेरगम्य नीलेण पानेद्देयं हौरहतौरेणसं
युक्ते २४ अथवा शिलाजनस्वरंगो
मूत्रयुक्तं प्रदापयेन्मालः मासाद्वेषा
लंपमानेमिर्मांसंसमपने देयं २५

विधि करके देवे २३ इस बल पान करने हाथ थोड़े को
परमा क्रम स्यानि होती है काथ के पंचदेषा मूत्रहौर
साथ मदयोगको देवे २४ अथवा शिलाजीन पु
उसके रया होपा गोमूत्र के साथ लोगों को देवे चन्द्र र
सो प्रमाण हरि नाथ दोहि न अरु फेर शालि उनगाम
लाममनी का भनोतिनि मिमन्यजाति भदसि सके मा
सर समायादेवे २५

पहेइयपयोमरसायणवाले जराव्याधिकेसमकरणे
वाले घोडेको कहेहेंन अरुइनकोयेविधिकहेहै
तिसकरकेइनदेवे अरुतेलकोतेलूणकोवर्जेमार्ग २९
यत्नेनयत्नकरकेयहेकरेसमरेहे औरशीतचिकित्सा
करावे इसप्रकाकरनेहोयां घोडेवेविषेंगुणकहेहै
तेसोहोनेहेंन २७ हेरसायणविधिकहेहै वाजीक
रणकेकरेहोयां घोडेकोंतेजधानवलप्राणजीवन औ

पतेरसायनाश्चेयोगाः कथितास्तुफल
रोगाणां देयंहुतेविधापावेवर्जयेतैल
लवणेन २९ यत्नेनचैवरतेनसर्वेशी
तोपचारमथकुर्यात् उपचारेनानात्मे
वेस्ववौदेतगुणासंति २२ इतिरसाय
नविधिः तेजः प्राणः ओभाद्याश्चवा
इस्थकेनामनस्यैश्च्यं वाजीकरणस्य
गुणायतेवाप्येचमेनस्या १ सम्यकूना
ग्रविरस्कापश्चङ्कोष्ठापवागिनेदेय
पानमिदंस्वर्वाहेतम्यकश्चकस्यहोइ
करे २ ऋषभकजीवकमेदाकपिक
च्छुश्चकनामाशालवृश्यः काकादनी
छिन्नरुहापष्ट्रणाहेतोवश्यकाव ३ मा
नमुद्गापर्णयुक्ता माषपर्णीतथावे
दारीच काशेरुकानापानेमधुशर्करा
युतेशीते ४

भाषारीरकी अरुहद्रदेहविषे वी
र्यहाड़ि अरुस्थिरमन एह गुण सोकरेहे मऔर
वोहोनीहेन सामनलो योग्यहै १ २ ३
४

© Dharmartha Trust J&K. Digitized by eGangotri

शा
टी
२८२
282

योधोडा ह्रद्धीनरो विरेचन करके शुद्ध करे पाछे गुरु
मलस्थान शुद्ध करे ह्रायपवोडेनाई पहपान योग्य के
ह्रणाहे सोदेवे जीवक ऋषभ मेदा मनूली वीजटो
टरसोनापाटा सतावरी रक्तोकामूल गलो मुलठ
स्याली मुद्गपर्णी हीरकाकोली माषपर्णी इनोंका
काथ करके देशकरके मखोर खंड पायके ग्रहउन्न
टाहिमालयविषे उठवेहू भाषाकरके इसेहेन निस

गुरुमस्तटाकल्केनपानमथेदाननय
दापयेत् मोसौचेवाक्षपानायहलोर
पानायप्रदापयेत् ५ खोटनेपवस्तवा
स्यनक्षाम्भेरसोदने उष्णटाचाविदा
येवमंयग्रमाफलानिच ६ मदाटे
यानिवाहानामेकाहेनानिमाचशाः
हनिवानीकरणम् ७ स्वेनागोक्षुप
थ्यालमयामेचनक्षेवापिस्त्रम
वेनरथ्यामहेचैपकशुतेवा पत्तस्याने
श्रथवाप्रमशानभस्याच देवायतने ८
मयगरेहस्वरथ्यामच नेरंगमे स्यावये
स्थबुधाः स्याले वशाभरहेनयत्राबे
पिनानानिर्मितेवापि॥

काकल्कनगदार
लकेपानकालविषेपानदेवे मवपचनावेनो ग्रनपा
नदेवाले इरवोलेको देवेवेप ५ मौर भाजनविषे
वामतिषे मालसमे ग्रहमासरसविषे मनविषे उब
हा ग्रहनास्याति होचवीनपर पहे सोइयोकोसदा
पकेवेलेयोई प्रमाणाकोपादेगीयो ७ पहेलानीके
रमाकहेपाहे पोउकमेवकचोरको ग्रस्यसमानेलो
विषेपमोषिवे शुराणविष ग्रहमृष्मग्रस्यप्रथाहेन
वनविषेगलोयोविषे ग्रहवद्रापक प्रधानहरके देव

© Dharmartha Trust J&K. Digitized by eGangotri

अथवा यज्ञशाला विषैं श्मसान विषैं देवताके मंडपमें
जहांमंदिरानिकालदेहैन उसजागा विषैं गुरुदेव विषैं
मूर्ख इनां स्थानों विषैं चोडेको बेनदेहैन अथवा योशा
स्त्राविधि वोई की शालवर्णनेकोकहि है तिसकारके
नहिं योत वेलाबनायाहै तिसविषैं स्थिनकरणकारके
अथवा बलि होम इत्यादिकविधिपर्वैदिनौंविषैं न
हिकरेजिसमैं गुरु पूणाहु तिस्मादि देवदमंशोकर

कुर्वन्ति न ग्रहान् सूक्ष्मे वा ग्रामवा
सिन बलि होमाघाविधयः पर्वस्वा
यत्र न प्रवर्तन्ते पुण्याहघोषशान्ति
यत्र वा मंगलाचाराः यभिर्नानाका
रैरुपचारानि कर्मसरगाणि ॥ छि
द्रान्वेषीणिमशुं शानानि विशन्ति
वित्रासं स्वस्थानां पुष्टानां कृष्टानां
वाजिनानां च सहसाव्याधि विषाग्नि
सरिस्पोद्भूपणा विनाभवन्त्येवं शोन्व
तथास्त्राने क्रियमाणानां बाधुपक्रमेन्त्य
थे ॥ १३ ॥

केशांतियाहूं नहिंकरि और मंगलकार्य
नहिं करै अथवा मसानगृह विषैं वा ग्रामके बाहर डौरै
को स्थानकरेहैन पहैं नाना प्रकारके अपचार इनतें क
र्मकारकै चोरेको उपद्रव ग्रहण करनेहैन ॥ योगी
वल्लिद्रको देखनेवालेहैं नाथि सकारके विचार होय तो
प्रवेश करीय ऐसा गृह नाना प्रकारके चोरेयोकेविषै
प्रवेश करवानेहैन योधाई स्वस्थानिहैन पुष्टनाने गुरु
रोकिसे रोग करके नहिं ग्रहण करै होय ऐसे चोरैयोको
सतावोरोग अग्निगुरु विषके सम सतुपतै रहिनहोता
है जिसके सत्रूपके नहिं जानेहो परेपा योबाकिन्मा क
रनेहैन सोमसभ्यलटारोग बहुतनकरानिहै ॥ ११

© Dharmartha Trust J&K. Digitized by eGangotri

शा.
टी.
२६३
263

यहेवडाभयानकरोगहै यहे प्राणोंकेनाशकरहै
यहेवडे यत्नकरवीनहिंजाणेयांनानाकोयेनिस
केलक्षणवालाकोइरोगनहिंयेनिसमझोवो १४
यहेग्रहकरकेग्रहणकरेयाहैतिकिन्हाकोदेख
नाह्रोयामाणे इनोंलक्षणकरकेजोजाणातसग्र
हणकरेयाहै इयहेकहे १५ इनोंकेनाम ग्रहस्व
रूपसबकहहेनेहों शिवका कुबेरका स्वामिकाने

वोरत्नरः प्राणहरो व्याधिः परिवर्जने
क्षेके नहिंदृश्यते विकारो यस्य सम
दृश्यो यजदेवजुष्ट १४ ग्रहश्चेतिलक्षने
यमः प्रतिकर्माणि विस्मयाने व
पर्वविधैस्मलिंगैर्वाजीरत्नो ग्रहीत
इत्यरुः १५ नामान्येषाम पुनारूपा
णिच सं प्रवक्ष्यामि ईश्वरस्य कुबेरस्य
स्कंदस्य वरुणस्य च ग्रहस्य नैऋत्य
नमः सोमस्याथ विवस्वतः ग्रहा
नानाविधाः घोराः प्रवराः लोकवि
श्रुताः १७ तस्मादीश्वरः समग्रहा
रोहाः प्रकीर्तिताः चत्वारो राहस्माले
प्यागास्त्रिलसपदं वच १८ लोहिता
लोदिरूपाश्चोर्ध्वबीनिस्मपैवच १

स्कंदकावरुणका सदसृतिका शुक्रका वंदमाका स्
र्यकोदनोंके नानावरुन प्रकारकेकेवडेघोर प्रसिद्ध
कीहै १७ तस्यह तिनोंसनोंकेसध्यमादिस्वरग्रहवा
र वडेघोर कठिनकरकेन यहरूपरास्त्रगाहदकहेन १८
लोहितादा विस्रपाहरविवानि ये शिवकेग्रहकहेन

© Dharmartha Trust J&K. Digitized by eGangotri

सकामो अथ अकामो अनकामो एहे गोकसे अग्रकहे हैन १९
नवगतस्य श्रीरूहद्रग्रहसोमभवो देपाको मारने हैन
एहे शिवके दर्शीनरहतोवाले माणाके दरणोवाले
वेड़ भगवानकहैन २० हेगते हृ एहे अग्रहसव्रयभिन्
भिन मेरे नैं नाणा योगाके पदे शोन योगस्थान विधि
स्थित होया दासनावी पिवले अधोभाग करके पीड़ि
नेहै २१ अरूअगलापड़े भागनिरोग पहै पीड़ासहेनेहै

सकामो वा अकामो वा अनकामो व
गतश्री १९ निष्कामो देवलोकस्य समा
निश्चिन्तितरंगमान् पदैः प्राणाद्द्वा
योगा रुद्रानवशावर्तिनः २० ग्रहरत्न
पाणिराजेदृष्टचक्रे केननिकेपमे
मद्धाः स्थितः स्थानेपश्चद्दैनावसी
दति २१ अपीडने प्रवेकायननिषेध
नघनोभवि अकस्माद्वापितेवाभ्या
रमकौविद्रविमचति २२ लोहितानाहतद्ध
नोपंटश्वेवपारेवर्णे येन २३ स्थिपनेस
दनेवाघापाभिद्रष्टनिवापिके पकेनि
मोलयनेत्रमेकमर्मीलयन्नपि २४

अरूमचनशिकस्थाननिशेषटरलदानदिष्टष्टवीने अरू
अकस्मात् आतिपाते रुधिरकी पावुदा वलनी पारहेन २३
लवलोहितानाहतकरके ग्रहणकरपाहे निसकोर
लेकेद्विस्थागहे ये १पावनहिकरे २१ पाचोस चयनपर
साघनरहै गहरलदाहै अरूवहन हिमाकदहै और प
कश्रतिमीटारलदाहै १कहमाईरिलदाहैये २४

© Dharmartha Trust J&K. Digitized by eGangotri

जिसका कोई रूप नहिं जाणे या जाता ग्रह दोनों ने ग्रकरके
विवेचना विक्रम त्रय है इसलदलाकरके विद्रूपात नाम ग्र
हकरके ग्रहणाकरेया है इसकी चिकित्साकरणी को ना
जावे २५ यो वो डाग्रपणे स्थान विषे स्थित खेडा होया दा
सता वी है मर्दन करके छ्यवो ऊपर गिरउपदे अरु भाक्
ल होया दासता वी उठके सारे बदलो फिरदा है अरु परसे
करसारा शरीर भिज गया है २६ अगले सर्व भाग देह के शा

अनभिज्ञो यत्र रूपेण ग्रहनाम्नो विवेचन
नः विद्रूपात्स ग्रहोनैन्न नाधिगच्छेच्चि
कित्सने २५ स्वस्थानः स्थितःस्थाने भू
स्रां निपाति मोभवि उत्थितेविह्वलः ति
र्यविम्बुलति सर्वेना २६ वेष्टते सर्व
कायेन शीतस्वाममरोहयः हृविग्र
हग्रहीतेन तदेहे वेपारिवर्जयेत् २७
खुराः केशाश्चबालाश्चशिर्यन्तेपरि
वर्तिनः त्रिस्रुकग्रातः स्तब्धाहनुः स
न्त कंठा स्थितोपरः २८ वाग्निनाम
ग्रहोयाक्स्तेन तेन परिपीडितेन वर्जयेत्त
रिमान वेहत्यायथार्पितस्तद्वैवमत: २९
थरहलदा फिरदा है अरु श्वासमहेउ लेना है इनां लक्षणां क
रके जाणीते है कि ग्रहने प्रवेश करेया है इसको दूर त्यागकरके
त्याग उपानाकरे २७ जिसबोडे के सब केशा अरु बालगि
र जान वा विखरजावै सबीरके मका फिर चवदी विविले अरु
देह चेष्टा रहित होइ होधां अग्रमरु होजाना तीया है ते बनइ का ण
अरु ठीरा रकाङ हिलिसरदा है २८ सो वाग्निनामसशो होर है
जिसनें पीडन करेया है ऐसकों बलरवैषम्याग्नै जैसे पन
सुइदा है तेसा ही पडदे है २९

ऐसे सोच होइके हर देसमें लेजावे कां पै और नांकों बीना
चे मेरे १० जिसके पिछले दोनों संबोविषे शोभन मन है
वे गुरु उपने आप जिसके राम ३ उ नाम और रवेग टमा
होवे गुरु एकुं वे ३ पेर थं गुरु जो के पास संविद्य शिकसपा
ने के पास पैहै जिसके एक पासे कालेमा ए लूले कौन
रो ११ सो कासीग्र हकार के ग्रहण करा है जिसको देके
हिया गोउपायन करे १२ यो वाङ्गं क्रोध एकांहो के अप

देशात् संतं येऽतिसमस्तानन्येन दृष्टये
न पश्चिमाभ्यो न वा तम्भोऽस्य प सुयं स
मायते १० एकस्मात् घोषं तरामका
मः स्वामसमनायते यतुं वकोप रेय
स्मकिं केनवं जानाति ११ सकासो
निग्रहीतेन दृष्टेवं परिवर्जयेत् १२
यस्य रोषसमाविष्टः स्वानि गात्राणि
खादति ३ समस्य कस्मात् याविमोद
नैदेनानिखादति १३ सेलव्यहन
निद्रा प्राथमानं न लिखति अस्य का
मोग्रहीतेन दृष्टेवं परिवर्जयेत् १४ श
यानं सन्यपाद्ग्रच्छायां मेदीमवमा
शिवनेदमनेवेवपनेपरिमुच्छाति १५

लोटहकों खावे वे गुरु एकस्मान् १२ गुरु एसी ना
वते और देहोके साथ दोनों को खोवे देहा किडके १३
गुरु नी हा टोडी मडा है नान गुरु उ वह लावता है सि
ने है सो गुरु कासीग्र हकार के ग्रहण है जिसको हर
में हिस्या गट है १४ जिसके सने होएके हि सेव गुरु क
उनाम गुरु देह शोभा बदमावे गुरु से हप रसादा०
हा हो वे देहके वे गुरु सकमावे १५

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा
टी
२६५
265

अरु देहहू बेष्टा हुलताचलायनोनहीं होताहै दमह्वे अरु यो
कोशाकेसहितनेमहणभाव स्थानकोवाहरकेघानप
नहोवेमोपहू भनकामी करकेपीडितनजाएकेहरने
देखकेउघापनाकरे २६ पहिसनगहवेइ करडेसबू
पकरके कहेहैन एकसमस्थितहूसरीवेशाखो
नीसरा गलग्रहू पहेवघग्रहकुवेरके वोउँघोको
ग्रहणकरणेवाले कहेहैन २७ योछोउदोनोनान्

निश्रेयसायवस्मिन्नकोधयःप्रमे
होत फलकामीमहोनेनरहिवंपा
वनेयन २६ येनममगृहागोह्यत्रुपः
नःपारिकोमिनाः क्षमीश्वनस्ववेशा
खोनश्ववनलग्रहः नेरगणोमम
हिमास्यःकोऽयकाग्रहः २७ खिनः
सबलनिनाशुभ्योशिरसामेहनोस्य
शेत् खेरयसमनेधर्मिकवैध्यथ
तिकेपने श्लोकपतिवानानेम
नेमवापिरक्षति २८ ममोश्वनःग्र
हःस्यहःसमकर्मनामित्याति यमक
श्रणानिमेणिमवोणिनध्यानवगुरू
णावविचारसमानःसबलनियोनसप्र
निवाहयः २९

श्रींकरकोइगटाहै परमाप्राबेशि
रकरके पृथ्वीपरस्पर्शकरनाहै अरु सबे केभारखेदे
नाहेघापृथ्वीउपर अरु कु वेसबकेमोउविषुकोउश्री
रकमहाहै ओरनिरंतरअपणाआपको देखनाहै अरु
वहनहिणकराहै २८ सोसमस्थितएकरके प्रवे
शाकरेणाहै निमविधिचिकिन्साकोश्मिजनुहिहोति
निमवोउके समभुगम्याकेहनाणा अरुभारहोण
अरुवलायाहोया इगपसे भ्यवायोनाचलेवोश २९

© Dharmartha Trust J&K. Digitized by eGangotri

वैसाखीनामनिसकूंपककरके इसप्रकारकरकेथोडे२
कोप्रवेशकरहै इसकौविकिनमानाकरे नीसेरदिनम
रनानाहै ५- जिसथोडेकोग्रीवाकेउपर करडाशा
नासारीकोमलकेस्थिरहै अरुगलकीवहनमनना
वेश्रकनाथलानाउलासमासलेवे भावाला तिसको
गलग्रहनामगृहरोग कहेयाहै तिसकोमोयहोपकी
जाएगा ५१ स्वामिकार्तिककेयहेग्रहकहेन पकमट्गुग्रह

वैशाखीनामनऋतैमेवमाथिशानेहृदं
नतस्मैकारयेनकर्मसत्यहेनाभिमनने
कार्दिनःस्वयपशुर्यस्यग्रीपमाहमानिह
तिकेवस्त्रश्रवनेनयथैशीघ्रंप्रसिनिह
वान् गलग्रहग्रहीतनमस्तरस्योवनर्हि
ड: ५१ मस्तग्रहीतेनवमस्यैवोडेग्र
हेस्थयः कार्तिकेयग्रहागोगनाम
नःपार्श्वकौर्तिनाः ५२ चतुष्पल्यापिव
त्पल्पनवखादतिखादनं कच्छादा
मेः तिनेनारमहृश्रेषविनस्यमन ५३
पिडिकामालमध्येतेग्रोघेवायमष्ट
ष्टपते मस्तग्रहग्रहीतेनमहेवेपरि
वर्जयेत् ५४॥

इसप्रदीवेन ए तीसरा अडेग्र
ह पहेवेरे थोर तिहांकेनामकरहैन ५२ घोडाराका
पथ्योडावरनाहै और नलकीपाडा खंदाहै अरुओरभा
नखदाणा नहिं खंदा अरुथोउसकोपकरके लेवलमा
है तिसकौवहेड़खकरकेमिलमाहे अरु वारंवारवह
नस्नासलेनाहै ५३ तिसकेमालके वृक्षकारपकुपि
डिका फोगुणोहोनीहै अथवाटाटीकेउपर देखीदहै
तिसकोमस्तग्रहकरकेग्रहणकीयाजानो तिसको
वैदेखलकेदिरहटमावे ५४

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
२८८
288

तिसके बाहर के सबके ऊपर जो भकालो अग्नि होवे सब सक
नावे अरु नव नैत्र बुद्धि स्मरण बलि चटना वे अरु अप
णे अंगोंको भी नाश गोपा अरु अयणस्कंद मांडे रंध्र श्रेष्ठ
के समीप स्थान इनां कों देखता है ४५ उर्ध्व श्वास लेता
है तिसके जाता है अरु कालीने के सहेले सहटा है
नव ऊर्ध्व ग्रहक रके ग्रस्त हे हे णा तिनां के लक्षण प
हे हैन अववरुण के चौरापकारि नवी नहिं वचदा ४६

श्यावा निद्रा समवे सुष्टुं कुंडलिनी समासरू
तिसया नावेदपातिवोगानि स्कंपारंभे
वटपपाति ४४ कंठस्थासा मशोदीनः
स्थलकर्णा शिरोपरः उर्ध्वग्रहग्रहीतो
श्वोद्दिवसेनानिवर्तते ४८ स्कंधौ नवा
रिणाम हस्तहस्ता लक्षणं भवेत् वा
रुणः प्रथमः प्रोक्तो देवप्रतीतिना
मतः ४७ द्वितीयो वारुणः पाशात्तृती
यो वारुणानलः कन्याग्रहस्तु नैर्यः
स्यात्तेने वारुणाग्रहः ४८ गुदं सू
त्राणां कोशश्च उपस्थानि द्रावनालं च नेत्र
कोशाफले चाभश्यावाम्यस्थानं केपने ४ ९

पर्हे स्कंद के ऊपर है तिनां के लक्षण पहे हैन अ
ववरुण के कहे मैं हो पहिला वारुण नाम है नि
सका देवप्रतीनामक हे पारे ४७ दूसरा वारुण
पाशनाम है अरु तीसरा वारुणानल है चौथा
कन्याग्रह नाम है पर्हे वारुण वारणके ऊपर बांहे
हैन ४८ जिस बाहरे के गुदा मलद्वार दूषण अ
हंकोश जीभ नाल भ्रतियों के कोश अरु नेत्र
स्थान काले में मिलिन हैं ४९

© Dharmartha Trust J&K. Digitized by eGangotri

गहोवे इनोंका श्रौर कंठे श्रौरलेभ अंग आकउजावे
अहदेह जिसका शीतल अरुभारा मतीनहोवे अरु
दृष्टिजिसकी उर्द्धहोवे उपरकोंदेखेदाहै अरुजरहो
तावे [illegible]भमदेहनाहैसारेपापसे ५८ पदअसे
लक्षणहोवे तोदेवतेलीग्रहकरकेग्रहणकरेयाहै
जिसकाजीवमस्तककरकेहै मरनाहै वाउकोजे
लकेविषेस्थितकों अथवाजलकेयासस्थितहोय

लेभशैर्मगरकरवगात्रांगपसल
होते ऊर्द्धदृष्टिर्मस्तकश्वासैर्मत
नेमृहः ५८ देवग्रहितग्रहीतमण्डलं
मनस्थितोवने नदगंसलिलस्थितंस
मीपेसलिलस्यवा दारुणावारुणैः
पाशैःवध्यतेनिगडैरिव ५९ सवजे
वारुणैपाशैर्हैरनेपरमविसनं हृद्
रोमाभ्यंगास्नस्योडाश्चिकिन्सा: सता
दृशः ६२ यो मृहृतैस्थितसौपेना
तेभ्यः समवमीट अग्निदग्धःशवास्पृ
किनाशःविवर्जितः ६२ स्यपामि
वाग्निनाचनस्वपनं एहि विशोधनं ॥

कों दारुणबहुनकठिन वारुणपाशकाई वेधन
करलेनाहै जैसारसे करके वेने ५९ सोवरुणकोंकाः
करकेवजाहोयादावाडाबडाहिरणकदाहै सोमल
देहोनेहैनअरुघुकुरेयाजानाहै सोअैसावोडे कोवि
किन्साइसबकरकेहै ६० योचाहादावडीपाणिके
विषेस्थितहोयाहदादोनों जानेभोकेरकेउदिवनहोया
है जैसे अग्निकरकेजलेयावहुनकिनाशकरके...

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
२६७
267

... पीडित ५२ जैसे अग्निकर्के किनले देहपकी इष्ट का
र्बंधपटजाताहै सोवारुणानल वरुणकी अग्निके सा
थस्पर्शकरे याहै यवयहलक्षणहीवेतौ सैघस्यागटे
वै ५३ जिसचोटकी भ्यांग्रंथि विवर्त्तनकाहे उपर
कारटेहापकीन्याइ जिसकीग्रंथिनेनलबलेपर
साप्रावै अरुदोरदोड़ीयारुकनाण अरुबहनके
वे वारुण कन्याग्रहकरके पुरुषचोगजीवतानहि

वारुणानलसंस्पृष्टमेवेद्यं पविवर्त्त
येत् ५३ विवर्त्तयन्निवस्पर्शेयोः हो
णोविषयनेहयः हन्तचोभमेहोनेव
यच्चेवयातिचापिक ५४ कन्याया व
रुणस्याथ ग्रहो नो स्यान्नजीवति ३
ये ते वारुणाः प्रोक्ताः ग्रहाः परमदारु
णाः ५५ वामभागेशरीरस्यानिष्पि
ष्टेयस्य दृश्यते नो हि तस्मादहनः शि
रोतोगण्डापिदृश्यते हृदयस्यानिर्ग्रह
ग्रस्तोनमनोवनीनादृशः ५६ भाला
नि कूटस्तनगोरन्ध्रामस्थाणि संवाने
रुण्डे मे हने चापि सवलमानाप्रगच्छ
ति ५७

यहवारुणग्रहकदेहैनवहुनजगतदायकहैल ५४
जिसचोटकेकालवायासनोनावे अरुनाडुनकरेयादाके
बहानहि अरुदेहदेहाहेसोहरयानिग्राहकरकेग्रहना
हे येसा योगनहिजीवताहै ५६ जिसचोटकेग्रंथिको
टोविपीड़ा ओरशोभा अरुलहकेस्पुटहनेहै अरु
पेछाव लहकाहोनाहै अरुबलनाहोयागिरनाहै ५७

© Dharmartha Trust J&K. Digitized by eGangotri

श्रोत्रे ग्रहन मनन करके स्पर्शी होया दायों ज्ञान यादिन उ
परे नु मर जाता है अरु घोचोउ घोड़ा खोलता है अरु
पापी की घोड़ापी अरु सुनादव हुनदमलेता है ५८
जिसको घ्राम ठडे आवने है न अरु देहवी शीनल है
अरु नेलकरके सारा स्नान करे की न्याइ अंग होने है
नपहेलतणा करके घोडे को सोम ग्रहन है पाड कोर
पाहै जिसको डोंबपीनाकरे ५९ जिस घोड़े के नेत्र

स्पृष्टो ग्रह्मणं मनसा विरात्रेनातिव
नेने स्वत्स ग्रासोदकश्चैव शोनशो दे
विनाशमन् ५८ घोनः घ्रामसडोनगा
त्रावाभिरणाव पटिसन: सान्यांविव जे
पेदस्य सोमप्रस्तानिपीडिने ५९ रक्ता
त:सनने घामो मूलके ठ:प्रवेषन:
स्वेदस्ववानि वान्य यैपथ्यानो योष्ट्यिन
लघा ६० श्रृंघ्राणं मेदा सास्फष्ठवने
वाष्पयमाथ्येने पथस्तु यं ग्रहेनामर
ष्ठैवं पाविवजेन् ६१ पकाविशानिर
वेष्ठग्रहा: संपाविकोनिता अमाध्या:
प्राप्या: सर्वे भवंतिमवज्ञायिप: ६२

लाल अरु वहुन घाम लेता है गलपीडा अरु केप:
होता है श्रौर परसाव हुन वगदा है नेसे नलकोविं
श्यिन हाके वाहर आपहो पकीन गो ६० अरु श्रम
सरमिर साथ मिलकर के अपशावना चलना
है पहे मरो नाम ग्रह है इसको टरवके हरनेत्याग
देवै ६१ पहे ग्रह रकीन गो है घोरे धाको कहे है ने है
गजन पहे सम अमाध्य निष्फल करके है न ६२

शा.
टी.
२९८
268

तिन्हों कों वानप्रिस्क फरक्क इन्हों करके और अभिवा
न चाटवाप आगेन पेहसभ इन्हों करके और अभिवा
कोई रोग नहि इकालिसकों विद्यमान ९३ तिसकारण
ने पेहगरहजिन्हों के आयुद्या चटगै रहे तिन्हों को पष्ट॰
क्का करके ग्रहण करने हैन कैसे वो पेहगरहेन जैसे अ
मि है ऐसे सर्प है ऐसे हलाहल विष है तैसे ९४ तैसे॰
हि वोडे पाके देहकों भ्रामहोके रानेंसें सगरहेवष्टा॰

न चापि वापुर्ने स्लेष्मापि ने वानव शोणि ते
अभिघात समुद्भवा गते नो हैं तस्त्रय नाविद्य
ने ९२ तस्माद्दीर्णपुर्वसंस्थरराहोनेने
पटलया पथ्याहानिर्यथानागोय
थाहालाहले विषे ९४ तथारस्यां
सिवैष्टने देहमासाघ बांतिन्तो नान
त्रकारयेत्कर्म विकित्साशत्रशास्त्र
पोः ९५ पानन्नोमाक्तनादीनाप्रथ्या
कै विनिवारणे प्रणामाने नमस्कार
शांतिहोमैनपेसलथा ९६ दीहाभिर्भू
तनाराद्यमनोबारैष्यानैवपैः ॥

लवण करने हैन तिन्हों विषे शस्त्रकर्म अरु शास्त्रवि
धियों चिकित्सा है सो सभ्यनिन्हां विषे नहि करहि ९५
९६ और पानन्तरसादि अरुमरुनादि इन्हों के हठा
णमाल याचयाग करहैन तिन्हों करके और प्रणाम
नमस्कार शांति पाठ होमजप दीक्षायल इन्हों कर
के और भूत नाग इन्हों के अनेक प्रकार के भिन्न
भिन्न तिन्हों के मंत्र उच्चारण करण करके विमाचे
सगरह करके ग्रहण करे होपेचौरै का पत्रपसाँव

© Dharmartha Trust J&K. Digitized by eGangotri

जिसजिसदेवताकीसरणकोप्राप्तहोवे औरस्थाप्
णकोमरणकोंप्राप्तहोवे १७ इतिगृहलक्षणंनामप्र
नविधाविधिः अवयज्ञकर्मयज्ञकरणेकोविधिकह
तेहै जिसकरकेरत्नगृहशास्त्रमयरूपगृहयाकेहैनेवि
नाकोनिवारणकारहोनेहैन सर्वदिशाविषैउत्त
रदिशाविषैसुंदरस्थानदेषयासनकोप्रतिष्ठितकरः
णेवालाहै जिसमैज्ञालरचे १८ जिसस्थानविषै

येनयेनग्रहोनानांरूपंभवतिवाणिना
अपयेनतनस्तादेवताशरणंहिते १७
गृहलक्षणंनामप्रथनविधाविधिः य
ज्ञकर्मविधानचरस्यग्रहनिवारणे
प्रागुत्तरस्यांदिशिकेस्थानेरम्येमनो
रमे १८ पयोंमसलिलेमध्येसर्वदोष
विवर्जिते नत्रोडुंवरशाखाभिःकुश
शीरसमन्विते १९ ह्लोकैलिंजसंवी
तेचतरस्रेसमन्विते उदग्प्लवेकारयो
तरूपागारेसुमंडपे २० शानदृक्तायन
हस्तुतोरणाबाटशोभिते पताकाभ्रसमु
मानस्थवारामपूर्वोत्तिनोत्रुयाः २१

ववस्त्रीनलहैजिसकेवज्रकार सभदोषनेरहितहैन
हांरूपलकोपांशाखाकरकेअरुदर्भसीरकेसहित
यास्थानहै १९ जिसविषै टहकनारेकरकेगुप्तकवचले
रेकरे अरुपकेंस्थानसुनाव अरुनहां चारोंकोशाला
उत्तरस्थलहारकरे वबलोकोटकरकेप्रावर्णकरे २०
तोरणभूमिमहोदृस्तवरीकरे औरवहुतमारीवनावे
ध्वजापताकानेअटाभीयाकरकेशुभायुमान औसीशाला
विषैशुभस्थानमें यनरवेयहोत्रैकोवामकरावे २१

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा
क्रा
२६६

ग्राम में पूर्व नृगर वैष्णो र द्रोणे निन्होके साथ परिवा
रितचारे ग्राम नै वाहर लेणा पोगये हैन नहां जाय के
सुशोभित न मुख्य कम हूत वणा मनोहर वाटशाहेन
वृषवाथ हूँये द्वाहेन मुखवा त्रिगणा हेनकराते
षष्ठीविधियाकीहि है १२ सोसुशोभित हैन वेष केसहि
न पटवस्त्राधारे और पंकेयभि कास्थान छोड़ हय
मरत्मकरु हालावणा वे १३ अरु पंके कंड़े करके सु

ग्रामैः परिवृता साभिः नैकैर्या ग्रामतो
बहिः त्रिंशता चैव समाहृदया कूपत
मेव च नवकूप्याघट्याघामाम्भिक
मेघ्रोहितः १२ सुकेनाभिषमासाउं
भाद्रनैलौमवासमा नत्राग्रथारणाक
नाषरहलैप्तपुलोपकैः १३ द्रहेकि
लिनसंवीनमष्टहम्लोपाने शुभे वेदि
ष्ककवद्भभिभो ३: कलशेष्वापशामि
ने १४ वच्चैलोनेष्ववीजेप्सरन्तैर्गोरो
चनापत्नैः कृशेरथ्यामपथेष्वनैलेघ्रा
ते: पृष्ठकालिये: १५ भद्रभाज्यप्रम
येष्वविविधेरापिष्टकालैः पविश्रसाभिब
लितमेवनैरसमनोरमे १६ प्रानकं
मविष्मालनसामेनाढ़निवावेरे ॥

कुटहस्थ वौहाकरे फुंदरसो वेदी बहुतसुवामा
लाकरके शुरुहरापात्र कलश रना करके सुंदर
शोभायमानकरो १४ १५ सुलपाभीदी पांवोलोंऔर
वोन रत्ने नेनाबन रनां करके माम कृशानल पल
वकोमसल पायाम और भिनभिन रचेहैन निनाकर

© Dharmartha Trust J&K. Digitized by eGangotri

केश्रोरभक्ष्यभोज्यपवित्रनिनाकरके ग्रौरम्रनेक प्र
कारके भूषणोंकरकेशोभित ऐसीयज्ञभूमिविषें
पश्चिमविषेंद्वारगमहै ग्ररुश्वेतहैंतवोकुनिसैं
ग्ररुपताकनसैं वडेविस्तारवाली शोभाकोप्रकेशू
ट वरून गमाहै जिसविषेंकलहनहि ग्ररुपापकह्न
नहीनहि ग्ररुवडेपकल्हवालीनहिहै ग्ररुशास्त्रा
नमरवचननसेंरहित ऐसीपृथ्वीकेविषें शांतिको
पावनावै ११ तहांसभपुष्प ग्ररुगंधद्रव्यवेदनादि

वैतथ्यमानरहितेनतत्रशांतिप्रयोजयेत् ११
तत्रसर्वाणिमाल्यानिगंधश्चैवविशेषतः
सर्वाण्यन्नानिभक्ष्याणिदधीमममद्
दीश्च १८ सपल्लवानिवस्त्रा
णिविविधानिच धातुधान्यविविधाश्चै
वमहौषधोषधीस्तथा १९ शुभेन
पुष्पवाद्येनाधिशंगोतवनादस्तथा गो
भिश्चैवस्वर्णरत्नभोजनलमानोपवृहिता
न् २० सतिकाश्चैवविविधाः स्वर्णपद
र्शसमन्वताः पुण्यापतनतोर्थैभ्यः
समानिनयपात्रगम २१ देवताश्चप
निष्टाश्च श्रद्धाणांसर्वतोदिशः ॥

ग्रौरग्रोपवित्रवस्त्रसमता ग्रौर यहरूपकौंप्रगटकरहैन १८
येमेंगलकरहन्ह ग्ररुनानाप्रकारकेवस्त्र ग्रौरवहुत
प्रकारकेधातु ग्रौर वहुत्रनेकनांकेभोजन १९
ग्रौर वेद मयौरवदवरमस्वेनदियेगु हारदल ग्रौर
श्रृष्टपवित्रमौयोंमेंजलमगावै वनेरधरिन २० ग्रौर
पवित्रस्थानोंकीपांसिमौपा ग्रौर येप्रादेवालपनोर्थ
रनौनग्रहणकरे ऐसे वेदनेकहेहैन सोकिदेकरावै २१
देवनादिसथानप्रालानिविषैस्थापनकरेदिग्पालांकौं २

© Dharmartha Trust J&K. Digitized by eGangotri

शा० हो० २७०

और सूर्यादिनवग्रह सभ दिशां भिन्न स्थापन करे ९२ तिनां
को तिनें दिग होकार के मजन करके शान्ति का प्रारंभ क
रे पुरोहित तिसके दक्षिण पासे अग्नि का स्थान करे अ
ला को उत्तर के पासे वेद का स्थान बनावे ९३ अरु वे
दी या मंडप विषे वेद शास्त्र करके विधि करके बनावे
अरु तिसमें दिन अरु रात्रि विषै बली या करावे और
शान्ति कर्म करावे ९४ फेर नवीन कलश ले के न
लों करके भरणे करे अरु गंध वस्त्रादि पुष्पमाला

प्रथनः स्नापितान्वस्त्रनः शान्तिप्रयोजने
न ९२ तस्माद्दक्षिणतः कृत्वा दक्षिणस्या
पुरोहितः शालायाश्चोत्तरे भागे वे
दस्थापितवेशने ९३ वेदीमंडपयोर्मध्ये वि
धिना यथाशास्त्रं यथायामं दिवारात्रौ
च बलयः कारयेच्छान्तिकर्मैव च ९४
नवे घटे रूपे शस्त्रे गंधमाल्याम्बरैर्युतैः
सतिकाभिष्टपुष्पाणाभिस्ताभिः सिद्धा
र्थकैस्तथा ९५ सुमालब्धानि सक्षे
त्राणि निनो मंत्रमर्वकैः दातैप्रनानि
नोरुकलाननेतरमेव च ९६ शुद्धनल
वगान्वेघः समेनाडपदीपने दाग्नाम
गन्धपार्थस्यारत्नोपमुपहतानि च ९७

इनो करके भूषन करे तेना करके और पुणपस्थानों को पं
रत्न को करके और सरेषा इनों को ले के वोरपों को अभि
षेचन करावता जोग्य है मंत्रों करके मानन के उपरे न एक
न के टीहक्षोनरा जगा के वा है को धरोंने ले करके व
वेदपर वेघः सादाबीं शुटी मंत्र के अनुसार करें नैं
तिस करके रत्न मनाशहोंनहै न ९७ ॥

सोयांनिचोरेयांके शत्रुरोगरहोनेहेन औरस्राव
घाबलशरीरहनांको होयानीहै यथाशास्त्रविधिक
रणनेदेवनागरहू अरोगपनादेतेहैन ८८ इशान
रानगारहोर समयायाईकोमारेचवखीफेरे नि
सकेपीछेफेरपवित्रजलोकेमाध्यसंचनकरावे
नवकल्याणकोलभतेहैन तिसके उपरंत रागनेर
हिनपवित्रपञ्चरत्नग्रहोकोमल देव पंचनिवेपनी

हिषत्त्वानिकृत्वेचैवयदेशंनन्वंगमा
न् आशुवेलेवपृश्चैवयथाशास्त्रंविदेश
नना: ८८ पंचप्रवालिनोदायोंपपानी
पासमेननः नरगानपुनरभ्युसप
विश्चेस्वसमालभेत् ८९ निरामपंपपश्च
मेध्यरस्वामभ्यस्मस्नेहलिं शांतिनि
वापनोलेषारत्वोयोपापनाशिनी ९०
ननस्त्रनयोदिवसहूपमाणेहृत्नाशेन
रयहस्तेमंहूनेवस्नानानष्यानलेकेना
न् ९१ यत्तभूम्यापथ्यादिहोमिषगुम्या
प्यमोरणं ननोनोरानलोमकोनवासान
रगानस्थानमेवशयेन् ९२ ॥

नामयांनिकहिहै रात्नसगृहकानामकरोहै औरपाप
कोबीरकरनोहै ९ तिसमेंयोथ्यादिनविषं अग्निकेवि
येहवनकेरे रापने योमेछादिनमरविषं रोईयांको
स्नानकरावे अरूभूषणपहरावेहांयोंको ९१ वेपुनी
ईयांको यहशवयत्तभूमिकोहिहै तेसविषं नोरणको
उठायकरके योग्यारनोकीविधिहै तिसकोकरायके
रके तेसमेमवेपाकरावे ९२ योशालाप्रवेशविषेगो
रीकरके पोसनकरीहोरहै तिसकोफेर ननसाध

© Dharmartha Trust J&K. Digitized by eGangotri

सेवन करे तिसतैं हर होय है न पाप तिस स्थान के कैसी
शाला है वर्तन र वर्तने हैं न तिनों कर के युक्त है और
मणिकलशों कर के शोभायमान है ९२ जिसविषे पव
रत्न गौओं धन वत्स सवर्णा पेखा लक्षणा युक्त हैं न ग्रह
गुरु हवनिवाले ऐसे ब्राह्मणों नार दान देवे ९४ सोम
णि हलत्राह्मणोंनि नोके साथ सभ मंगल के वाने व
जो देहाएम दहणाकरावे होड़े पांकों ९५ पैडोडे

गोभिरश्वथितेश्चैर्वासोभिर्मरकतकल्प
षे वादित्रध्वनिनोपेते सर्वैर्णाकुंभैरलं
कृते ९३ यश्चरत्नानि गावश्च धान्यसंवा
सांसि कांचने शुद्धेभ्यः शुद्धविद्येभ्यो
ब्राह्मणेभ्यः प्रदापयेत् ९४ ब्राह्मणा
श्चनो विप्रास्त्रीश्च वदनेरगमान् यव
तिणां ननकुमुदः सर्वैर्मंगलवादनैः
९५ एवं दोषहरे हीनानो वाजिनां कर्म
कारयेत् देवानां वप्रमादेन रोगाश्च
नाशिवाजिनः ९६ नाहि नष्टे नेष्टाश्वि
वनेपि नमन्यथा तस्मादेवपरोनि
त्यमुत्विरश्वानुपक्रमेत् ९७

रवसों ने ग्रहण करे है न तिनों के निमित्त पहले विधि करा
वे देवतेपांको प्रतिमना कर के बाड़ रागों ते छत्र ना
देन ९६ अरतिनिहांथविना और कोई न हि हरा करने के
समर्थ है तस्मात् तिसकारण तै नित्या हू पवित्र
होके देवताके आश्रय होयके कसमणकोर ९७

इतिग्रहलक्षणाध्यायः इतिचिकित्सास्थानेसमाप्तम्
जिसकोचिकित्साइच्छितनारीकरतेहोयअग्रामनतरिनावि
धेकुच्छविशेषनाहोवे सभयत्नोंकरकेनवनिसकोउ
कीचिकित्साकानबावदेदेवेअस्तुशास्त्रकेजाननेवा
वाला १८ योवायनलटाणखोटाहोवेसोअसाध्य
वोहैतिसकाउपायकरेवैद्य अरुयोबोइभोजनयो
इकरे अरुसुखसाध्यबीहै नदवी उसकात्यागकरे

इतिग्रहलक्षणाध्यायः पञ्चेचिकित्सा
स्थानेसमाप्तम् यत्नेक्रियाप्रयुक्तास्समा
र्हेनाभेवोहिभेषजम् सर्वौपायेस्तुयत्नः
प्रमाणेभ्यःशाशास्त्रतः १८ यद्ब्रूतेनाथ
लोहुत्तमष्टनमसाध्योरोगमुच्यतेपु
नरेष्विषक नस्मादस्माद्धारेसमाध्य
मापिसेवनेनमात्रः १९ हीनाग्निस्त्वा
हारःप्रमाणोत्यल्पसर्वरोगेषु परिवा
रिकहीनोपष्टोषधसंपदाहीना २०
लघ्वालोनिष्ठुणवालेनचीनयेद्दनिः
मिथ्याहः सहतेनाऽनमार्गिकाकाष्ठ
नवारयेयस्तु १ योनोष्ठामावाजोऽशौ
नगदोपष्टुप्रीनिनामासमः प्रास्यनस
निनादैविसनेयेत्तुद्रिमानवैद्यः २

वतरः १९ जिसकोरेकीअग्निमंदहोवे अरुहारभोज
ननाखावेसोसमनोरोगोंविषे जवावदेणयोग्यहै
योकोनापरिचारकसेवकभी रहितहै और ओषधी
योकेसंग्रहसे हीनहैयो २० जिसकोरकेनेत्रनइहोन
औरवचाहलाणाउसकाणानहि अरु उसनहिडोलता

© Dharmartha Trust J&K. Digitized by eGangotri

शा
टी
२०२
202

अरुमारकेंबोनहि नागाना अरुअग्निकेसेककोबोन
हिमनना और कांकांकोडुगदेहांयाकेंबीनहि हटानाहै
५ अरुशीतलस्नान गुदा अरुनासा मुख येहै टेटेहो
मेहैन औरमुखनेदुर्गंधआवे ऐसे लक्षणवालकाउके
वनरवेषआग ६ जिसघोडेकारकरोगहटे अरुरघ
दा औरकांपकरे अरु और पक हैवे वारेवारजिसको
होण ऐसेको मागे ७ जिसघोडेको हरव वाल्याके

पकशोणितगवातिभयश्वासःप्रकुप्यति
विकारःअन्यश्चान्यश्चक्रनयंस्यभवेद
नेयनेन ६ यस्याहृन्नयमलधाभुलोवा
धापिनाभिभूतस्य सस्नावभवेजिह्वा
दहैवेसस्यभेन्मातिमान् ७ यः होयते
नसमान्याहारेवेहविधेयपक्वानः स्व
लक्षनिरारुद्धारोहाचेनोवनेयनयातः
८ सर्वैगात्रेवामेदातेणमपरेवश्यते
यस्य वायसत्खमपरस्रोमेदाद्धोरोगसा
ध्यत्व ९ एकंपस्यनगात्रेसवेदनेभूप
लेस्यापरिदाह सनरमयकोटविन
वैकोगनेसजेन १०॥

वै शोनवातिसकरकेव्याकुलहोवै इजाण औरपीराहो
कनावै ऐसेकोंदेखकरकेबुद्धिमान् अरुजोहालम
याचोगलनोलाहै सोबहुतप्रकारकेभोजनउपायनाकरे ७
नानानहिहोनेरे औरपाखानननाहिहै अरुदेहस्थलहो
से एकहोरोकोवनरवेद्य मागेंक्योंकिस्यानाकरे ८
निसघोडेकाशरीरकासनासा मेघपरले पोनाहोवे
फेरवबपासविषे शोनहोवे पदत्यनलसाध्यके है
पाहै इसलिये लेपानबटनाचनो असाध्यकहै या
है ९ जिसका इकपासापेरा अरुहाहै काकेउकरावे

© Dharmartha Trust J&K. Digitized by eGangotri

अरु बस्तिहृदै अफारकविषे इंवट मनालपीरा नि
सकौं त्यागदेवे १० जिसकौ आफरा होवे अरु लेलाको
नरा दमहोवे टंरा ऊर्ध्व स्वास होवे अरु होल लगनि वले
और मूलहोवे वेगज ई होवे तिसकौ विकि   त्सान क
रे ११ यो वो अंतराय करके मूत्र वो ई ज्वरका होवे और
कं वे लिंगविषे पीडा आफरा और स्वास होवे तिसकौ
तिसका जतन वैद्य नाकरे १२ यो वो डापिंडकौन

अध्मानितदृग्यो हृतिवन्नशीनोछ्वासीबस्ते
रुगार्तिश्च ध्लोपसक्तः चाहः प्रतिकर्म
न कारयेत्तस्य ११ वातेन मूत्रसंरुद्धोपके
पोतिमूलमेहनो ध्मातः नातस्वास स
भैषेन प्रतिकर्म न कारयेत्तस्य १२ यः
पिच्छिलेप्रमेहात्तिश्लेष्माणो पांडुरेमश
मोडुः लालास्यमाल्पापी वा वाजीना
केन रंदस्य १३ गलसंटीपस्य गलेक
रोत्सेपोपरवामयोकठिनः समहा
न गलग्रहो वामस्या वा स्रोषिलायस्य १४
सोहोव वह्नोविधिवर्णो भ्रमनिगोधा घवा
भवेत् श्लेष्मात्तननः तनकासो वा यो
नान्वजेयन्सवीन १५ गले घावालक रता है
और श्लेष्मयुक्त पीले रंगका वमन होता और सब तनेला
लोवगन अरु थोडा लाव और तिसके इंद्रियार वेदहो
न अेमलतणवालेको त्यागे वैद्य १३ जिसको इकेग
लेलकौ गल सुही गल ग्रंथिरोकलेवे अथवाकोटने
योंमा गलरोकलेवे और वहुतगलरोकलेवे अथवा
मस्सा गलना ग्रंथि पीडायुक्त होवे १४ और बनानेवहत
रंगावाला औषधिवाला भ्रमणाव होवे अरु चापकरके
रोग और तनका सक्तका शरीर होवे तिसको पकेको
तालवणा तिनो समभनौको वाद्यिमान त्यागे १५ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा०
हो०
२७३
273

योघोडछीणनिर्बललिसाहैजिसको लालरंगकाशो
थाहोवे फरपीक्केनेमूत्रविकारहोवे पहिलेलक्षणसव
असाध्यकेहैंहेन १६ योघोडावडावेलकर औरजिस
केवक्षस्थललेवकेघजावे अरुलिंगकोवहूतलेवक
नावे औरघोडावारंवार अपनेआपकोदेखे सोमर
जाताहै १७ येसर्वविषेअयाहैकाहिरकीया अरुत्रय
प्रकारकेश्वासःकहेहेन अरुजिन्होकी ग्रीवाकाडी

क्षीणस्ययस्यशोथःप्रजायतेरुणास्या
स्वस्य पश्चान्मूत्रविकारोत्रयाणेवताम
साध्यानी १६ गुरुवेगोयस्तुरगःप्रलेव
वलोयलेवनोमेढ्ं भूयोभूयःस्वमात्मा
नेवीक्षतेसीयतेवाजी १७ याःप्रवेनि
र्दिष्ठाहिक्काक्तिसृनस्तथात्रयःश्वासाः
वर्ज्याहयणाशस्तेनर्भमग्रीवाश्चयेवरु
याः १८ यस्मिन्कर्मिन्नानेव्रणेनरंग
स्यघ्राणस्त्राणपाति अभिभूतेव्रणरोगेः
णवर्जयेतभिषकुप्राज्ञः १६ वक्ष्यामिश्री
घ्रंकेनकामनोपानिर्दुर्मना दृष्टाने
कुशलोवैद्यानापमत्तोनिर्तिर्दिशेन २०
यस्यतुरंगस्यभवेद्दुष्टोमनोहत्यणका
नथाश्वासः

भजजावे इतनेघोरे केश्वासकेजन
णवेल योने त्यागनेयोग्यकहैहेन १८ जिसकिसत्रु
णव्रणविषे घोडेके शोजहोजावे योव्रणरोगकरके
विमनव्याकुलहोवे जिसको वानुरवेद्यवैनेत्यागे १६
योघोडाबलमा क्रानी शावकरकेयुक्तहोवे अरु
हेगरा वक्रतुरगकोहोवे विमनहोवे इसका इस्वके
वनरवेद्य परेक्षकहर्दैसे पहेनहिदेवेगा २० जिसको
रेकेहोताघकरनावेल्मारवातिहोवे अरुश्वासरूप

© Dharmartha Trust J&K. Digitized by eGangotri

होव पसाव बहुत आवे और मूत्रविकार होवे ऐसे घो
ड़ेकों बुद्धिमान् चिकित्सा न करे २१ जिस घोड़े के बा
हू मुंडों के मध्य बहुत करड़ी होणी शोजा होवे अ
रु घास अरु सो होणी तै रसबेग चिरकाल ऐसे इस
रोग करि घोड़ा मुक्त नहि होता मरता है २२ जिस घो
ड़े की मेंढ्र की सेवकान लम्बनी रोगविषें तिस आव
का रसबेग दाय है गिला अरु छुटा दारु बवधनान

सेरस्य मूत्ररोगश्च वर्जयेत्तं भिषग्वरा तिस
न् २१ बाहोर्मध्ये कठिना शोथो विद्यते य
स्य ह्येणाकाश्च स से क्लिश्यते च सुचिरे
ण स रोगान्मुच्यते वाजी २२ जीर्णायो
मेढ्काणि सेसावानत्ते भवेयस्य क्लि
न्न शुक्लिन स्रवत्तु रोगो विवर्जयेत्मनेन प्रातः २३
यनेत्यामाद्य त्रूपा स्तरंगाणामायथः
समुद्दिष्टा सुस्पान्तापरैरिहैन तद्दिा
नीमेप्रवक्ष्यामि २४ इति षुनराख्यानी
योनामध्यायः अथाशिनेत्पाक स्मा
होन वलोद्रमेनाम भवेयस्य विकलस
रोविवर्सेवाजी त्याग्निना पुरितम्नकः १

है तिसकों चतुर वैद्य वर्जे ३ पाप नाकरे ५ इतने अ
साध्य रोग घोरयांको कहे हैं न अरु साध्याना सब घुके
घोड़यांके अरिष्ट उपद्रव व्याधिमारणे वालि अ
व कहते हैं इति प्रसाध्याख्यानी मवावदे ३ पाव करणा
ध्यायः जिस घोड़े कों रोग कोइ नहि है अरु अकस्मा
त निठेल होजावे अरु विमन होवे सार विकल
होवे वर्ण तिसका विवर्ण होवे पहेल दाणा जिस
के होमो घोड़ा अपचारी कहना कहे यां है १

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा
हो
२०४
274

शीलभ्राहार घोसदावाणेवाले भोजनन्प्रस्मान्माये
देहकोंस्रवटेणेवाले इनोंविषैविपर्यय इच्छानाके
ग्ररुश्रीरकुछ्रवीखाणपानननहिंग्रहणवरे सोघोडा
सनावीनाशहोताहै २ जिसघोडेकोंप्रपाविषैया
देहोयें घोडेकीछायापरामृखीउलटीहोवे ग्रथ
वाविकृतहोवे ग्रथवाछिन्नकटीहोइहोवेसोम
रनानाहैघोडा ३ जिसघोडेकेमस्तक ग्रोर इबके

शीलेघाहारोरुस्मान्मेघुविपर्ययोमवेय
स्य ग्रादेनेनचाकिंचिन् हिंयविनश्य
तिवसोवाजी २ यस्मान्पगयानस
वानिनःस्यानपराङ्मुखीछाया दि
गुणायमवेच्छिमावासोम्रियनाश्वः ३
यस्यललाटेपुच्छेपप पुःसमज्ञायते
नेरगमस्यघ्यानिवयःहविरेसाम्रियगा
माशुःसमाप्यानः ४ यस्यानपोविष्
टेच्छायानदिदृश्यतेनरंगमस्य ग्रप
शाकुनमलवनेसोम्रियनाशुःसमाप्यानः
नेलाकाख्येकेशगाद्दृश्यंतेवैसमंततोय
स्य सेमातीशावशीर्येनेसोम्रियज्ञोवम
समहे ६

विषैसोजाहोवे ग्रहरुप्रापरादसहोवेविरकाल सो
घोडागजापु ग्रापुणारहितेनकरहपाहै ४ जिसघोडे
कीछायानिर्मलप्रणविषै नहिंलवे ग्रकलिट जिसकी
मेलकेउपरनारे सोघोडावीग्रापुरहितकरहयाहै ५
जिसघोडेकेकेशालोवाल मेलकरकेमिलेहोय की
घार ववरवनेलवता ग्रकरोम स्ट्स्सवाल जिसके
उडेंपोणसोमनदिनाविषैघोडानाहिंजीवा ६

© Dharmartha Trust J&K. Digitized by eGangotri

पोकोज्ञास्थिता होगा दाप से कर के सिज जानाहै ७ अ
कमेद लिंग को उद्यत करे अरु सिह कीन नाचे टनाहै
सो चोउ गम वे स्थान को जानाहै ७ जिस चोउ के का ब
स्ति मूशा पतु लना वे अरु शर आकरा होवे सो मर
जानाहै जिस चोउ के गेठ नाल नो भस्या मध्ये काल
होन अरु विमन चिव होवे सो चोउ शवो नहि जीवता
जिस चोउ के स्तान करे होप कौ मूर्वे कोइ दपवद ८

यत्स्यार्वेनं मानः प्रासि मोमेष्ट न्मपन
येवाजो भ्रमहेलवडपावेशनिमेनावा
नेसपान्मः ७ यत्स्ताविमन्को वानिधं
यम्प्राथ्यानिजीवतिन सोसूसः स्याबो
ष्ठनालनिद्धो विमनयः सोपिनवाजो
जीवति ८ स्तानस्यपस्य मूर्वे क्रोड्वाला
विसृष्टनेष्वस्य मासेन तस्य मरणं भवे
त् दिशेत्तुहेमानवेयः ९ यस्यचरमे
पिमेनामामेद्रालिंगाग्रेभिसृंगपतन् ते
रगस्य संप्रवर्तेनवर्जयेत्तेभिषकमः
तिमान् १० मूलादरग्रहमेदेष्णस्तावते
भ्रवक्मद्योच यशविभ्रमेनरंगःप्रम्ता
त्येपोमहानिभिः ११

केमध्यस्थान नासा
पहलेमुकजांन जिसका मरणामहोनेविषेवुद्धि
मान वेद्यकहेदेवे ९ जिसचोडेकेनासालिंगअदि
गुदाइनोविषे इकटाहि करियापिनप्रवर्तनहोवे जिस
चोडेको वउर वेद्य वैसेहि किन्मानाकरे १० जिसचोडे
केमूलहोवे दरदेवेयनावेपोजहोवे गुदालिंगविषे
इसहोवे वटपोवे पछावलाले रंगका होवे इसका
विगुरिनामहै इसगुरूपोचोडाहै जिसके यत्नकोड

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
टी॰
२७५

दिवेंनेंनेंनवावदेरोगयोग्याहै ११ जिसकोउ॰कोम
लिहोपकाघोकोंग्राग्मूत्र वारंवारवारप्रवर्तनेनका
हिरणविरणविषे ग्रावे वलदेहोपका वेटेकावाम
नेहोपका १२ याउ॰पकरकेमटलिंगकोंनिका
लताहै अथवा पनला मूत्रमनलकेसमफेन वा
लापच्छावहोताहै ग्रोरम्भास मेदाग्निहोवे तिसका
उपायनाकरे वैद्य १२ योउुधाकेरतनेरोगग्रसाध्य

मूत्रस्यवेगानेहस्मस्तूमवर्तनेनेभी हुण
बुनताघोने छलोवास्वपलोयमवाष्प
स १२ कोपामिरस्यमेफेनयवानन्तु
लोयवनस्मफेनेस्मात्र भाष्योमन्दाग्नि
नेपतिकमेनकाभयतस्य १२ इतिना
निवरेगाणामविशेषानिसमासतः आ
रोगाणांयघोक्तानिवांधिनानोचवा
जितो १४ शास्त्रस्यग्रहणंकृत्वाशा
स्त्रग्रहणंकुरुन्शास्त्रार्थग्रहणंकृत्वाहम्
कर्मानतोभव १५ यत्नकेवलशास्त्रवाद
छकर्माणिकुवले प्रवर्तनेचिकित्सायांकृ
कुभौनरकाचिना १६ अशिष्टानामनायुधा
णांनेनोवियामकाशयेन् नेयमारद्या
नेभवपावोमयस्यकदाचन: १७ मारणेवालेमं

तेपकरकेकहेन योनिरोगपद्योरोगवालेपोहेनतिना
केकहेन १४ मर्वेशास्त्रकापढेकेरपाशास्त्रकाग्रर्थहेजि
सकोनिश्चयकरे फेरशास्त्रकोनागालेहछकमोटसक
रकेयोकापेरनाहै सोकरीवालाहोवे १५ ग्रकपाकेव
लशास्त्रकोनारागा ग्रथवाकेवलुहछकमांहोवेसोचि
किस्ताकरणसाहूवेन रकेभागिहोनेहैन १६ पांचहने
हिग्रकरणंहनग्रेसेछकणाकोपढेहविद्यानापहावेग्राजि
सकोग्रायानाहोवेग्रहपापिहेनतिनांकोंकदेवीनामके
शाकर १७

ऐसे पुरुषके नाई भ्रनाशैववाला होवे जिनंको वीनाहे
वे तिसकारणतें यो विद्याकाअर्थि होव गुणकेजाणने
वाला होवे चतुर होवे ऐसेकों पढें विद्यावज्ञाव ॥१८॥ प
ढेंवि किन्साकिते यनटेहिहें किनेमिश्रीवाणानेहें
किनेकपर्मकिनेपशुः किने अपणेविद्याकाअभ्या
सहोनाहै पढेंवि किन्साकिनेमेवेनिस्फलनहिहे ॥१९॥
इति पदेअरोगरेष्टमारकरोगकाध्यायः अशोगरि

नष्टयायनवभ्रातेनवाभुसुषवेनया न
स्मारण्याद्धयार्थिमोत्रणावज्ञोविवव
र्णा ॥ क्वचिदर्थं क्वचिन्मित्रं क्वचिद्धर्मः
क्वचिद्यशः क्वचिदभ्यासयोगमिनेवि
किन्साहृथाभवेत् ॥१९॥ इति आरोगारि
ष्टनामाध्यायः अरोगारिष्टमिमस्कं
सोपसर्गिकमध्यने देशोसमिभ्यंदेघ
दानरोगाश्चवायमार्जेवा २० यापिस्रा
येद्रेसौशासह्निपिहेनयास्मापवा
आसाद्विषदिरधेयवमेवाल्लमद्य
विषवेन २१ आविनमध्यायानोयोपिवे
तिवेकालइहेवा ३ः स्यानसौनिरोष्या
नोद्वेष्यारवानेयानिरोधाहा २२

एकदेशपाद्दे युवउपमकेगंककहनेहो योदेशअभि
ष्यंदनलकेश्रवणवालाहै जिसकेविषेबाहनका
वलाईदेहेन अथवा योरोगप्रायदेशाहैन। यस्यानुशा यो रुद्वदेशहैनः
सकरकेमनकरेहै न अथवावाहूनमेदेशहैनिहो
विषेस्थितहोणाकरके अरुयोविषके शुक्लग्रास
देनेनिनांदरवोणनें। ओ यूविवरहिरपयाणीपीनेनें
अथवाभोजनविषवालाकेरणाकरके अथवाविर

© Dharmartha Trust J&K. Digitized by eGangotri

भा
ख
२२६
226

हीनपोकालसरनोविपर्यकाललपाननें ग्रोर माहेषा
नविषेशकरपागाकरके ग्रोरवडेगरीदकेविषे
ग्ररुबहुतमुपाविषेस्थितकरणेने २२ गर्भधुपाविषे
मार्गविषे मलापहापाको ग्रोरभुखकरेईसिघपहेन
ग्ररूतित्रिष्यथयोकेविषेरवेदरहनेवालेको ग्रोर
ग्रकालविषे ग्ररुकालसमयविषे युक्तिविनाहेहूपा
नकरापहेपाको ग्रोरपसमस्तविनौकेपासरवोटवा

ऽस्माणोपात्यि पुभ्कानां तुभवत्रपावाधिपी
डितानावा रुतपामस्यथमानिहनोवे
नयाकाले २३ कालेबाल्यगणागमाया
पुमाल्लिमामानानो सखेवांहेनाना
मनगानेचाप्यतीतकालेवा २४ सस्वा
निवादतोवापसवि– मवीयोणिता
पसहापास्पानो नस्तेपीडितेन धा
मत: २५ यातिमाहतनादतिवधोदस्यु
पणाक्षीनलाहानि नीहारस्पवयनना
रिधुरवाजिनानपीडितावेष २६ अस्ते
नरेनाधमनाहै पैवांपानरकानां ॥

महामोटइत्यादिककालसमयकेविषेनहिदेयेजि
नाको ग्रथवाकालकुदीनदेरवाणेवालेपाको ग्र
थवा पथायपयानविषे म्यानेनजिनाकोरवणवाले
को ग्ररुपावोयपराक्रमेरहितयाहूनुनिनाहे रवाणेवा
लेको ग्ररुयनसगलिप्रिया म्यागीपानजिनाविषेला
नुकरेहेन ग्ररुनतेपाकरकेपीडितग्ररुपेनासोक
केयक्करेन पोरबहुतनषा ग्ररुवायुकरके ग्ररुवहु
तगम ग्ररुटेकरके ग्ररुबहुतबर्फपातने ग्ररुवार
ग्रोरमाघकरके पीडितहोनेते २५ ग्ररुबहुतभुके
हहोनेथकल्हाणेते ग्ररुदंशोकरके मनरइत्यादि

© Dharmartha Trust J&K. Digitized by eGangotri

छुड़णो करके और रक्तपित्त के कोपने अरु बहुत कु
ष्ठि करणे ने वर्णाश्रन विषेयो बाहर उत्थान वि
षेशोन करणे वाले यांकों २० अरु वैद्य के नहि आम
होने ने और पथ्य औषधी के न देने करणे ने
अरु पेरक करके इस्विन होय ले वानेनांको अथवा रु
धिर नाहे निकसने ने वा बहुत रुधिर निकलने क
रके २१ अथवा बहुत रक्त वाले का थोडा लहूके

अन्यथैव्यापामात्रदोषास्राकाशशस्त्रापि
नावापि २२ वैद्यालाभाद्ब्रनथायानिक
र्मणोः प्रयोगेन अभिभूतानां रक्तेन
निस्सतो शोणितेन चान्यथै २३ अले
वाप्यवसिक्ते रुधिरे बहुशोणितानां चैव
अतिवेदनाद्कालेहीनानां वाभिनां
मर्मयाणां २४ शालेस्वापि विहीनाना
मसंस्कृतेन वा प्रतनां वापि अविधो वहु
नेपद्मानां रहोमृपेस्व थानहीनानां २५
शयश्चितेना नेष्यकृतेः शोस्माद्विभि
वापि यभिनोन्नायकारैः शास्त्रनिषि
द्धेष्वसंविनेवहुभिः २६ नायेनेत्र॰
गणिरुश्यांनिवपावयाययोवोगाः

इणोने अथवा हीण चोटकें बहुत नाडीवेध करणे
ने अथवा राजो चोटका रुधिर मातके ममविनाभजि
रक्ताडणे करके अरु जिनांकों बाहर विषेयो बाये है
न जिनाके नाहे याम होने ने अरु पोसक्कार विधि है
जिस बिना भोजन करणे वाले यांकों अरु विधिरहि
तपत विषे हवन करणे ने अरु येरा बसग्गडकदेन
जिनांकरके यहुत करणे हो वांको २० अरु याशि
नके होये हवि स्थानि नहि करणे करके इत्यादिक

© Dharmartha Trust J&K. Digitized by eGangotri

शा
द्वो
२७७

277

अनेकप्रकारकेपेशावहोनाविवरनेनकमैहैनतिनोंक
रकेअनेकनरोंरेउपसर्गकेरोगबहुरोग होतेहैन
पहेउपसर्गभेगंदरकेहैन वोहुयाकेसोसबप्रकार
णोकेसहितनकहेहैन अब इनोंदोषहैदयोवाडे
याकेलक्षणहोतेहैसोक हतेहें वरश्रौरपिठश्रा
कउमानीहे श्रौरश्रंगकीजउहोतेहैं कहेलालप
क्वावकरदाहे १२ योचवैषवैपीडा अरुश्रेउ १८

पवनोपसर्गदोषःसहेवकःकौर्तित
स्त्वेषागाणा १२ पत्राभपरस्लानोंद्रपा
णपनानिनांपैव सन्मालस्यहोगाः
कदाचिदस्मकशिराः १४ पलपक्षिम
पानेस्वमस्थलस्त्रवणोद्वरः प्रहान्ना
विक्रमीरोनाःकासश्वासनिपीडिताः १४
वेदनानिस्तत्ताहामाःभिमपामाप्र
मेलनाः खादनेपवसेवापिपानिषे
भोजनानिवा पन्नेनाप्युपनीनापैन
नैवाश्रोनिकदाचनकदा चिनेसमन
सःसहितमनमोहया १६ नेपानिम
पिनाचैनियापनैश्वासनिद्दरा ह्याना
मुपसनामेतत्रवनिलक्षणे १७॥

येमपीरहोतिहै अरुखभावनिकूलहोताहै तिसारोना
हे अरुहमसंगकेमाथुउकोहोताहे १५ सोकोरपो
ताकरकेइतिवनहोकेतिसाहोनाहै अरुयोतिश्रसप
नकरकेभरीयोरहितीयोन श्रौरवोपदापणागोभी
मन पचे पवनकारकेदोषहोयन दिखोनेकहेवी १५
सोचारकेदेवोमतिसनोहदेति अरुवहेकहिनश्वास
करके ओति सवनाहितभद्रा उपसर्गपककोउ पाके
पहेलक्षणहोतेहैन तिनोंदासनावीपत्रकरे वन

© Dharmartha Trust J&K. Digitized by eGangotri

रवैय ३९ बाइकौं और देशविषैं लेजावे कौ होरनो
कौनाशकीकरे समागमतें ४० नहांउस स्थानविषैं
लेके चिकित्साकरे येजरनके घाय दाणअहसो
ज्ञानोकौं आवे ४८ अरुपानी खावरणभोजन नहींले
देवे अरु बांबेशोषिकनामशांतिहै सोकरे अरु र
समग्रहोकौं बलिदानकरावे ५० अरु सावधानआ
त्मणेकरके रोगकी शांतिवास्ते शांतिजपादिक

अथास्य घातिकर्माणि कारयेत्सुनिमा
नभिषक् देशमस्यनयेहित्वंसमस्थान
यिवर्जयेत् ४८ नत्रस्थानानिग्रमा
णिकानैषाकारयेन्नक्रियाः यथुनेय
वेसमस्याशिहमेभ्यः प्रदापयेत् ४९
पानीयंलघुदानंस्वादनेभोजना
निच कृषाहशोषिकोशांतिरत्नोऽप्य
थबलिहरेत् ५० आत्मनोः प्रयतेःक
मेकारयेद्याधिशांतये सर्वेचकुर्या
दिनातमस्थानेविवक्तमाः ५१
स्वस्थानेयदचक्रनेषमस्थानेवबा
जिनोनस्वर्वमाद्दितः कर्माणि यथा
दिदकारयेत् ५२ एवंनरोगमाणामप
स्थानामपक्रमः कथितः आरोग्य
स्थाने

रावे अरुसमस्तानके चतुरपंडित अस्था
ने हमारे स्थानविषैंलेवे ५१ और सुन्दर स्थानकर
णेकारण है बाइयोंका योग्यविधि कहिहै सोस
मस्थानसे लेकर रहोनिश्चयमैंकरावे ५२ पहलेरोग
हेउपरस्थके हेनिहांकौंचिकित्सापनकहथा है अ
बनिरोगपवारेका सबस्थानसमासेलेपनेफेरक
हनेहा ५३॥

© Dharmartha Trust J&K. Digitized by eGangotri

तोलि डोलि चलना अरु स्वप्न मन सिर अरु इंद्रियों अ
हंमसिमनने है और रोड़े को देखकर के हिराकदा है
और कंनदोपविसत रवेड़े स्वदा है शिर होलनारोग म
विकने ४४ वायुदोमाड़ यथोके विषेखायलेता है
अतसभ संगसदेहरोगरहित देखिदहेन अरुदेसो
मायशरीरको गुरुकदा है अरु भोजनको प्रसि
महोकेयोपनेवोदा है ४५ मनसिसकामदाहि

सानमाशोगमस्मनमुत्तमं वस्वासिसमास
नःकलसे ४२ लतुचंक्रमनेनस्थैो ह
ह्याचाश्रमदेषनेसमनाः कासोवासे
विनसिलशुषिताः स्मलरोगमव ४४
शूमोवरनिसामश्च रोगस्वापिह ष्व
नेसनने देने वेषनिरानेसनिभेस्या
निभस्यनेप्रीताः ४५ मनसस्याप्यो
हर्षनिमेचेवोपलस्यनेयस्य अप
लायूलेविविपनिरंभनेपोषनेवा
रो ४६ आलिप्यमेवनाशप्लालान्न
प्रवनेनेवदने बलानवयिश्चनोन्न
गानिवत्वसोपहस्मेने ४७ अस्यः स्वा
नि नानिस्वामनिनवसंगुरुः श्रोषनेचास्या
पवनेने ४८॥ हर्षकवेपादानभदा है अरु
देनवोइदस ४४ दोनोवासे बलानाहै इमानोपामा
नाहे अरुफरहकदा है ४५ अरुमुखप्रकारत्यादिक
रके नहिभेरपादा है अरुवलते गाकोमकुमादा है
वनिमेनरहितसेहरेन ४७ अरुस्वपोपनेपन
स्योनाहै ममपोनाहै अरु गुरुश्रालकदा है अरुभ
कगनहिहोना अरुबहनदस लेगनहिहोने देह

हैला शुरू खिलना है ५८ शुक्रवाशुमलम्नउपयार्थ हो
ना है इनोंत रूणांकरके छोड़े निरोगयजानो देहैन ५९
एसन रोगभरोगणेष्ये रहैन छोड़े मनासाके वनरउ रूमा
नाके कार्यविषे यो रैने स वेद शास्त्रविषंकरहैया है ६०
इतियहे सुरोगप अरु उपसर्गोन विहाका ध्यायकहैया
है एवंइसतै परे निसक्रमकरके यह ग्रंथहै मोकह
ना हो स्थान यो है नामसत्रो कोविशेषने करने हो
इसविषे प्रथेलक्षण स्थानेकहैया है तिसके उपर

वातेनसहकेसूत्राणांप्रागुणेलक्ष्येवास्य
प्रथस्थानेनीरोगंनृपैरनेविमानोया
न ५९ एवंनरोगानानारोगाःसर्वेविवर्जि
तेनिपुणाःसानन्कर्माणिप्रयान्जोत
यथागमेषुशास्त्रे ६० इतिश्रीरोगप
लक्षणोपसर्गोनविहोनामाध्यायः
सूत्रःपरेऽथवृत्तानिनेत्रस्थानस्ययथाक्र
मे स्थानानीवैवनामानिसूत्राणांच ६
विशेषतः १ प्रथमेलक्षणस्थानंम
स्मिननेत्रेषुवस्थिप्तं ननोरसश्चाकर
णे कल्पसूत्रेनयेवच २ निदानेचवि
किन्साचरहस्यशादमेवच स्थानानि
षष्ठेनानिमृत्यावध्यायमतःपरं ३
प्रसेशावाजिनामर्वमावर्तोध्यायमेवच

नरमें कानिरूपकपक हैया है फेरकल्पस्थान कहैया है
फेरसूत्रस्थान है तिसके उपरं निदानस्थान तिस
के परे चिकित्सास्थान है फेर रहस्यशालाकरैन यह
षष्ठस्थान कहैन इसके परे ये ध्यायकहैन सो सूत्र ३
शालविषे घोड़ेयोंकी प्रशंसा उपमा का ध्यायकहै
या है फेर घोड़ेयों के भावने वालों के वृक्षों का ध्या
यकहैया है तिसके उपरं नरमअंगों की परिसाक

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
२२८

279

छिद्दे और रलेमिले श्रेष्ठ मध्यमाने कूटलक्षणका
धापकहेयाहे ४ जिसकेपरे वर्णरंगोंके लक्षणका
ध्याय फेरसर गंधवोंरेकाकहेयाहे फेर छाया प्र
माणि सत्वपराक्रम पहकहेहैन मेत्तेनै ५ जिसके
उपरंतमहादोषकहेहैन औरनालकोविधयेरगहेन

सर्वांगानांपरीक्षाचामिष्यकेवाजिलक्ष
णे ४ वर्णलक्षणसर्वांणि सर्वांगंधाव
वानिनो छायागानिप्रमाणानिनिर्दिष्टा
निसमासतः ५ महादोषाश्चलाराणाः
कुलानिचवपलक्षा वर्णगाजेपमाहो
वमेस्मानश्रेष्ठलक्षणे ६ लक्षणस्थान
मेवेतनमध्यमेपरिकीर्तितं ननश्चप्रा
यानिदेशः क्रियासवेतत्थैवच ७ प्राक्षे
पहनेकेदेशाः कल्पनेलवणस्यच
परिवर्त्यानिरंगाणांमस्थानांचविधिस्त
था ८ विनिश्चयोरस्माणांचवसर्वांग्येः
विनिश्चयः गुणदोषाश्चदृश्याणांवा
हनानितथैवच ९ कुशमलविधि
श्चैवसंख्याकरणमेवन कल्पसूत्रेपि
हकल्पस्तथैवकहायिद्विका १० प्रति
पानविधिश्चैवभोजनानांतथैवच
नावनानिचसर्वोषध्यपमनानि
च ११

शाकहेन जिसकेपरे वोरधोंके कुलकहेनफेर अ
वस्था कथनकरीहै जिसकेपरे जिसवर्णकाग.
नाकेबारहन धाम्याहे शाकहैन ६ पहेपसवविधि
लक्षणस्थान कहेयाहे इसके उपरंत आपिके
निरदेशानेक्रियासत्व कहेयाहे ७ ८ ९ १० ११

© Dharmartha Trust J&K. Digitized by eGangotri

फेर पालाकेरचनेकीविधि कहिहै उपरंत घटक
नचर्याविधि कहिहै फेर दशाकोकल्पनापे शोडेपो
कोमहनिघेहैन सोकहेन फेर लूणकीविधिक
हिहै फेर पेणाकारणपूगपलाकहिहै फेर जनतो
होणावालेसम्याखोदमोदइत्यादिनाकीविधि
फेर रसवीर्यकानिश्चय फेर द्रव्योकागुण अरु
योगकहेन फेर पेखादनहैनसोकहेन फेर हद्यौ
शमूलकिविधिफेर रसकाविचारकहेयाहै क
ल्पसूत्रविषे सेहकल्पकेहेयाहै फेर कदुपिंडी
कीविधिहै फेर प्रतिपान अरु मानन कीविधिक

मृत्खपावननस्यंगोलेपनेचोपनाहने
ग्निकर्मक्षारकल्पःसिरावेधविधिस्त
था १२ स्वेदानामाहितोगाहणंकल्पा
चमनदाहतौ हीरबस्तिमबाहाना
मभेगवास्तिरेवच १३ बस्तिनेत्रहक
ल्पश्चकल्पसूत्रेमकोर्तिने वाषोनि
दानमथमेपित्तस्यचकफस्यच १४
रक्तस्यचततंगाणांनिदाने पारकोर्ति
ते वातपित्तकफानांचरक्तस्यचस
मासतः १५ ॥

हिहै फेर नसवार धूमपान
धूपमननसवारभेद इनकी विधिहै मुखधोन मा
लसलेप बंधन अग्निकर्म क्षारकल्प शिरानासीवे
धइनाकीविधिकहिहै १२ सेक अरुअहितोग इनां
काकल्पकहेयाहै फेर तीरवस्ती अरुउत्तरवस्तीचा
हैयांकीकहिहै १३ बस्तिपत्रकाविनिश्चयसिलकल्प
परेकल्पसूत्रविषेकहियाहैन फेर बानकानिदान
अरुपित्तकफका १४ रक्तनिदानचोडेयाकेकहेन
वातपित्तकफरक्तइनांका संक्षेपमेंकहेन १५

© Dharmartha Trust J&K. Digitized by eGangotri

मा
हो
२८०
280

पहेसाधारणचिकित्साकहिहै फेरनिसके उपरंनक
बनो औरमञ्ज्वादिककनाणे और उडेवान और वट
को ग्रहग्रहणतिसारकी चिकित्साकहिहै १६ मूत्ररोग
की चिकित्साकहिहै तंवचिकित्सा पकोगरोगकी
ग्रहमुखरोगकी चिकित्सा १७ कामकी चिकित्साक
हिहै वेहव्याकन लवण धान्यहारावर नल १८ तौउ

साधारणीक्रियाप्रोक्तावन्तोनोचचिकि
त्सितं विवंधस्याउवंनस्य क्रियावतीति
सारिणः १६ चिकित्सामूत्ररोगाणांमृ
नांचचिकित्सितं पकोभगोगस्य नथा
मुखरोगचिकित्सितं १७ कामानांचवि
कित्साचस्वेदस्यलवणास्य च धान्यस्य
वस्रावणास्यहारस्य सलिलस्य च १८ गा
त्रास्यापदंशस्य क्रिमिकोष्ठचिकित्सि
तं विधुरगृहेनरोगाणां हृद्रोगस्य निवा
रणं १९ ग्रंथलिकार्बुदकोष्ठवर्कण
रोगचिकित्सितं मद्यपानचिकित्सा च
वानवालास्यपवन च २० ग्रमेडकलयो
गानस्यशाकस्य रक्तस्य च ग्रहवालचि-
कित्साचापि नस्यचचिकित्सितं रक्तो
दस्यकपोतस्य वछस्य चिकित्सि
तम् २१

रनाकराकि चिका रककेनसन औ
क्रिमिकोठचि विधुरग्रह हृद्रोग निवारणक
कवेन १९ ग्रंथलिकालीन काष्ठहिहै ग्रहक
रोग मद्यपानवानवलास २० ग्रमेडकचि उमीन
शाकरक्त ग्रहवाल स्नाकीचि पिनचि औररक्तो
द कपोत वछोउ रनकी चिकित्साकहिहै २१

© Dharmartha Trust J&K. Digitized by eGangotri

पैछे प्रकारका अर्शीनिनांकीचि अरु कालाटकीचि
किन्सा अरु छप्रकारके उदरोंकि अनुकंटवि फेरराज
यक्ष्मावि कहिहै बालकवि फेरगोविन्दनवि झूणोंचि·
यालेकिवि मदमन्नवि देशावि पैविकनवकदोष
स्वपथु झोणोंका कष्छप रहीकोचि २४ और गलकोहि
गोहिदकी स्वास अतिसार कोटरोग शालिविरोग
लिलिनरोग २५ पादरोगवि फेर प्रक्रेचवि प्रकोट

अर्शोसांच छप्रकाराणां बालादस्यविकि
त्सिते उदराणां च याक्ष्मानां प्रस्कंदस्यावि
कित्सिते २२ अनुकंदचिकित्सा च राज
यक्ष्मचिकित्सिते बालकस्यचिकित्सा
वगोविन्दनचिकित्सिते २३ झूणशाल्य
कितोस्याप्रिमदमन्नचिकित्सिते देश
पैतिकनवदोषाःस्वपथुझोणाकच्छपाः २४
गलवन्हा रोगाणां काहिक्का स्वास एव च
वाजिनां अतिसाराः कोटराजीशिरो
रोगस्यलिलिने २५ पादरोगस्य वाहानां
प्रक्रेचचप्रकोटस्यो उल्कपादस्यानक
कगदाभ्रेपोसनेवच २६ भाराभिघरा
णादोषास्यपाकाभिघातनयवच अभि
नापरक्तपित्तेविषुनाडिमसनेवच २७

वि कहीहै उल्कपादकहेपाहै स्यानककहे
पाहे फेरगदाभ्रेपावि· अरु भाराभिघराण कि
चिकित्सा पोकाभिघातकहेपाहै लिसकेउपरं
न अभितापकहेपाहै और रक्तपित्तवि विषु
नाडिसवि २७॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा
ह्रे
२८१
281

अभिष्यन्दवि नतेकीवि सिंहाणकवि अभ्यावारक
वि अर्जुनमवि पर्वणीवि अर्बुद कावि चिकित्साक
हिहै २८ तिसकेउपरान्तपटल परिस्रावः अम्लाध्य
षितका और नासापुटकी नेत्राभिष्यन्द अल्पसूत्र नाल
पर्यन्त नेत्ररोगकहेहैंन २९ कर होनेरोगचिकित्साक
हिहै नाड़ीवि होयपुंडरीकयहकहेयाहै फेरअर्बुद
शल्यतान अनष्टशल्यतान ३० अथोभग्नलग्नाश्चवि

अभिष्यन्दचिकित्सा च नराणां चचिकित्
ने सिरजालकचिकित्सा च प्रावारकवि
किन्सके अर्जुनमर्मणथाक्षेपाऽर्बुदः
कावपवव २८ पटलस्यपरिस्रावः अम्ला
ध्युषितवामिना नासापोतोनिपन्नो ने
त्राभिष्यन्दपवव मनस्रसेनजालस्यनेत्ररो
गाःप्रकोर्तिताः २९ जोव्रणोपसनाडीव
पुंडरीकयहस्तथा अर्बुदशल्यविज्ञाने
नष्टशल्येनष्टवव ३० भग्नलग्नास्था
नोभग्नवचिकित्सितं विषनेत्रचवा
ह्यानांनष्टवचरसायन ३१ वाजीकर
णानेत्रवग्रहाश्चवेकविंशतिः पनेचि
किन्सितस्थानेरहस्यमभुनामरणं ३२
प्रमासाख्यानोपनामावश्चारोगाविष्टमेवव
उकुंभस्त्रीपस्त्रामासमग्रहस्येनकः ३३
किन्साकहिहै फेरअंगोरेपोका विषनेत्रकहेयाहै
तिसकेउपरान्तरसायन कहेयाहै अंगेवाजीकरणनेत्र
कहेयाहै अहरकोनराकेग्रहरोगकहेहैन यहचिकित्सा
स्थानकहेयाहै इसकेअगेके अंगेरहस्य अब नसमण
३२ प्रमासाख्यानोपरोग नाम कहेन अंगेप्रोगाविष्ट
कहेन अकुंभीसनाउपकुंभनाम ३३॥

© Dharmartha Trust J&K. Digitized by eGangotri

शास्त्रमेंगूढनामपढे रहस्यस्थानपैमोकहेपाहै पढे
छेप्रसिद्धस्थानइसतेरकेनिरूपकरैहैन शरहस्यके
उपरेन समममउमेरस्थान कहेगामैं २४ इतिवैपारि
हूनामाध्याय: अबफेरशालिहोत्रकौं वडीवुद्धिवाले
कोसुश्रुत पूछनाभयाहेभगवन् वडेऐश्वर्यवाले
तुमीकेसेहो संपूर्णधर्मकेजानणेवालेहो अरूसब
शास्त्रकेजाणनेवालेहो प्रसंनाकरके १ हेभगवन्

रहस्यस्थानमेवैतत्पृष्ठेवपारकीर्ति
ते एवंषद्वस्थानानितेजस्यस्यविदि
स्यु: उत्तरेषममेस्थानेसेप्रवस्याम्यत:
परं २४ इतिवैपारिहूनामाध्याय:
शालिहोत्रंमहाप्राज्ञंसुश्रुत: परिपृच्छ
ति भगवन्सर्वधर्मज्ञसर्वशास्त्रस्य
पारग: १ कथंवैय: समुत्पन्न: किंतदै
वस्यलक्षणं मेजमेचकथंतस्यकथ
यस्वप्रसीदत: २ एवंमतिमताश्रेष्ठ:
शालिहोत्रोभ्यभाषत सुश्रुतश्रूयतांसम्य
ग्रहस्यवाजिनस्यकोपतं ३ अश्विनकार्तिके
मासेग्राषाढेवनयाश्रम: ऊरूतैसंपीवस
वेवमालेवेमाकतोवेहूत ४ पहेवेषपोहै

सोकवकेसेउत्पन्नहोयाहै अरूतिसकालक्षणक्या
है अरूतिसकोउषधीक्याहै केसेकरणी पहेसमम
रेकोंप्रसिनहोकेकहो २ ऐसेंवुद्धिवान सुश्रुनकरके
पूछ्याहोयाशालिहोत्रनिसप्रतिकहताभया हेसुश्रु
तअश्विनपोषेमें कहताहोसोतुंसुण याचस्थराजीवाजे
कोतिसकेकोपहोताहै ३ अश्विनमहीनेमा कार्ति
काषेषे अथवाआषाढविषे वाअतकोमेपीविघेवा
वसेनमें वाउमाहैनविषके मिलेपादावगताहै ४

© Dharmartha Trust J&K. Digitized by eGangotri

सो वायु जिस देश विषै ग्राम में नगर विषै अरु जिनां जि
नां स्थानां कों स्पर्श करता है जिनां के विषै गौआं अरु
मनुष्य हाथी इनां कों पहे रोग उत्पन्न होता है ५ मनु
ष्यां कों राजयक्ष्म अरु गौआं कों मानाम होता है अरु
हाथीयां कों पाकल नाम व्याधि अरु घोड़ेयां कों सर्व
नाम करके कहेया है ६ ऊंटां कों अलर्क नाम है
अरु बकरीयां कों प्रलापक है अरु खोतेयां कों खारक

यो ऽसमनसो मंडले देशे ग्रामे च नगरेऽपि वा
यान् संस्पृश्य स्पृश्यसौ वायुर्गोमनुष्यांश्च
कुंजरान् ५ राजयक्ष्मा मनुष्याणां
भवति गोषु वै गजेषु पाकलो विद्यात्
हयानां सर्वं ऽध्माने ६ उष्ट्रेष्वलर्कः
प्रोक्तः अजाखुगलेषु प्रलापकः खरेषु ७
तारको नेयो मार्जारेषु हृद्रकः मृग
गां मृगेणयक्ष्म अवपानं पन्नगेषु श्वा
स्वपिषु श्लोकः अलर्थो मूलकेषु वै ८
मत्स्येषु हि रमदः प्रोक्तः ग्रीष्मकोपिव
गुल्मेषु ज्योतिषा मेषघपि वोपिविष
स्थानलनोचनत ९ सोऽसौ पवेनः प्रो
क्तः पाकेषु वमधुरकः

नाम है मेंडेकों हरिद्रक नाम करके है अरु मृगां कों म
गोग्राण प्रगट करेया है अरु पंखीयां कों अवपान ना
म है अरु सगीस्प सर्पां को उत्सोक नाम है अरु कने
कों गुल्मय नाम है अरु मछां को इंदमद नाम है अरु
मृगां कों ग्रीष्मक नाम है अरु शोरबीयों में ज्योति
ष नाम है अरु कमलनीयों में विचन नाम रोग क
हेया है ९ सो अनें विषै पवेन नाम कहेया है अरु
शाकां विषै मधुरक नाम है सपवी विषै उपर नामक

© Dharmartha Trust J&K. Digitized by eGangotri

लर है अरु नल विषै नील कनामक है याहै १० जिसके
है पैने चोड़े कों पोलसण होना तिसका स्नान करना है
सो है सघन नु स्नान यथार्थ ने मस्तीया वहूतीया होए
अरु त्रिकसैपि फोलो होनाते है जैसे कमारे है पको
न्याई ११ अरु स्पर्श के नेनकों सहन नहि सकदा अरु छा
याकों चाहता है अमैरु मुख नीचा करता है तिसा होता
ता है निबल होता है अरु पतिव डीया विस्तार वाली
योगुल जानीया है १२ अरु मललिद आम अरु लडु

भ्राम्यामत्र चरकोज्ञेयो भवेमीरेषुनीलि
का १० नस्याज्ज्ञाते घवस्यामि पूर्णाग्रुत
तः स्पर्शेन: मार्तिकाम्नापिनीयते त्रिक
सेपि विमत्युते ११ ते मेन सहते सौरेछा
याचैवाभिवांछति अधोमुखः कृशो
दीनविनाननयनस्त्यथा १२ आमहते
मरकंवग्रोषमभिसार्ध्यते कदाचिद्
मेनावाज्जोकदाचित् सृमनातुनः १३
कदाचिद् रोगो मानि रोगहृदिंनदा
दिशेन् यदानभेदे मनतिनराद्दोणः
प्रजायते १४ अतः सकल्याकल्पमान्
सृमनाश्मेनाभवेत् यःस्त्यः श्वसवों
गमत्वराचेश्नेहृदः १५

के साथ करता है अरु चौडाकटे ग्रसि अमन गुरू होता है
कबीविमन होता है १३ कबीपद व कृन्लंबेदाहै नदरो
गकों वजिकों प्राप्त होता है अरु यदराज्ञाणकों छोडदे
ता है नर सीएमांदा होजाता है १४ अतः इसकारण
करके समर्था वाला होए करते अरु असमर्थ हो
एकरके वोगासमन अरु नुमन होता है यामो जा
जिसकोश्रपिट अकशगाइ है अरु समर्थ प्रयासके ग
कोई ताम अरु नरके साथ इसके छाकरके अफ्रोनाहै १५

© Dharmartha Trust J&K. Digitized by eGangotri

शा
टी
२८३ कवीवोडारुधिरकामूत्रकरनाहै अरुकवीसको
हीइलिद्करणेवालाहै अरुसंवसकेदेखरुसोजे
करयुक्तहै अरुजटरविषेद्रोणिकापट्टीहोतीहै
अरुवासकोविनहीखोटा अरुविमनवोडाविलद
है पहेलेलक्षणसभतिसकेकहेहैन १० पहेसमलल
णयथायोगकहेहैन अववीषपकहतेहै तिस
कोनेलपिलावे अरुमालसकरावे अरुवोडपेला

कदाचिद्रक्तमन्नेष्यानयाम्भक्षपुरीष
वान् पादाम्सकावसयेनेनदेहशो
कम्भवेम् एवमेचनवांदनेडमेनाः
श्वाविवृनेने पनबलहाणायसमवे
नबविनिर्दिशेन् सर्वमेनेनव्याखो
नमलोवसाभिमेषजे मेलपानेनः
ष्याभ्यंगाहूनपानेनन्थेवच मघोविवेत्
माहाविपूर्वकाले नपत्रमघंवलनत्र
वेपः ननापमेकार्निकमुक्कपवे टाहे
वकोस्माबरडीनिवारः पिबेशयमान
निर्यासं श्रवहवगेनस्थेवव हेसारीक
इकाबोयालवगागामपिप्पली त्रि
कटत्रिफलावेवत्रिजातेहिंगरेवव
रीयंनेनस्यकापार्गिवेपवेवोपशाम्यति

वे पवमाविट नर्षाक्रनेविषेहोवेनो मदिरापिलावे पे
करमदिरानाहोवेनोनवनिसपकरके नाडीवेपक
रावे अरुसोपदकनोकेमुत्तपहोविषेहोवेनोदाहके
समचार वहन इसकरकेहरणेवालाहोनाहै १९
तिसको टालीका गुंदवासार अरुग्रहवर्ग काको
लि लीरकाकोली जीवक ऋषभ ऋद्धिवृद्धि मेदामह

मेदा स्रवतहोतार सलीतार कौडवचे लूणपंन गज
पिप्पल मचोमपेवगुड हरीड वहेडे आमले लावीपा
दालचीनी तजपत्र हिंङ पहेडेटुकोअग्निकोसम
करहै सरुवेयवी समकरहै जिससोडेकावतण
घोडेकेपासकास्थान उडेहोण सरुसमदेहआकर
नावे स्वास मेदाग्नि मधुवगन सरुडगंधआवे म
लीपोवहुत करके गुरू सरु आफणहोवेनो घोडा

उन्नेरमवत्रणः स्तब्धः स्वामी मेदाग्नि
रक्तवान् इत्येषां मलिकाकोनाख्या
योवास्योनजीवनी २२ जीवतिनर
गोमासेवलीपतेन्नजोव्रणि सोवीस
वक्षरेवापिनचरोगानत्यमयाने २३
युतः स्रेलपुतः प्राहुस्तेशायोयसमाग
तः नेत्रवत्मेपटोलपाकिमस्येमवलो
कयेने २४ कनिकारिष्टरूपाणिविद्
कोकूनिपामवेन नेत्रदृष्टिगनेदोषेः
केतिरेलेलयोननन २५ पवेष्टहोम
हाचार्यैः शिलिहोत्रप्रभाख्याने सुदेश
नयदेयुत्रयसत्नेनमयाणबुधे २६

नहिजीवता २२ येकरयोडावल करके युक्त होवेनो मही
नामर सथवापतपंद्रांदिनजीवनाहै वावसभर वी
जीवे नहवी रोगनेनहिछुटदा २३ फेर शालिहोत्रको
सम्मतकहनाहै हेउरोमेरको परहसंशयहोयाहै का
नेत्रकेपवनको अग्निकाउपरकास्यामतिसकापुटअग्नि
नोलकिसवालिद्रतेनेहै २४ कितनेक अरिष्टरूपमारणे
वाले स्वरूढिडकाकिननेनगोकेदेन स्वरुनेत्र दृष्टिगन
यामदोषदेरोगकिजोलवणाकरके यामिदेहणमो २५

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
२२४
284

ऐसे समुत करके पुछे हो यं शालिहोत्र महाचार्य कहता
भया ऐसे समझ लक्षण आठ है पुत्र मेरे तेलक्षण २६ वा नने
टष्टिरुक्त अरु श्वेत होती है अरु पित्त में पीली अरु लाल
होती है कफ करके चिटी अरु जल करके गिली भरी हो
ई होती है अरु जरके आगम विषे पीले रंग करके युक्त हो
ती है २७ जिस घोडे के नेत्र अखि के वक्र कार वहने रंग की
धारा विंदु लक्षण सो घोडा छे महीने के बीच अवधि मरन
को प्राप्त होता है २८ अरु जो घोडे के वी अखि के मध्य
विषे रवन गेरु की भाई छपता न वो रेकी पा अरु सग
न वा तिसकी मरन दो महीने के विषे कहि है २९ घोडे
ष्टिकलासिता वा नाता पित्तान् पीता रुण
प्रभा कफात् श्वेतानला हो च पीता श्याव
तगामे २७ नेत्रेत्वे दशपने यस्या विंदुका व
ह्रूपा तथा मृत्युमासे न्यसे वा नो षं मासाभ्य
तेरभुवं २८ यस्य स्यापि हि नेत्रेने यदा ली
नेव वाजिनः गंधी नमरणो तो ह्यानदा
मृत्युर्हि मासिका २९ पिगरके पङ्कहे घोर
के मध्यमंवाते नेत्रेने पोडरेवं वस्यो
मृत्युमवाप्नुयात् ३० नीलपीने च नेत्रेने
स्याता वाजिसमागमे सोपि निर्वाणमा.
मोति त्रिभिर्मासैर्नसंशयः ३१ यस्य नेत्रो
नेर ख्याव हृदर्शनापने ॥
हापिगरके के रहे है पडे तहके रंग के अघुधा नमागदाहै
अरु आखि को ण पीन वेन पांडर वर्ण होए न वसो घोडा स
ताबी मर जाता है ३० जिस घोडे के नेत्र दुसरे घोडे के मिले
हाए नीले अरु पीले आखि कोण हाए सो घोडा बीच
महीने के बीच मरता है निश्चकरके ३१ जिस घोडे के ने
त्रो के वक्रकार वहनेरंगो कीधारा दो होए विशेष क
रके शारद ऋतु में तिसकी चार महीने प्राप्त काकहते वे १२

जिसके दोनो अखियों विषे सवर्णकी न्याई प्रकाशमान हो
वे तद्वो दशमहीने के उपरांत मरजाता है ३३ यो चोड़ावाग्र
करके पीड़त है अरु नेत्र जिसके नील वर्ण होए तद्वोड़
ढ़ महीन वीचड़े जल करके जीवता है ३४ अरु यो पिसके
रके पीड़त चोड़के नेत्र हरदल देरंग के सम प्रभावर्ण होन
तिसकी आयुम नीयों ने सात महीने की है ३५ जिसघोड़े
के नेत्र अन्तकी संयोग विषे बहुत वर्णके होन तस्य तिसकी

विशेषानुपादिनस्य चान्तर्मासायुमादिसेत् ३२
येषां सुवर्णावर्ण स्यनेत्राभ्यांसंप्रकाशते दश
मासे सममासायुपितानोपिषिविनश्यति ३३
यस्य नील विभेनेत्रे स्यातां वाजादिनस्य च मा
सत्रयंस कृच्छ्रेण जीवेध्याद्देनरंगमः ३४
यस्य नेत्रे हरिद्राभ स्यातां यपिमाह्रदिनस्यतन् न
स्यायुस्सप्तमासास्यामन्निभिः परिकीर्तिते ३५
बहुवर्णौ यदा नेत्रे स्यातां अन्तसमागमे तस्य
वस्यभवेन्मृत्युः सप्तरात्रान्नसंशयः ३६ य
स्यैकलोचने नीलं द्वितीयं रक्तसन्निभे घुटो
नैस्तवविन्नेयो येषामासामनो वइक ३७
यस्यापि नसमसमस्यकालिमा व शाबाल्लिनी ना
नीयान्नीविनेनस्य दिनादैदसर्पचक ३८
नासाविकट निद्रालुः प्रसार्यास्य घ्नस्तलहस्य
न् आनेरक्तप्रभो वाभो निश्चेष्टः वथवाश्वनः ३९

मरजाता दिन पिषें निश्चय होता है ३६ जिस घोड़े की अखि
यक नील वर्णकी होवे दूसरी रुधिर के सम वर्णकी होवे
घुटकोनके परयत सात महीने पंचवेद ह्यारता है ३७ जिस
के पिसन्त बंधपादा होवे अरु कालिमा नेत्र भाग को बनक
रे लेवे तिसका जीवना पंदरां दिन करे रहता है ३८ जिसकी
नासाडी गी विकृत होवे निद्रा बहुत अरु मुखको नाक
रखे अरु नेत्र बहुत लाल प्रभा है वे अरु स्नेह रहित वा
३९ अरु नेत्र जिसके चिड़वाले अरु मलके लेके रंग
के बाघन वा हरदल के सम रंग के अरु रिनेदेमासके व

© Dharmartha Trust J&K. Digitized by eGangotri

शा
टी
२८५

णिहैवितो छोडपमकेअन्दर पानेवालाहै ५० इतिनेत्रपरि
ता अवनीमकीपरिताकहने हैं जिसचोडेकीअभवि
षे अकस्मात् विंड होजाए पवकलेरंगकी यां होएतो
महीनेमेमरताहै ५१ पीतवर्ण होवनेतो दोमहीने येर
क होवेतो उपहिहीने येवडुनरंगकी होवनदवारमही
विषेमरयाताहै ५२ येनीलवाचेहमाके वर्णकीयांवि
ड होवेतोपंचमहीनेविषेमरजकहिहै अरुहीरेकेरंगकी

विंडतेमिचकोस्याकोसितोहारिद्रवर्ण
को ३ भिमसोमप्रतिमोनदागेताघमत
ये ५१ इतिनेत्रपरीता अथाने हृपरीता
निद्धायांजायतेविंडरकस्माद्यस्यवानि
नः हसेनजायतेमासैविंडकेनवसं
शयः ५१ पीतामासद्वयेनवनरगोमर
श्रमिश्कृति त्रिभिर्मासैर्लयारक्तावर्मि
लविविद्यनः ५२ पंचभिर्नीलवर्द्राचष
डिर्वज्रसमाकृतिः सप्तभिःपाटलाका
रा चंपकाभल्लथाष्टभिः ५३ नवभिश्च
हारिद्राभो दशभिर्नेवृकोपमः एकाद
शभिरनाभोवन्नोरणहेमद्युतिः ५४ य
स्यस्यासोभवन्स्मा:शरीरेबुलकोकि ते
निद्धादिसमसाकारामासमेकसनोवति
५५

विंड होवेतो छेमासेकरके मरताहै येपाटलपीनरकहो
वेतोसनमासलगजीताहै येचंपकेफूलवांगृहोवेतो
आठमासकरकेमरताहै हरदलकेवर्णकेविंड होवे
तो नवमेमासकरकेमरजाताहै करहोएतनवदशमहीने
आयुहै यदरनमणि अभाकालिपाविंडहोवै नदन्नारैमा
हीनेआयुहै येसवर्णकेवर्णहोवेतोवर्षकेविषेरोग२ ६
लवेहोए जोभवर्णकेसमरंगहोवेसोचोडा एकमही
नाजीवताहै ५५
मत्युनाम ५६ जिसकेआसनमेंहोवे अहयोगविषे ३ ३

© Dharmartha Trust J&K. Digitized by eGangotri

तिसको नर होवे अथवा रोप मलदोकौका होवे अथवा ति
दोषवा मारणे वाले रोग होवें इनाको देषकरके चतुरवै
द्य सर्वआयुकी परीक्षा करलेवे ४४ इति शालिहोत्रे अष्ट
मस्थ॰ वैद्यरहस्याध्यायः अथ सप्तमस्थान विषे प्रकृति
स्वभाव का लक्षण अरु तिस्थरलमिले लक्षण कहेन
और गर्भके होणे का लक्षण ज्ञान और देह का नलाहि
प्रमान शरीर का निश्चय ४६ और प्रकृति का उपाय कहे
या है अरु शरीर का प्रमाण अरु पदार्थों के अर्थ का ज्ञान औ

रोवाप्यथ रोपलक्ष्यानि सूत्रयोपि वा ह
स्तानि मयोणै वैद्याविलोकायुःपरीक्षते
४५ इति शालिहोत्रे अष्टमस्थाने वै
द्यरहस्यो नामाध्यायः लक्षणं प्रकृ
तिं चैव स्वाभिप्रेत बलक्षणं गर्भसंभववि
ज्ञानं शरीरनिश्चयस्तथा ४६ प्रकृतिकोः
प्रक्रमं चैव तत्ना मानं शरीरजं पदार्थो
देशविज्ञानं विशेषक्रमसंभवं ४७ प्रसू
तालक्षणं चैव वैद्याधाराशुप्रक्रमः दे
षितं चैव बाहानां बालप्रकरणं तथा ४८
बालिनं चैव यात्राचनं ध्येयो ध्यानिकानि
च मात्रज्ञानं विधायोगः योगाभ्युकलया
विनं ४९ कृयाअपरिक्षाश्च प्रतिसंपानि
कलश्च उत्तरं सप्तमे स्थाने मंवे संपरिकी
र्तितं ५०

रविषा चिकित्सा ४७ सूतवाली का ल
क्षण अरु संटुकी चिकित्सा अरु घोडे के हिणका का
ज्ञान अरु बाल अश्व की विधि ४८ घोडेयांके पोटदृने
मिलिक सदी है तिसका ज्ञान और याजा चोडेकौ है अरु
उस्थानकोहिहे अगेअ ध्य को मात्रा ज्ञाने हे अगेविधायो
ग कहैया है अरु योगाध्याय है तिसके योग अकलयाय
है फेर याविनध्याय कहे याहै अगे कृयाध्याय है और प
रिषकहै अरु प्रतिसंपानि इनाकर के सप्तमउ स्थानक

© Dharmartha Trust J&K. Digitized by eGangotri

शा० हो०
२२९

286

हैयाहै इतिसंग्रहाध्यायः षष्ठस्थानेसमाप्ते ५० अथविर
नोकेस्थानोंविषेंनाहै करैयाहै सोसम समस्थानमें संदे
पनेकरनाहै १ वातपित्तकफइनोंकरकेउपजकरहैं इन
श्रयमें शरीरविषेंदोषजन्य एकसमस्वभावपहैं समप्रकृतीयांहैन २
ऐवषाविषें गर्भाधानहै सोवातस्वभाववालाहोताहै अ
रुशरजनमेंहोवे सोपित्तप्रकृति पोहिविषेंहो सो कफ
स्वभाव वसंतविषें समप्रकृति गर्भहोताहै ३ स्नायुश
रुशिशनताई इनोंकरकेआवरणदेहै जिसकाअरुसे

इतिसंग्रहाध्यायः इतिगणाकृतेअस्यांशा
र्ङ्गधरसंहितायांसंग्रहेषष्ठस्थानंसमाप्तं ६
नोक्तंलक्षणंकिंचित्स्थानेषुतेषुषट्
सुतद्वयः कृत्स्नमिहोत्तरतंत्रेसमासतः
संप्रवक्ष्यामि १ मारुतपित्तकफैर्याश्च
सन्निपाताद्विदोषजाश्चाम्याः एकाश्चसमा
प्रकृतिर्विज्ञेयाः प्रकृतयःसप्त २ प्रावृ
षिवातात्प्रकृतिःशरत्सुपित्तात्हिमा
गमेकफात्प्रकृतिः प्राकृतिस्समावस
तेगर्भस्यभवेत्त्रिविधिकस्य ३ स्नायुशीरा
तालसनःस्वल्पांगोरोमशःकृशोरूक्षस्वः
कृशाक्षिस्वरकेशोह्यज्ञानी इरुपचपलस्व ५
चपलोभीरुःक्रूरःस्तुज्ञारेणुचैवनसद्दिस्स
वात प्रकृतिर्वांनीप्रियपक्षमसुराल्लव
णानो ५

नप्रकृतेहैदेहनेवामअरुलिसा अरुरुव
देहजिसकोअौरस्वतिपास्वर बाल पढेसमकरते अरुहवरना
करपीडितहै अरुजिसकाउपवारःउपचारतःस्वकरके
होताहै ५ अरुवेवलहै इरपोवालाहै क्रोधीहै अरु
भुवलेभारकौंनहिंसहसकदाहै सोसोउगावातप्रकृ
तिवालाहै अरुमिठालुणाअरुपहैजिसकौंप्याराहैपण
५ जिसकाशरीरछिद्राहैरंगजिसकासंदाहै अग्निजिसका
शाहै अरुक्रोधीहै वेगगतिवालाहै शूरवीरहै सोपि

© Dharmartha Trust J&K. Digitized by eGangotri

नप्रकृतिकोजाना है औरकषायमधुरतिक्तप्रहैरसप्रपहो
ने है न जिसको ८ जिसके मस्तक बाल रोम स्थिर दृढ होन अ
रू स्थूर वीर हो वे अरु थोड खाणा अरु स्थिर है अरु मार
ग और मार्गसेदके सहारणे वाला होता है सो श्लेष्म स्वभा
व वाला होता है अरु जिसको कसैले कोडे तिक्त इष्ट
प्यारे होते हैन ७ जिसका मध्यभाग संकीर्ण अरु स्थि
र है अग्नि सम अरु सम भेगटट है न अरु प्रसिद्ध का
या दृढ जिसका अरु मांस पुष्ट सुंदर शोभावाला है

स्निग्धः समसुवर्णो दीप्ताग्निः क्षोपनो जवी
स्थूरः स्यात् पैत्तिकः प्रियो वै कषायमधुर
तिक्तानां ८ स्निग्धमूर्द्धरोमकेशः स्थूर
त्वास्थिस्थिरो बभार सहः श्लेष्मप्रकृति
र्वाजी कषायकटुतिक्तसेवी च ७ संकीर्ण
मध्यकायः स्थिरः समाग्निः समदृढः सर्वांगः
सुविभक्तकायमांसः श्रीमान् भद्रो जवी
स्थूरः ८ वर्षाणपस्थीनस्सहः सर्वे रसाशी
स्थूनः समप्रकृतिः संसृष्टः सौम्यप्रकृतिः सं
सृष्टः संकीर्ण रसेराद्वः ९ सत्वाद्रजस्तम
समा विज्ञेयाः प्रकृतयो रसोपरालितः १०
श्रीमान् भद्रः सुभटाः सन्वाग्रप्यान् समाविकौ
वाजी ह्रस्वाग्रहः सनो तणामनसारेणारा
नमाहृपानेयाः ११ इमे पमोलसालेनि
संदिग्धाम्नेनामसाः प्राकाः
दर वेगवाला अ
रु स्थूर वीर ९ वर्षांसुपणीन के सहारणेवाला अरु स
भरसके खाणेवाला है सुंदर सम सभाववाला है घो
रले मिलेर स खाणेवाले संहप्रकृति हैन ९ अरु सत
रजस तामस प्रकृति रसो के प्रीति करके होनाणी दे
हैन १० घोडो के सनो तणाधके है शोभावालो अरु घो
डाणा अरु घोपाधावरी माप्रवाला होना है अरु रनोग

© Dharmartha Trust J&K. Digitized by eGangotri

ज्यो॰ सा॰
१८७
287

ण अक्तवोरै है थोडी मात्र प्रसन्नता और रजीहरण स्वभाव वर्षा कर
के युक्त है न योनमो गुणी है सो उह बुद्धि अरु स्थाल सो वह न
निद्रावाले होने है न जिसको उकी रोम अरु नख बालस्निग्ध अरु स्न
ष्क होण अरु गात सवेकार हो लीही के अरु दृढ शरीर अ
रु स्वरमाहो होवै १२ और उरुथो न दिल उदावी नहि वनर
है सो भद्रा सबक है यां है अरु जिसके स्तनस्म है न संवरोम च
मडा अरु संवानाके बाल १३ निबल है अरु कोमल बाल

स्निग्धाननव्यकरोमा सत्वसंचारः सुनिर
द्धः स्वरः १२ न अतिपीनो न विशालाः ह्रस्वबुद्धिमान्
पक्षमद्वारः नवकुंडिका रोमस्पर्शकवालकु
ञ्चितकेशैव १३ दीनेमत्ज मघा एणमंदन्नरोमं
स्निग्धानीयान् इति प्रकृतिलक्षणम् श्रुभ
गंधो भारसहः श्वेतः पीनो उरुणः श्वेता तो
वा स्थिरदृष्टिनः स्पर्शो लोमहस्त्रकु नोल्लाल
णवाहुः १४ नीलनरोमानी नेजस्वोक
पनो महाकायः गंभीरस्वरः हीघोलबुक
मः तत्विणावारः १५ मघपिप्याश्चविनीमा
नमानिनोमध्यशोभावाः रुद्ददनाम
हाकेसरद्वः पिंगोहणवैषणा १६॥

जिसको भरयो गनाये इति प्रकृतिलक्षण जिसको उकी गु
ण गंधि होवै भारको सहारे अरु रंग विट पीलालाल
वा गौरहौ वेस्बरु दर्शन प्यारा लगे अरु शील होवै अरु
वरेश बदवालाहो ऐसा चोडा जालणजोनि कहेया है
१४ यो ठोडा कर देसु भाववाला सुरमा मानी नेजवाला
कांपिबदेते स्वभावादवाला महाहुणाकणा गंभीरस
रकरके हीलीचलनासो हाविणानिवाशहै १५ योमद
काप्यारा है अरुमुखे विमानी है अरु मध्यम सुखी है
अरु भरवपीडाकों न सहिसकारा कोमल पीलेनेत्रसो
वैस्य है १६॥

© Dharmartha Trust J&K. Digitized by eGangotri

जो रुदन हे ग्रहस्तंगतरटेवइहै न ग्रह क्रूरस्वभाव जोपि ग्रह
है हलवलिके मारताहै माटोग्रसगंधी अति कालीघोमे
दकुछि खोटी ऐसाग्रहजोडाकहेया है १७ इनिवानुवर्ण
के चारवर्णके है हैन ग्रहपवघाउजीनकहतेहो जिस
कोइकास्वरनेवरकोन्याई है ग्रहवालविकट है सो इक
महीनाजीमदाहै १८ जोविषनेकटयाहोयारोगणकीन्याई
हिणाकदाहै सो एकमहीनाआउहै तिसको ग्रहजिसके
नेत्र मल स्वर भेव काकके रंगकेसम हो न ग्रहमासनेर

रूक्षाविषमाक्रूरः क्रव्यपारिकोअनिष्टवित
रोगपाक्रसातामेदाउमेयसःस्मृतः १७
चववर्णके चात्तवर्णसमात्तानमोग्रस्ता
नमनपरे किंकिणीकस्वरोविकटगति
मेकेसजीवति १८ विक्षिप्तरुदितामेदेष
नेयः समामासाउः नेत्रास्यस्वरपादैःकाका
भैर्निमोमसोत्वहाषिः १९ दुर्वलतालुम
रोष्ठोयः सविजेयोहिमासायुः त्रिकककघो
काकपदैर्भग्नामासेप्सिनेचवङ्गभाः २०
मद्भसःभूर्नेत्रयोकपदिग्ययोसममासायुः
यस्यास्निग्धरपाभोमांसेनाहतलोचनोः ए
मासायुः २१ इहलोपिकगात्रःसंतिमयट
मल्लको हसोमतोहःकंटाह्नेननकुपि
कोःल्पनिमायसासोवर्णायुः २२

छिनशोव्वकेन
ल्पटछिद्दोवे १९ ग्रहनिर्बलहोवेनालग्रहउपरका ओठजि
सकामोटोमहीनेआयुषावालकहेयाहै जिसकात्रिक
ग्रहलक रिठंष काककेपदहोवे ओरुग्रवटेनाआविषे
वहनेहोण २० ग्रहसनावी मवटेग्रहनेत्रोविषेहोणनव
सनमहीने आयुहोनिहै जिसचोडेकेनेत्रमास्रिकरकेज
लेहोयमासकोनहो मासमेटकेहोयनेत्रहोणनवग्रह
महीने आयुहै २१ जिसकापीडवृत्ताहोवे ग्रहमध्याउग्र
योकोटीयो ग्रहकोरनेउपरहैजोठनजर उपर होवेनपटे

© Dharmartha Trust J&K. Digitized by eGangotri

आ
रो
२२८

2 88

अरु बालयौ उ जिसकी वर्ष आयु होती है २२ किशोर अ
वस्था की समके बीच पांडु अपथ्य पथ्य पहि करता है अरु ली ए
बीन हि है अरु बलवान है जिसकी वो वर्ष आयु होता है
यो थोड़ा अकस्मात् कारणों से विनाश करता है लोकों के
विषै वसते होय पथ्य सो पंद्रह महीने जीवता है २३ थोड़ो
डा बहुत भोजन करता होय वो निर्बल है अरु निरंतर न
आयु कम रहता है अरु मुख ते लाला बहती याहै न अरु उ
गंधि आवती है जिसकी वो हिम वो हि महीने आयु होता जाने २४
कैशोरः पाण्डुरोनाथ्यवर्तिनि तोयने बलवा
न् सोपि वर्षायुः यस्त्वकस्मात्क्षयं निते ने
वसने सप्त वर्षा मासायुः २२ बहु भुङ्क्ते
दुर्बलः सततं तृपिपासितः प्रतिमुखो ला
लास्रावी तेयः सविंसति मासायुः २४ रक्ता
बहु भक्षयसत्वकामि यो द्विवर्षायुः मृदु
द्दीनो गौरवमी स्फलापनै स्तब्धभिगात्रैः कृ
पानतो लेववत्ताः स षट्वर्षायुः २५ कृशा
मे दद्रद्रकेशः यो यो दकोनालि रिक्तगा
त्रः प्रलेववकर्णः समवर्षायुः २६ प्रयातेय
स्यामिनरावनेः सोपि समवर्षायुः अमर्थ
नाथ दृष्टिकालपर्यंतो स्त्रष्टावर्षाजीवति २७
यो थोड़ा लालस्रावि वाला है अरु भोजन बहुत खावे अरु
बलने कामी है बलानकार करके जिसकी दो वर्ष आयु है
जिसके थ्रवटे वटे है अरु गंडु विषे आवते हैं न अरु सटे ने
विस्तार वाले है न अग जिसके मुख को पत्र है वहस्य
ललमें होन जिसकी छे वर्ष आयु है २५ जिसवा उका
प्यासा अरु बहुत लिसावीना है कर्णलेव जिसकी
सनरवे आयु है २६ जिसको उके दाढी विषै आग ले
कालभाणकरके आलने होना वे जिसकी तीसना गांवे
आयु है अरु जिसको उकी बहुत रामकी नराट दृष्टि होवे
जितना कालजीवना है सो सप्तवर्ष जीवना है जिसकेशि

© Dharmartha Trust J&K. Digitized by eGangotri

र अरुग्रीवा वहुत रंगों की यां होंन अरु अपिष्ट रंगवरे
ग होवे तिसकी अट वर्ष आयु है २७ षोडाक्रिमिको
छवाला है और पिसके मुख नेत्र कमल लालो वर्ण अरु
लाल रंगवाला होवे तिसकी नव वर्ष आयु होवे है जिस
का शब्द वडा होवे अरु कौशेय पट वस्त्र वा कुसुंभे के
रंग के सम वर्ण होवे अरु काडी छोटी होवे अरु मास
जिसका कसे या दो होवे अरु वलवाल है परसा वहुत या

विवर्णोपि योग्रीवा षष्टहायं यस्य सोप्यष्टव
र्षायुः २७ क्रिमिकोष्ठिलालोमुखनेत्रवास
थैरक्तवर्णो नव वर्षायुः महास्वनः कौशे
यवर्णो हस्वग्रीवः स्वउमांसो वलवान्
मेदी वहुमूर्तो स्तनस्तोपेन रुरोविवर्णाले
मिर्मांसलो दशवर्षायुः २८ ध्वस्ताग्रपला
शुगः प्राप्ता नयना हस्वस्तकुशकक
र्णः प्रोतेषापिमसेनेने घास्ना पुदेशो केव १९
मकुटी वदनो लेवोफलः प्रोष्ठवक्रवलि
स्तरगः सुस्थूलमानदशानोदशवर्षा
णि जीवति ५० सवरोमदंगमध्यागरक्ता
स्यारक्तनालजिह्वोष्ठः हृस्वैर्नेत्रैः पादे
स्तथा दशाग्रायुस्सकृत् ५१

वे अरु पच्छा व वकूनकरे अरु नेमाया ल्हा है अरु सं वषेत
वर्ण के होवे नेत्र विरूप करावर्ण होवे अरु मास थोडा है
हृविषे तिसको दश वर्ष आयु होती है २८ जिस घोडे का
रंग भड़ा होवे अरु चंचल होवे अरु वीर्य है अरु पाहु के ने
त्रों के सम अहिपां होवें अरु पेडु को पाछो है अरु कान
के न छोटी अरु पोशीनकाल विषे वीर्य सम करे ने नेनो की
आयु ना वर्ष है २९ जिसके भवें अरु स्रवलमा होवे

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
२८९
289

और सआंडे औषलंबे होन और चोड़ा वडे वलवाला अरु मो
टे नान्हे नेत्र होवे सो दश वर्ष जीवता है ५१ जिस घोड़े के
सब अंदर होण अरु लकम ध्यने सदंग वजेनस कोमार
सहम होवे अरु लाल होण मुख नाल जो कुछ उठ जिसके
अरु काले होन नेत्र ने सेव तिसको नेरो वर्ष आयु कहि है
५१ जिस घोड़े के चट वदेद होवे अरु वालो हव वड़ीया हो
वे अरु पिट गौर वर्ण के होवे अरु जाव ने रोम मोटे होन
तिसको वीस वर्ष आयुषा होती है ५२ यो घोड़ा वेडूर्य
मणि के वत्न रंग के नेत्र वाला होवे अरु खावे वहुत क

विषमैर्दशनैर्वाजी मकाहन्त्रुष्टैव गौरपृष्ठ
स्थ स्थानस्थलजानुरोमा चवन्नेदशावृषाग्रुस्ख
ल ५२ वेडूर्यवर्णनेत्रो वहुभक्षकरः स्थलश्रो
णिकर्णः स्थिरग्रमदीर्घपृष्ठः षोडशवर्ष
णि जीवेच्च ५३ रक्तैर्दन्तैर्विसन्नेनिर्हृतल
लाटचरणो महान्सारः लेवकर्णः शुभ
दंष्ट्रोजवः द्वादशाद्यायुः ५४ नीलग्रीव
मुखाङ्घ्रिः संहनेगामानिकेरयोहरयः पी
नशाफालेवफलाश्चिपंतमकोनविंशा
दे ५५ श्यामाखुरारक्तवालारक्तजिह्व
वरक्तमेहनेयेषां क्रूरैर्दृष्टोवर्णाविं
शति मेयान्तियमसादने ५६

ऐसे घोड़े सदा रखे
अरु तिंदीनैविस्तार वाली पिट सो ग्रोलां वर्ष जीवता
है ५१ योलालवर्ण हाय छाव करे अरु मष्यो नेम व घडे
विसाला होण अरु वेर उनार दमो होवे अरु कालेवे
होवे अरु दाहाओ छ उदर होते तिसको अठारां वर्ष आयु
है ५४ जिस घोड़े का मुख नीला होवे अरु काशी नीली हो
वे अंगमिदर होवे उदर शुड होवे सापापोली होवे अरु घोड़े
ले वे होन सोउ नी वर्ष विषमरता है ५५ जिस घोड़े के सव

कालें अरु वाल ऋक्ष वर्ण के अरु जिह्वा लिंग होवे अरु के
वडे के फूल सम इंद्रमा—ख के तुल्य वर्ण जिसका सो वीस
मेरवे स्तन होयजातहै ४९ योघोडा सिंह शार्दूल कीन्याई दे
खता है अरु चलता है होले होले अरु स्पर्श विखे कोन
ा कोमल है सो घोडा वडी आयुवाला होता है ५० जिस
घोडे के कर्ण दीन व होटो के समला सलु रूप है नअ
रूने अरु पीडी होय लडु वगम्याबे अरु नेत्रों का अंदर
ला—पासा और मोजे वी लाल होवे सो वडी आयुवा
ला होता है ५१ योघोडा मरक वरण निर्मल चंद्रमा

शार्दूलवत्पश्यति गच्छति शार्दूलवद्वयोमे
दे मार्जारवन्मृदुस्पर्शो यस्स दीर्घायु
रिष्यते ४९ यस्येंद्रगोपकाभे कर्णौ ग्रान
पीडितानन सर्वे द्वगके दीर्घायुःसतुरंगोय
त्राक्तिकैः क्रूर्चमध्यस्य स्फटिकदृश्यवि
मलभाशापर जनस्सवर्णाः सहसव
ललाटः ५० हेमाह्नाःशुभगंधाः आ
दीर्घायुषोबाहूः विपुलसलिलप्रवाहे
पादेनास्मभ्यापिवंति ५१ योभिमखेवख
स्येचेदेंद्रस्थानदानिमस्दीर्घायुरिष्मकः
दलाचाराः श्रुणः समेपमः सिंहमेवगजना
दः वांदिउगीनरतयोवाहाविपुलायुषा
रेयाः ५२

रूपा के सम वर्ण वाला होवे अरु मुख नेत्र
तक वडा विसाल होवे ५२ सुवर्ण की न्याई नेत्र अरु श्रेष्ठ
गंधिवाला और शूर वीर सो दीर्घ आयुषा वाला वाडाक
हेया है योघोडा वोरे जल के प्रवाह विषे वीसेव के साथ ज
ल को इस्नाय करके पोन जलपान करता है यो सत्तनमुख वे
दू मा को उदय होयवे का देख के पोशाहु करता है सो वडी आ
युवावाल घोडा कहिया है जिसकी पांस दरवाले हैं ल अरु
पर वीरदिल वाला है अरु सुंदर वुद्धि वाला और सिंह मे
घ हाथि की न्याई शब्द अरु वजेव गीत है न प्यारे जिसने

© Dharmartha Trust J&K. Digitized by eGangotri

अ
दो
२९
290

ऐसा घोड़ा बड़ी आयुवाला होता है ५० जिस घोड़े के अंड
फल लंबे होंय अरु अस्थि दीर्घ पांडुर होंय बड़े बेसुख केशवाले
मुख होंय जघन पट बड़ा स्थूल जिसके अरु घोड़ी पीठ
में बहुत प्यार अरु जठर जिसका थोड़ा है सो बड़ी
आयुवाला कह्या है ५१ जिस घोड़े के रोम के रोम विषे जल
ले अरु कर्ण छोटे मुख बड़ा अरु भोजन बहुत करे अ
रु देह बड़ा होवे अरु अथवा कालापन होवे सो घोड़ा बहु
त चिरजीवी होता है ५२ यह आयु के ज्ञान नाम ए
काध्याय है ये मनुष्यों के हाथों विषे देखा है तैसे हि

लंबवृषलाः सुमनपनाविस्तीर्णैः प्रोथजघ
नवक्षोभिः वड्वाशिपाल्पजठरा वा हावि
पुला सुखोतेयाः ५१ प्रतिरोमसलिलवा
यी ह्रस्वश्रवणो महास्यो बहुभुक् म
हाकायो कृष्णो वाजी वति पन्न चिरंजी
वी ५२ इत्यायुर्ज्ञानं नामाध्यायः ॥
यद्दन्तसुमांसायाणां रेखा प्रोथेन यावदंग
णां वंजनैस्तिसकलमायुष्कल्पमानाम्सा
प्रसंगोत्र १ एका प्रोथमध्ये यस्याईरेखा
सोदशायुः अंगुलप्रमाणो द्वे रेखे प्रोथ
मध्ये यस्य सो सोद्विवर्षायुः २ तिर्यकः स्थि
ते द्वे रेखे यस्य गले यस्य सो नववर्षायुः ३ औरे
खा वामेनन्तागत्र पचाग्रे से पंचवर्षायुः ३ ॥

घोड़ियों के प्रोथ मध्य विषे देखने निश्चय करके आयु ज्ञान होता
है संपूर्ण तिसकर के इस विषे रेखा का प्रसंग कहते हैं १
जिसके प्रोथ के उपर मध्य विषे एक आड़ी रेखा है तिसकी
दस वर्ष आयु है जिस घोड़े के मध्य के मध्य अंगुल प्रमा
ण विषे दोय रेखा होवे तिसकी दो वर्ष आयु है २ जिसके
टेढ़ी दोय रेखा होय गल प्रमाण होय तिसकी चार व
र्ष आयु है जिसके ऊर्ध्व रेखा होवे अरु प्रोथ रेखे प्रास
प्रोथ नेत्र टेढ़ी होवे इसकी पांच वर्ष आयु है ३

© Dharmartha Trust J&K. Digitized by eGangotri

जिसके एक रेखा दो अंगुलीप्रमाण ऊर्ध्व होवे यस्मा जिसके
तिसकी छः वर्ष आयु है जिसके ठोडी के मध्य मे चार अंगुली
रेखा होवे तिसकी सत्तर वर्ष आयुर्दा है ४ ओष्ठ के बराबर
जिसके रेखा होवे तिसको अठ वर्ष आयुर्दा कहि है पउंके
मध्य अंगुप्रमाण रेखा जिसके होवे तिसको नव्वे वर्ष
प्रमाण आयु कहि है ५ जिसके ओष्ठ के विषे ऊर्ध्व रेखा जा
वे नव दश वर्ष वो जीवता है अरु जरा वर्ष होती है आयुष
व ओष्ठ विषे दो अंगुली प्रमाण दो रेखा होवे तो बराबर

एका रेखा द्व्यंगुला ऊर्ध्वं यस्यासौ षड्वर्षायुः
माऽद्व्यांगुलया ओष्ठमध्ये रेखा यास सप्त
वर्षायुः ४ ओष्ठसमा रेखा यस्यासौ अष्टव
र्षायुः एवमध्यांगुला रेखा यस्यासन्नव
त्यायुः ५ ओष्ठार्द्धे रेखा यदि स्यात्तिन्न दा
दशवर्षाणि जीवति एवमेव द्वे का दश ओष्ठ
द्व्यंगुलप्रमाणे यदि द्वे रेखे नरो द्वादशव
र्षाणि जीवति ६ अंगुलेकिंचिदधिके म
ध्ये एका द्वे रेखे यस्य सत्र्योदशवर्षायुः
ओष्ठमध्ये यस्य रेखा तिर्यग् रूपा काकपद
वत्स चतुर्दशवर्षायुः तिलमात्रा भवेद्
द्वे रेखा यस्यासौ सपंचदशाब्दायुः द्वे रेखे
ओष्ठसमे स्थूले यस्यासौ षोडशाब्दायुः ९
रेखाश्चनस्ता यस्यासौ सप्तदशाब्दायुः

आयुषा है ६ जिसके ठोडी के दो अंगुली कछुक अधिक एव
के मध्य विषे दो रेखा होय तो तिसकी तेरां वर्ष आयुषा है
जिसके मस्तक विषे रेखा त्रेडी या काकपद की न्याई ऊर्ध्व
होवे तिसकी चौदां वर्ष आयुषा है जिसके ठोडी को तिलप्रमा
ण रेखा ऊर्ध्व होवे सो पंद्रां वर्ष आयुषा वाला होता है जि
सके ओष्ठ विषे मध्य ओष्ठ मोटी दो या बराबर रेखा होय ति
सको सोलां वरे आयुषा होता है ९ जिसको वार रेखा
ऊर्ध्व रेखा होवे तिसकी सतारां वरे आरबला है जिसके

© Dharmartha Trust J&K. Digitized by eGangotri

सा॰ टी॰
२५१
291

बारेरेखां रलोयां होनानवेतिसकी ग्रठारांवेग्रायुकही
है १० यदजिसघोडेके वारेरेखां वरावर ग्रकस्थितहोयां हो
न नवउनी वर्षे ग्रायुकहोहै ग्रकजिसकेपंजरेखां वरा
वर वडीयां ग्रगटहोवेतिसकीवीसरकीवूरेजोवनहो
ताहै ११ जिसघोडेकेंभरेरूपकमलसकीन्याईरेखा
चिह्नसखउपरहोवे तिसकोबारवर्षे ग्रायुवाहै जिस
केग्राथमध्यविषेंमनस्यरेखा ग्रथवारोमसेरेखाहो
ए नवसोवोजोउरवर्षग्रायुरखावालाहोताहै १२ जि

रेखान्स्योपदिमिलिनभवेतिनदाषष्टाद॰
शाब्दायुः १० यदि वर्न ओरेखाः समाः स्ति
ग्याभवेतिनदेतन्विशमब्दायुः पंचरेखाः
समाहोचा पस्याविच्छिनामन्नीवस्यैक
विंशतिः ११ अंगक्रमोपमं लक्षणं यस्य
सदाविंशति वर्षायुः मनस्यापस्य प्रोथ
मध्येमनस्यहपंचाशत्त्रयोविंशाद्वायुः १२
प्रोथमध्येशाखोपमलक्षणं यस्य चेन्नवि
शात्यब्दायुः वर्धमाने प्रोथमध्ये यस्य स
पंचविंशत्यब्दायुः यतधंत्रप्रोथमध्ये
षट्त्रिंशत्यब्दायु १३ पुष्कराभंभवेद्यस्य॰
समसप्तविंशाब्दायुः अष्टापदं यस्य सोष्टा
विंशाब्दायुः १४

सघोरेरेप्रोथविषेंशंखकेवोउनचिह्नहोवेजिसके
तिसकोवोवीवर्षग्रायुहोतीहै जिसकेप्रोथविषें
वर्धमानग्राखतोपांवहैति जिसकेप्रोथमैंयनुसरेखा
होवेतिसकोछवीवेग्रायुरखाहै १३ जिसकेकं
मलकीन्याईं शोभायुक्तरेखाहोवेतिसकोसताई
वेग्रायुहै जिसकेग्रष्टपदजीवकीन्याईरेखाग्र
कारहोवेतिसकीग्रठाईवे ग्रायुहोतीहै १४ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

जिसके कोटके सहित नगरको प्रकारकीन्याई होवे
चिह्न तिसकी उनतीवर्षे आयु है जिसके नदीके वर्त्त
नकीन्याई आवर्तभौरहोयो एक वृंदा त्रय सलि
काकीन्याई होवैतोत्रीहोवर्षआयुषाहै १५ जिसके
धना अरु छोटी धजा भेद और छत्रयह चिह्न होवत
तिसको एकत्रीवर्षे आरबला है जिसचोडेके होडे
उपर अर्द्धचंद्रमाका प्रकार होवे तिसको बत्तीवर्षे

सप्राकारनगरोपम्यसैकोनत्रिंशाब्दायुः
धनपताकाछत्रवाप्यस्यकत्रिंशब्दायुः
नद्यावर्तोहनेयस्यएकत्रिंशतिकोवाप
स्यसत्रिंशद्वायुः १५ अर्द्धचंद्रेणाब्धगः
प्रोथमध्येस्थितेनयः द्वात्रिंशाब्दसमासा
यसस्याःसमरणोब्रनेन १६ एवमायुप
रिज्ञानमृषिभिःपरिकीर्तितं पुंसेनन
त्ततेवाबनस्मायुक्तोभवेदिति १७
सर्वरोगानिवृत्तिमःद्दन्तुल्लेभगलग
हस्तगानेभ आवर्तेहणरोगाज्वररोगवा
तशूलमस्याल्लेभ शूल उईवते उरःस्थाम
धनावेशप्रयोक्ताभिधानमूत्रकृच्छ्रा
सवपरकोरमूत्रकृच्छ्रवानोदर ॥

आयु होती है सो आयुभोगके स्वस्थ हि स्थिनकी प्रभु
कौ प्राप्त होता है १६ यह मुनीयोंने आयुका ज्ञान कह्या
है इसके पुरुषज्ञान नतोवाला भुलतान है तिसनेर
सकों हस्तीन रोना नरोवाला होवे हैय १७ सर्वरोग
निवृत्ति होजाणी खावोनहोजाणीया गल
रोके याजाणी मगजेभरोग वुट हणरोग ज्वर वान
शूल गलनाडीआकउजानीपाशूल उदावर्ते अंजेखा
स धनयहप्रवेशयोक्ताभिधान मूत्रकृच्छ्र आसपर

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा॰ ह॰ २१२ 292

रक्ताद मूत्ररोगकृच्छ्र वातोदर मुखरोग शिरोरोग ज्व
रलापदाह उत्कर्षक मुखदोषोंका वातगुल्म सर्प्प
दंश लिंगविकार विषकरकेमरण क्रिमिकोष्ठ इत्यादिकों
रोगोंकरके इत्यादिकोंवेरोगोंविषे अथवा अधिक व
र्षोंकरके यथाशास्त्रकरकेमरनेहै नचाहे इतिपदे
शोपदेशवालानन्दका उपायकरेहैयाहै आयुकाज्ञानमेनक
हैयाहै अवचाहेयोंकी उत्पत्तीमेरेनरूप सतयुगकेआ

मुखरोगशिरोरोगज्वरतापउत्कर्षोकमु
खदोषोंका वातगुल्मसर्प्पदंशलिंग
विकारविषमरणक्रिमिकोष्ठयभिरेभिवा
पकैरेभिरेभिवर्षैम्रियेत १८ इतिमोक्षोप
देशादिदेशाध्यायः आयुर्ज्ञानंसमाख्या
तमस्माभिंसंभवंस्मरण कृतयुगादाव
स्मृत्युकप्रकापहेः श्विनीनक्षत्रे भगवा
नब्रह्मलोकमतःसितस्त्वरितदिव्यनं विधिनाम
वैदोक्तमार्गेणद्वाव ततःप्रथमायामा
हुत्यांपुरुषो द्वितीयायामाद्यामाम्बः
श्विनः सुतपुत्रान् सर्वेलक्षणसंपूर्णांसम
भवेत् १ अयमसंभवः॥

इसविषे आश्विनमहीनेके शुक्लापक्षमें अश्विनीनक्षत्र
विषे भगवान् ब्रह्मलोकवाले ब्रह्मा पिता माहाप्रपणे
नेपहमगनकेरचनेहीइच्छायुक्तहोयादादिव्यविधि
करकेवेदीवनायकरकेयज्ञस्थानवनायके अग्निवि
षे हवनकरताभया तिसकरके पहली आहुतीविषे
पुरुषप्रथम होतेभये अरु दूसरी आहुतीविषेघोड़ा
श्वेतवर्णका चार पत पगवाला अरुसभलक्षणोंक
रके संपूर्ण अश्वरूप होताभया १ यहघोड़ेकीपह
लीउत्पत्तिकहीहै॥

© Dharmartha Trust J&K. Digitized by eGangotri

अवतसरीरउत्पतिकहतेहैंहो फेर तिहांके औरलोकों
के विषैग्रासहोयपतें अरुऔरसभविस्नुकेलीनहोयें
ते अरु इसजगतविषें एकसमुद्रकेहोयपते ब्रह्मार
सप्रकारकरकेप्रजाकेरचनेकीइछाकरताहोया
तिसहिसमुद्रविषै योसूर्यविषैकहेयोदिन अथि
नभुक्तपत अग्निनीनद्रविषैहवंकीयाई वदीव
नाकरके हवनकरताभया तिसकेध्रमकरकेने
त्रव्याकुलहोयब्रह्माके तिनोंनेअश्रुनिकलतेभये

अपरःशुनसेषुलोकांनरगतेषुप्राणिषु
काणेवोभूत्तेजगति ततःसर्वे भगवान्स
नाःसिसृक्षुलसिमेवाणौवेहुनिहुत्वे
मर्वेवन् वेदोक्तमानहाव ततोधूमना
कुलोभूत्तलोचनस्य भगवतो ब्रह्मणः
अश्रुणिप्राक्रमंस्तानिसमुद्रवः तानिपत
मानसभिसमीस्सश्रीभगवतीनभैवशा
रीरादिभिर्निर्गतादहितेनदहितेन निवा
मान्यथुणितयामेनयाणेनापारयासम
ततस्वास्वाम्बउमेभूताःअत्रयातेतसमाः
श्रियःकरत लगतान्यश्रुणिमुष्टानितेश्री
लक्ष्मणयाम्बुरम्भेस्थितानितैः होत्रयामा
भरपल्लान्नुरूमयाणितानि वैष्णवाःपाद

अरुबगतेभये तिनांकोंफिरदेखतेहोयेयांकोंदेखके श्री
लक्ष्मीभगवतीतिसब्रह्माकेशरीर अरौकलकरके
सभगवतीमजेहुच्छाकरकेमर्नेकेअश्रुपात अरुरवेवे
केरवेवेहच्छकरकेधारणकरतीभई तिनांनेजोईप्रगा
टपदेहोयपहेन अरुपेहुंश्रीलक्ष्मीके हस्थ विषैस्थि
तभ्पष्डहेसोपहस्थतेगिरनतिनोंनेजातस्तणहोतेभये
अरुयच्छातीविषैस्थितहैनतिनांकरकेतजोइस
नेभयेहैन अरुयेहणीकेहुटपटोविषै अपहैनति

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
२९३
293

होकरकेवैश्यहोतेभये अरुयो पैरां विषैहैंन तिन्हों
करकेशूद्रहोतेभये अरुयेसबैपाशोकेअष्टहैंतेनां
करके इस्त्रीयांहोतीयांभेयां अरुयेअष्टदलणपासे
केहैंतेतिनांकरकेघोडेहोतेभये और येफेरलक्ष्मी
केहस्तनैपर्यहैंन अष्टकेतेनांकरके गर्दभहोतेहै
यहैंतेमोविस्तनहैंन सोसभसाष्टि प्रगटहोयहै प
हेहमसाचोरकासंभव मनुष्यादिकहिहै और नी
मरासंभवकहतेहैं नीपारोउत्पत्ति वेर ब्रह्माकौ अ

यौलैः स्मृद्राः वामपार्श्वेस्त्रियः दक्षिणेन रा
मा यानिपुनः स्त्रियः करतलस्पृष्टानि
अष्टणिनस्माभाषामानितेगर्दभानि
हिप्रपवितनःमानुषेनाः इतिहितीयसं
भवः तृतीयपुनःब्रह्मणःसुसंभवे अ
श्वनामाप्तउत्पन्नेनमैहद्बलोभवतितम
मनसानपत्रमपारथेनमग्रेनपक्वपु
मानमपलभेदःसविभूतिपमिंग्रशाद्री
नःस्त्रियमवेमोतिलोनमांचात्तापयामा
स। ताभिस्तस्यामंगताभासाभपवतितोऽ
शुः मनसांस्त्रियमेवचकमे मनयासहका
मापभोगान्ः॥

शुभानप्रगट होतेभये तिनों
नेअश्वनामपुत्रब्रह्माकाहोयाहै तिसनेमहैहदपदवी
केलोभनेहरयागया मनजिसका सोवहाडग्रतप
करणेकेउद्यतहोताभयातिसकेउग्रतपकरनेहो
यकौदेखकेइंद्र अपणीविभूतिअपहरणकेडरहोणे
केभयकेइरयाहुआ नीलतमोउर्वशीऔरतिलोत्तमाअ
सीराकोआज्ञादेताभया। सोअश्वअष्टकर्मकरना
तिनांकरकेतपतेंभंगहोणेने सोतिनांकीचेष्टानेल
क्ष्मीकौगहणकरणेकौ इच्छाकरताभया सोअश्व

© Dharmartha Trust J&K. Digitized by eGangotri

तिसके सहित बहुत काल वांछित भोगां कौं दिव्य विहार
करने होयगा असे पौर कदेक श्री देवी यव देवलोक कौं
चलो गाहेन तिनां जानीयां होइ यांकौं देखके सो अप्र
सना थी क्रोध युक्त होके तिसकौं श्राप देता भया कह
ता है तुजा अरु स्वर्गो हो पैसें श्राप युक्त हो इ दो तिस
कौं पै हु श्राप देती भइ २ तेवी तिस प्रयकर केइ सव
न विषें उलू होयगा पैड श्राप देती भई अरु तिनां दो
नो के वन विषें विहार करने होयां तिसस्वर्गी विषें प

बहुधेनानामहानं कालं नरनया अथ २
कथ्यादाचिनश्री देवलोके प्रस्थिता तासां
प्रस्थितानिरीक्ष्य सहसा रुषितः शशाप
कुवेरस्वर्गो भव त्वं शाप सततिनमे वेश्मा य २
नेमवासिन् वने उलूको भविष्यतीति त
या सह याव वने विहरतेत स्वयां स्वापाने इम
जायत २ तदे इकालांतर प्राभो स्फुटिते
तस्मात् समाख्यः प्रादुर्बभूवुः तेन भगव
तो दिनकरस्य रथ समूहोंते २ इति र
तोयसंभवः वनर्थः पुनः तोरादादभिम
थ्यमानदेषमाणे हयश्ववः पत्नपात्
उच्चैःश्रवानाम हयराट संभूतः इति चत
र्थ संभवः वाजीनां संभवः शालकःस्यामाला
लतणस्फुरणं॥ फूटउजन्म्या है २ सो अंडेकि तनाक
कादीने होयां फूटया है तिसते सतघोड़े प्रगट होते भयवा
समुद्र से प्रगट होया है तिसकर के भगवान सूर्यकार
थ चलना है १ फेर घोड़े कौ तीसरी उत्पत्ति कहि है वो श्री
उत्पत्ति कहते हैं फेर क्षीरसागर के मथन करणे थें ति
सतें हिणक रो होयां घोड़ा वाय पत्नी अरु पाद युक्त उच्चैः
श्रवानाम घोड़े यों का राजा प्रगट होता भया यह घोड़े
का चौथ संभव कह्या है घोड़यों का संभव कह्या है अ
ब सायों का लक्षण कहता ॥

© Dharmartha Trust J&K. Digitized by eGangotri

अश्व

२५४

294

नवारुधिर मांस मद हडीयां मिंज वीर्य सत्वधातुसार
सारों को पांच प्रकृतियां अष्ट प्रकार हैं न १ जिस घोड़े के त
वा कोमल अरु देह सूक्ष्म अरु रोम वी कोमल सूक्ष्म चि
कने होय जिसके अरु बलवाला होवे अरु निरोगी होवे
तो सो त्वचासार वाला घोड़ा कहेया है १ जिस घोड़े के जि
ह्वा अतिशोथ मुख नासा के पुट रक्त गोट हेनी अरु लिं
ग पद नभि के समरंग वाले होय तिसको रक्तसार घोड़ा
घोड़ा कहेया है २ जिस घोड़े के स्कंध पनोअ अरु वतस्थल

त्वक्शोणितमांसमेदास्थीनि चैव मज्जाच
शुक्रं सत्वं वदन्त्यश्वसाराण्यष्टकं नयत्वविदो १
तनुत्वक्सूक्ष्मरोमा सूक्ष्मरोमा चिक्कणामृदुः
स्निग्धाश्च सबलत्वाग्निरुजस्त्वक्सारः
कीर्तितस्तुरगः २ जिह्वास्यशोणेश्च श्वस्य
नासापुटे नयनौ चोष्ठौ नाभिवृषणौ शिश्न
नाघ्राणि स्मृ रक्तसारस्य ३ स्कंधौ वक्षोन
घनेस्थिरं मांसानि नानि यस्य तुरगस्य व
हूतः स्वल्परीवोधनिनस्तानि मांससारो
सौ ४ स्निग्धाः स्वाशस्वबलपः सम्बुद्धमाः श
रीमेदुला श्वेव स्निग्धनेत्रविषाणमेदःसार
स्य वाहस्य ५ शिष्टानि च बृहन्ति च शुक्ला
नि महान्ति यस्या चास्थीनि शुक्लामधुवर्णा
वाटेनासोप्यस्थि सारो मतोश्वः ६

स्थिर दृढ मांस युक्त होय अरु ज्ञव नपट
होयां सो तिसमनने मेतेरकौं नाशशम होवे सो पहे घोड़ा
मांसमासागवाला कहेया है ४ जिस घोड़े के स्व चिकने पि
द होय अरु उरजीयां ना होय अरु राजा होवे अरु संपू
कोमल होवें अरु नेत्र स्निग्ध होय नखमेद सार घोड़े
को कहेया है ५ जिस घोड़े के हाड़ सिर दृढ होंव
होय अरु स्थूल अरु बड़े होय और हड्डीयां जिसकीयां
चिट्टीयां होवें अथवा मखीर के समरंग होवें अरु इट

© Dharmartha Trust J&K. Digitized by eGangotri

वीखेतवामध्रवर्णकेहोए नवतिसकों अस्थिसार
वालाजाणे ६ जिसघोडेके दंदमोटे नें विरले होवें औ
र जंघामोटीयां शिर वडा अरु वीरवडादर देह स्थि
रा है अरु भोजन थोडा करे सो मज्जासारवाला है ७
जिसघोडेके अतिचिकन अंग होवे होयहोए अरु दंद
चिकणे चिटे समवरावर होवे अरु वर्णचिकन अरु घो
डीयां विषे प्रीति अरु वडे वेग चाली वोलासो वीर्य
के सारवाला घोडा है ८ अरु यो घोडा वडे न मागे व

विरलास्थूलादशनास्थूले जंघे महाशि
रःशूरः स्निग्धोमंदस्त्रीगो मज्जासारः सवि
ज्ञेयः ७ स्निग्धतनुः स्निग्धांगोदंतैः स्निग्धैः
सितैः समैः शुक्लैः प्रियकाचित्रियाप्रजवीवि
ज्ञेयः शुक्रसारोश्वः ८ वहनः खलुदीर्घ
ध्वनिर्भूमृत्स्वभ्रतपापीडितास्यनग्लानिः
श्रीप्रहतिमान् उदधोवनसत्वसमसार
स्व ९ रसस्राः सारवर्णश्वासोष्ठास्प
र्णावर्णातिमान् हृतोपिपासानपः स्प्रहाः
शाद्याः श्रमेनस्विन्नः सारवेनोभवेत्स
स्वाः सर्वेलतणेय्युक्तो नाः १० आरोग्यवल
मायुश्च भोगांश्वास्मांश्च केवलान् अपत्य
तेन्नसोहारिण्याः सौभाग्यस्तनसं ११

लताहोया भुखदा अरु तृषाकरउ रिवे विसानिको नथा
सहोवे अरु सूरवीर अरु धीरज वाला अरु सब दुखसेच
कोन्याईवान् सो सत्वसारवाला जाणो पहे सारवर्ण
गुरुघोडा केलच्छक हैन अवरनां के गुणपहे लक्षण
योंसें खस्वरूप सारदांको महारदा है अरु चालीवाला
सूरवीरधीर्यवाला सोघोडा सारेवाला अरु समलह
णोंकरके प्रजित होना है १० जिसके वरविषसारवा
लाघोडा स्थित होवे तिसको निरोगपता बल आयुआप्र

सा०
हो०
२१५
295

मोग औरव स्ते अरु संतान तेन कीहर्षियशः अरु शुभ
भाग्य अरु तिसमांहि हे ंदर स्तोयांपाम होतीयांहे अरु लक्ष्मी
वो जिसके चरविषे स्थित रहितो है जिके चरसार वालाहो
उ स्थित रहिताहै १२ जिस चोउके विषे सारके सम गु
ण होणसो देवाश्चक हैणाहै तिसकारणतें चतुरवैद्य
चोउके सारकोपरिक्षाकरे १२ यहे साराध्यायः कहैणाहै
अब इसके उपरंत चारप्रकारकायोग्यानूक है तैसाकह
तेहैं गतिकरके स्वरकरके स्वरूपकरके सत्वकरके

तिसंदाराश्च प्राप्नोति समसारे प्राप्य वाजिनां
श्रीश्च नव नते वेश्मपत्रे तिष्ठति सारवान् १४
यस्य सारगुणाक्रान्ता दृश्यन्ते सत्वसंततः
तस्मात्सारे परीक्षेत कुशलो निपुणो हि
यः १५ इति साराध्यायः अथ अनूकं प्रवक्ष्या
मि अश्वानूके चतुर्विधं गत्या स्वरेण रूपे
ण सत्वेन तु शुभाशुभं १ नरवानरमातंगे
मानूके सत्वलक्षणं त्रिविध सत्वसंस्थमे
दाः षोडशः प्रकीर्तिताः २ तेषामनूकानि तेषा
निम्नशस्तानीतराणि च स्वरदेहाकृतिनि भ
रूपानूकमापन्ने ष्वश्वानूके यथाभावये
प्रवेवतुर्विधे देते शुभाशुभसानूके पर
के सत्वलक्षणं ३॥

शुभ अरु अशुभ कहते हैं १ घो
सवगानश्वानूक है तिसविषे सत्वके लक्षण जाणी उपप्र
कार मनुके सोलांभेद कहे हैं २ तिनांकरके अनूक
जानणो श्रेष्ठ अरु निंद्य घोस्वर अरु देहकी स्वरूपवा
ला होवे तो रूपानूक जाणे अरु ऐसे हि स्वर अनू
क जाणलेवे इसतरें चार प्रकारके पहे जाणले
वे घोसवानूक के शुभ अरु अशुभ लक्षण है तासा
स्वर लक्षण विषेकहे हैन ३॥

© Dharmartha Trust J&K. Digitized by eGangotri

जैसे स्वराणूकके वेगे ताउ लक्षणकहे हैन जैसे शिग
त्यानूकके नामो पहे वारप्रकार अनूक शुभ अशु
भ निंद्यक हैन ४ यो चोउ सिंहादिकोके समशब्द
करयुक्त होवे सो स्वरानूक शुभ कहिये है इन ने निंद्य
यकर के सो भाजाके स्वना ने विडंपन को वृद्धिकर
ते हैन अरूपेका काकदिकको न्यायी शब्द करने हैन
सो स्वर अनूक निंद्यपापलक्षणक हे याहै ५ यहे स्वरनू
क ध्यायक हे याहै अब कोवोज वालीक वनायने अ

गम्यानूकम् विशेषो स्वरानूकं यथा नथा
पवेवनवैविपंहेमानदानूकं शुभ निंदिते ४
सिंहादिशावियोगेष्वस्वरानूकाः शुभास्म
ताः नैवैउंने पंनित्पनेः कोशागारेवस्
नित्र धोहादिशावियोगेचने वाग्यं शुभ
लक्षणाः ५ इति स्वरानूकाध्यायः ॥ अ
थ कुंवोजनवाहोक वनाग्रुजानाम काले
याना शरीरे शरीरे परिशिलितं भवति १
तत्र शरीरं नाम अंगप्रत्यंगोपांगविभक्ता
यामोत्सेधपरिणाहं शुभलक्षणं समाहि
ते मानोन्मानसंपन्ने रोगेशु रक्ष ८ शुनहे
मस्तुलिस्तयमस्तुमेदुलनी हराणं भीरसंश्लिष्टो
मान माहृदायननिर्मांसो मानोपघं ने सर्व
नरनयन

जानेय इनोंका शरीर अरु शारीर की परी
क्षा करणो पोग्य है १ तहां शरीर का नाम क्या है शरीर
अंग प्रत्यंग उपांग अंगविभाग विस्तार उंचाइ गिर
दे याइ शुभलक्षण सवधान उदार मन संपूर्ण देह
वजालोका मोटा सूक्ष्म कोमल चिकणा कोम
ल मंइल वज्र सीतल दृग गिर्द उंचे वजा विस्तार
निर्मांस उच्चाय पार्श्व अरु सर्व नर नेत्र

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
२९८

298

समहृदयकौं दृढेलगणा अरुविकार वालेनहिहोत
अरुपुभअंषहोवे वर्णप्रभा आवतेजिसके अरुशरीर
नेत्रोंकरके परिक्षाकरे शरीरुको एहेमालिहोत्रने क
हेयाहै तत्र अरु इसका विभागकरकेवर्णकरतेहै
आदविषेशरीरकहतेहै जिसविषे अंग प्रत्यंग एहे
शरीरकेधारणविषेकहेत अंगकहतेहो ग्रीवाशि
र वक्षस्थल क्रोड ग्रेसनदोपा उदरमाकि वक्षक ३
पांड त्रिक रोहहणी एहेसमअंगकहेहैत अरुतिनो

हृदयमणमविस्तनमपिस्वभवृणोव
नेप्रभाशालंवत्सुषापरिहेत शरीरं एतका
लिहोत्रोकेस्तत्रमस्पानिर्देशःक्रियते
तत्रतविस्त्रीरस्तुपने अंगप्रत्यंगापांगा
निशरीरस्यपारणे अंगानिग्रीवाशि
रोवक्षःक्रोडमेसपार्श्वोदरमाकिवक्षके
पंडत्रिकेरोहणाचेति १ अथैनेषंगेषु
यान्याश्रितानितानिप्रत्यंगानिभवंति
१ तद्यथा श्रोणारहननेत्राकुटिका
हवणानिव उपांगान्यतेषामाश्रितानि
भुरकर्णाहिजिह्वाग्रोष्ठश्रवालार
नि ३ एतेषांलक्षणंसर्वांगपरीक्षायां
निर्दिष्टमेव ॥

अंगोविषे येलगेहोएहैत येसे प्रत्यंग होतेहैत १
सा प्रतकहतेहो श्रोणाहत नेत्रो कुटिकाहष
ण एहेसम —पांगकहेहै अरु इनोकेविषेयेलगे
देहैत संव कर्ण प्रतियां नीहा प्रोष्ठ हवे वाल
एहे सोसम उपांगकहेहैत ३ इनोकेलक्षण सर्वोप
गेहांविषेकहदेहैत अरु आयाम अरु उत्सेध इनो
कालक्षण लक्षणस्थानविषे कहेयादाहै ॥
॥ ॥ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

सो साण लेवे अव दीर्घ अरु लघु इत्यादिकों का लक्षण श्रे
ष्ठ बुद्धि वालेयोंने इसको कहैया है पहे दीर्घ थोडे के अषु
करे पार्श्व ग्रीवा मस्तकि अरु बाल पहे बाहु जीभ न
खो पहे अठ थोडे के दीर्घ श्रेष्ट है प्रोष्ठ कर्ण पिष्ठ अरु
सेव मांजे गुदा लिंग पहे अठ छोटे श्रेष्ट कहेन थोडे है
अरु गुदा जठर गोडे सेव वहु दादी पहे वर्त्तिक गुदा
का उपर भाग पहे दश थोडे के गिरद श्रेष्ट कहेन अरु
बाहु अंगुलियां बत्तीये ललाट मस्तक उदर नेत्रहिआस

आपाणिमोन्नेपादीनां लक्षणं लक्षणस्थाने
निर्दिष्टमेव दीर्घहृस्वादीनां लक्षणमेतन्
दाख्यैरुक्तने दीर्घाणि च शस्यते पार्श्वे ग्रीवा
मस्तकेविष्टवालाः बाहुजिह्वा नेत्रपनास्य
ष्ठौतरेगाणांप्रोष्ठः कर्णौष्ठ हृषणौ तु
रक्काहिकेगुदेमेढ्रे हृस्वान्येतान्यष्टौ त
रेगाणांप्रशस्यते पायुवजठरेजानुव
त्वरवद्वदंष्ट्रा उन्नतानिकाचैवहस्तानि
दशशस्तानि स्कंधनेत्रवक्षोललाटम
दंतनयामनेजघने समैतानि हृपानाष्ट
थानिनिम्नप्रशस्तानि भ्रोष्ठौजिह्वाप्रोष्ठौ
वालारोमाणिकेशारसूना सूक्ष्मकोणनाम
ष्ठैप्तरदनिसतनुविपास्यते दंमानेत्रवर्णः
स्वराश्चकेशाश्च वाहूनां स्निग्धानिमेतानि
सदाप्रशस्तानिनवैः पायुवमक्षि

नेत्रस्थान जघन पहे समन थोडे थांहे निम्न हिस्सुलसोठ श्रेष्ट
कहेन ओष्ठ जीभप्रोष्ठ बाल रोमपशम आलशिरकेबाल
सना खालां पहे अठ थोडे के महीन तै कोमल श्रेष्ट
कहेन दंद नेत्र रंग स्वर केश पहे पंज थोडे यांके चि
ह चिकने थोडे यांके लहणा मानोणवाले योने श्रेष्टक
हेहेन अरु गुदा अंडेनासाबुठ पहे गिरदस्थंडलोवाले

© Dharmartha Trust J&K. Digitized by eGangotri

सा०
टी०
२९८

297

श्रेष्ठ हैन कंन दंतवाल परेत्रय त्रिवे श्रेष्ठ हैन गुदा
स्तव नाल परे त्रय इगोमदाहि प्रत्य श्रेष्ठ केहेना गु
दा लिंग मव पहोत्रय गोल चेंगकेहेन वहस्थल
मथा ददे परेत्रय विस्तार वाले श्रेष्ठ केहेन कोउपां
केसाक्षि पवलेपासे किंनेवांकानोउ अरुकंठ चा
हा हेत्रय कोउपों के विस्तार वाले श्रेष्ठ कहेन अंस
नयन वक्त्र श्रुतियो नासा के हार के पुट शिर परे

नासापुटौ परिमंडलानि वैष्णे ते विशाच
कर्णौ दंतावालाभ्ली लाणि निष्पाश्याने पाणुःउ
रोमनालं वगंभीरं प्रत्याते सदाविनये संस
त्तमिष्टं विनयं पाणुवृशीर्षस्तस्याश्य व व
क्षोल ललाटं दश नानासौ एकानि वै प्रशस्ता
नि सक्थि कंटस्य हनेत्रय मासायन मिष्ठाने वा
नौ श्रत्यं नयने नवहौने त्र नासापुटौ शिरश्च
व पताल निमहंति सदा षडं व प्रव्याति वा ह
नौ दोषणचाटं ने व नालं ललाटं चनिर्मां
सा: ह्रैवो मंते प्रशंसिते हिनाः उरगाश्च वा
हानो इति श्रीरललणादी यदीनामेन
लक्षणो भाइ शाविपक्षरिष्टं अंगविकल्पवि
कल्पना ॥

इनने छे वउ विस्तार प्रत्य श्रेष्ठ केहेण कोउंदे शेर
णा श्रो थ के मध्य स्थान हे जाटा पुरु पुडीपास ओर जे
नेवां नाल मथा परे स्थान थोरे मास वाले श्रेष्ठ क
हेन दंद और संव परे दीय चोट के उ हेर छे हेन
परे शारीर लक्षणादी वें इत्यादिकों कथोलो ॥

© Dharmartha Trust J&K. Digitized by eGangotri

तिसको कहेया है अव विकार विना अरु विकार सहित तथा
अंगप्रत्यंगों का लक्षण कहते हैं अव सोहोड़ा बडेके सेहो
गांसस्थानों कर के युक्त होवे अरु बलवाला है १ अरु
विकट डौल कर है नख अरु नलस्थान जिसके अरु वेग
मार करके युक्त है शूरवीर है सुंदर चालिवाला अरु
स्थिर आयुवाला है अरु चर्बी है थिर उदर जिसका
अरु देह सम है २ सभ अंगों कर के श्रेष्ठ है अरु अंग प्रत
प्रत्यंग समर्थ हैं न अरु शील है अरु अति मन को आनंद

दोषांल्लक्षणमप्युना प्रवक्ष्यामि अथ संहनन
ेनोपेता मांससें दृशा अप्यस्थिने वैलिनः १
विकटांगपादैर्दन्तौ जवासारसमन्विताः
शूराः शुभगामिनो वयस्यास्तु नरस्तारस्थिर
दराश्च समकायाः २ सर्वांगैरपि शस्ताः
अंगप्रत्यंगसम्पूर्णाः ये चाप्यीशीलवेनान
यनमनोनंदनाः शुभच्छायाः ३ अज्ञानेः
यास्तु भग्ना ये याप्लेन विकृता नाश्च ये वा स्तः
संस्थानमांसहीना मांसे स्नायोस्तु विनिमे
ग्नगाः ४ स्थूलास्थि मेध याये प्रमाण ही
नाश्च कुनाश्च संतिमा वितिमाः क्रूराः ख
लंजवेला अकर्मसहा ५ शैवेरोगैर्ग्रीवाक
टिवदनहीनाश्च येषां न पश्यति अन्ने विह
स्यपश्यन्ते विपरीते षां ६ ॥

के देखने वाला है और
शुभ छायावाला है ३ जो कोई ज्ञान में लेकर शोग से सुंदर
अंग अरु भनीयांवाले से विकार सों रहित कोई जाणे जो
कोई जिनको स्थानों विषे मास हीन है तिनों विषे नहि अरु
अथवा उलटे मासों कर के छपेटे हैं ते अंग ४ अरु मोटी
यां हडीयां से पिया ई जिनों है अरु प्रमाण में बडे हैं न कु
वे हैं न किसके भेंग संगा पहेक पाके के बडे अरु कोप
वाले निर्बल अरु मारी भार को नहि सहारना ५ जो रोग
वे गले के अंग अरु काडी लक मलव कटहोवे जिनोरे अरु नि

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ द्वा॰ २५८

नौकेश्रेननापचे बाम्रापापोउाकरकेपचेपिनौकों
भोजनतणानहोवे भ्रहपेविलणकोंवीसमर्थनाहिं जि
नोहेगात्रपिटवनपो आकुणपांहोनसैम्रेग भ्रहप्रंभे
ग व्यटवापद्धेण १ नौकरकेविकृनयौउनाणेजिणा
कौसाके नचन नष्याधेस्थानविषेहोन सयम्रेगाथुभ
यथास्थानहोवे भ्रहदोषौकरकेवहिन सेम्रविकृततेबा
उकेहैत जिनाहेसंवबलित भ्रहमासउपोउ भ्रहसक
पाउछुउकौदीहे भ्रहम्रेउ रिवसकेद ५ भ्रहपादशेगगु

येषांच भोजनगणानकृन्तमः प्रकाशोते
परिवर्तितम समसथागाउदृहेचपार्श्वयोस्त
थाः अंगप्रत्यंगेषुपिविषमेषपाविकृतनाद
पासेषाः सकोनेवनेवनयास्थानसम
गुप्तमपेक्षा २ दोषैरहितावगातिलेप्रो
प्रोक्ताप्रविगनावाहाः चलपादम्बलमां
साउपांउविमकाम्बमाश्चिपदंउाम्ब ५ पाद
विकारैषुप्रेमाः सेचाटारोदणोभ्रष्टाः वि
नैतियेचशृंगनिलहण शांघिनाहया
हीनाः ६ नृत्तिगतानाविजयाभावेधनिनेव
पोम्याल वर्षिपांपजउामकानपुंमकाः
केपादेहनमेव ७ विक्षैमैः कर्णौलवन
यापिशुनासेवाजिनोसेयाः ॥

कृत्यवें भ्रहजिनोंकेसंचाटरोदणीस्थानभ्रष्टहोएण भ्र
हवेंमर्धिउलेलेगांहेवलदेहेन भ्रहजिनकोगतिगुमहै
भ्रहपेयोराणांविषेनहिपामहोने ६ सोचोरहिकृत
नाएण तिनांकोभार भ्रहमार्गककार्योविषेनजोउ पे
बोले भ्रेनेनउननेपरिहाकननेहि नपुंसक भ्रहजिनां
रालिगखजानेरवाहरनाहिंनिकले ७ पेकर्णघोपेजिन
होन परहयोगेपिसनकरहै नतिपडेन पोचोरेसमोंप
हेन भ्रहपेचटभ्रेगेवालेहेन सोवोउ विकलनामकरे
हेन पेरेवानादिविकारौकरकेभ्रगभजगपन बाकृ

© Dharmartha Trust J&K. Digitized by eGangotri

उकगपेन थोडजिनांदे जेकाण येतिर्वलसंवोवाले अ
नवुडे अरुपेडे एकअंडवाले है १२ येडेवादंतनलोकी
न्याईअंडंवाले हैन अरुपेअंडगमैविना है सो अर्थो आ
कहैन इतनेथोडे अविकलनविकाररहित अरुविकार
युक्त अविगत अरुविगत १३ औरविकल येयुन
एह थोडे वुद्धिवालेपौनकहे हैन १४ ये अवि विकलो
केलक्षणअर्थविषैकहे हैन अवयरलेमिलेलक्षणहै
नसो अव कहते हैं १५ आद विषै योगमानेकहैन

ज्ञानं यथा ह्वीनं गाविकलासेवाजिनः
श्रोक्ताः वानायेसविकारैभ्रमविभ्रमा
श्रिमेपपश्चवः १२ काणाज्ञवेलपादा
नवपसामीनात्वेकमकाश्च १२
कपिमुक्तासपमध्याः स्थावपौलेसमा
ख्याताः इमेतेविकलावविकलाश्च
अविगताः सविगताश्च १३ विकलापि
श्रुताश्चनयातसंगमाकीर्तितलनेः १४
अविकलविकलादीनांलक्षणतः स
वैनिर्दिष्टमेवरशानां सर्वलक्षणमा
मिश्रवश्च १५ गर्गाकेनावश्यमने स
वकोषस्याभपनस्तनोवाहस्यकोर्ति
तो सतस्याहतोसहनोवपशास्तोकिंवि
श्मनो १६ एवंविधोचवाहस्यलनोप
योजपावहो अनयमाणाद्यधिकोस्तनो
यप्यक्षमस्तनो १७

सोकहतेहै योमूत्रस्थानके
दोनोपासौथोडेस्तनकहैन वडनछोडे गिरेअरुमि
ले होए अरु कलु काढेसो ओइफल वाले कहैन १६
इसतनां देप थोडे स्तनपोकहैन सोअष्टहैन अरुज
एकेहोणवालेहोण अरुयेप्रमाणयोकरेयाहै तिसनें
वडेहोनतो सोस्तनीथोडीकरेयाहै सोसनाकीराजाको

श्या॰
मा॰
२५५

299

देशाकों राज्ञेदेसहित नासकरनाहै यो घोरा अगलीयां जं
घाकाली होएा वर्णास्येन देहदाढ़ोवेसा अपणेस्वामीकों
रणविषैमारवना है १८ योश्चनवोचिटा अरु ग्रीवाकाऊी
नीली होवे सोवी खसमकोंयुद्धविषैमारता है जिसके क
र्णमें इलें वाले होएा जिसके चाला अरु मखे वालेंवा
लेहोएा वाहनोविषैअलहोवेवामोटे होएा १९ जिसके
अंगुलियोंके पल्मके उपरले भाग प्रगटना होएा अरु नेत्र
अपोमखनी देखणेवाले होएा जिसकोपहेलहृणाने

लिपंनाशायनेराज्ञ्यराष्ट्रेणस्वरूपाश्वे
घाङ्भयाहूस्वाभ्यांस्थेनाम्धः स्वामिनरणे
हन्यात् १८ श्वेतोनीलग्रीवाःसोप्याजो
हंतिभर्तारे पश्मिंडलोलकर्णीहस्वव
क्रोरोमशेश्चस्रोलेवा १९ अस्पष्टेवाहिकु
टेअपांमखेलोचनेचैव लहणेमेमय
स्यनंनेविघामायलतणेन्वरंगे २० य
मेनयानिसमरंनमजोवखलसमाया
ति गंडैविवृकेच हृव चेशमग्राग्वेमंल
विनोकर्णौ २१ म्हाटोग्नेललाटंय
स्यसभल्च्चेरमकः यस्पनशिरोमव
र्णोपृष्ठेश्चवास्यवर्णकोस्वस्य २२ वर्ण
स्त्यान्यवर्णाभरैश्वोनिंदिनश्वासौ स
मेनरकाशिंसमासंग्रामेयोजनेनेराम्
कः २३ नस्मिनेवमकनोसंग्रामेनीविने

स्कोंपापलहृणमरिलहृणवालापाले
योजिसकेरेकरके गुरुविषयपालाहैसो मीवनामुडुक
रके गोहुमावना जिसके गेड गलो होरी ठह्नुवालेमावा
ले अरुलेवके दहोण कर्जजिसके २१ अरुमथ्योजिसदेस्य
जिसदोरेकाशिरहोरंगदाहोवे अरु डुंवहोर वर्णा
कारोवे २२ श्रोरटेह होरवरणादाहै अरुअंगपकहोरक

समीन

© Dharmartha Trust J&K. Digitized by eGangotri

णे है पहे दोचोडे थामो के मारणे वाले निंघ है न पो श्वेन
चोटा शरण लाल है ऐसे चोडे करके पोमुह शुद्ध को जा
वे तिसके सहित स्वार प्राणों को मांगता है सो चोडा उ ह
की नहीं कुत्तियों का ला अरु पय के सम मध्यस्थान वा
ला अरु कक्ष की न्याई सूव अरु उदर जिसका २४ अरु
कपि ड. ली पुरुष उदर पहे सम चोरे भर्ता के मारणे वाले
हैं न पिसचो डे का रदन मूल माडे रूप का है अरु ददद्रव पी
कहे णा २५ अरु जिसके काला दंद दने कले या है सो
भर्ता के कुल के नाश करणे वाला कह्या है सो रवोन

मंडूककुक्कुटिरक्षोपवमध्यः कक्ष्यपा
दोदरश्चैव २४ पिटकोदरो घवान्नो सर्वे
निवेतिभर्तारं यस्याश्च प्रलंबपे एादंतः
मूलोपि कोटिज्ञो श्यम २५ निर्गत इति
कालदंतः कुलानककोतिनयाप्तो खे
रदेहतेल्यरूपाः स्वरदेहसंभवा स्वयं वा
स्ना: २६ खरदेहरता ये स्युः पंचशाखा शि
कणश्च पंचस्यम्कानानाहिरवरायेव
श्रेमिणास्तानिनः २७ यवेद्दवदपोवे
ने: स्याउन्यानकमोरः यस्येनेदयेपने
नगरेवाप मन्नेजन पदे वा २८ ॥

के देह के सम रूप वाला है अरु पे खोने के देह के साथ
रमणे वाले २६ पे खर के देह विषे प्रीती वाले हैं न पे
पंच संबो वाले हैं न पे ऊपके ग्रों वाले हैं न अरुपे मंद
र श्रेष्ठे के सहित जन्मे हैं न अरु पे दोखुरों वाले हैं न
संग वाले पे हैं न अरु पे स्तना वाले हैं न २७ पे हैं न जी
पां वाले हैं न पहे सम घोडे उपद्रव के करणे वाले क
हैं न जिसके स्नान करणे वाले नगर ग्राम निगट ह
कावि षेवाल वण म्याहे खोपे २८ तिस राजा को के शा हो
ता है अरु तिसका देश नाश हो जाता है तिस ने स्नानो

© Dharmartha Trust J&K. Digitized by eGangotri

वैद्यांकों शत्रुके देशविषे छोड करके शांतिकर्मकरा
वे २९ अरु ब्राह्मणांका पूजन करके गौ भूमि सुवर्णप
द्रव्यांइनां दानांकरके प्रसन्नकरे रोगवैद्यचोरयांके
भेद अरु तिस लक्षणांके जानणेवाले अरु चिकि
त्साजाणते हैन ३० अरु रोग अर्थनांके जानने वाले हैन
औ सो सबकों जानते हैन वैद्य तिसकारणते राजा वैद्य
कों सुवर्ण इत्यादि वस्त्र गौ अन्न ३१ और श्रेष्ठ द्रव्यांका
देकरके और सुंदर मन कों प्रीती करणे वाली यांवा
णीयांकरके अरु श्रेष्ठ मान करके निरंतर पूजन करे सो

रात्तलस्यक्षसने देशाद्विनासम्यग्यथाति
तस्माद्राजा मतुकार्येषु विषयेशांतिकर्मकु
र्वीत २९ संपूजयीत विप्रान्हिरण्यगोभू
मिदानैश्च यत्लक्षणं हृद्यानां शृआगृभं वै
किस्मितेचक्ष ३० औषधानिकानि यतज्ञा
नवैद्याः सर्वं विजनंति तस्माद्वैद्य राजा
हिरण्यभूषवस्त्रगोदानैश्च ३१ वाग्भिश्च स
नोज्ञाभिः सुसत्कारैः सदपेत्सनन्तं तेश्चजि
तोसकष्टात्रंगमाणांहितोक्रियांकुर्युः १२
नहिवैद्यपरोहितं समक्षेमदनैः मापिपारयेद्राजा
मानापयथापिनाकान्तथावेभिषकत्तरंगा
णां ३३ नित्यं परमेश्वरतां हृद्यशास्त्रविदो वदं
सिनाः स्वैरगस्य ३४

वैद्याभिन्नहोवदे अरु हर्ष
युक्त होवदे वो रोगियांकी पीडा दूरकरणे चिकित्साकरते हैन ३२
राजा रोगियांकों वैद्यनै बिना दीवदी मात्र होनाहि रवै
ये सब पुरुषांकों पिता अरु माता है ते सहि वो रोगियांके वै
द्य कहयाहे ३३ वहे वो रोगियांके शास्त्रके जानणे वाले
परमेश्वरताका कहने हैन जिसचोरके लालके से
व हरे पीले वादि होता ३४

© Dharmartha Trust J&K. Digitized by eGangotri

जिसघोड़ेकेसुंब काले पीले वा चिट्टे लाल होवें अथ
वा श्वेत घोड़ेके सुंब पीले हरे सब्ज लाल होवें वा पी
त घोड़ेके सब्ज लाल वा काले होवें श्वेत होवे पी
काले रंग दे घोड़ेके श्वेत मैले सुप पीले सुंब होवें
जिसके इस तरां के सुंब होवें दो रंगा के अथवा त्र
य रंगा के शुभ होवें एक वर्ण का वा उपवर्ण का ऐ
सा घोड़ा देवताओं के कहा है ५८ राजा जिस घोड़ि का र
के मारिहथ वीजीन दा है और वैरीयों ते रहित हो

यस्य हरेर्वापि शफाः कृष्णाः पीताः सिताः
रक्ताः श्वेतस्य यस्य पीता हरिता रक्ता
शुराश्चापि पीतस्य हरिता रक्ताः कृष्णाः
श्वेताः खुरा यस्य श्वेता हरित रक्त पीते
यैः पादैर्भवति कृष्ण वर्णास्युः ५५ यस्य
हयोः खुराः स्युर्हि पादैर्भवति कृष्ण व-
र्णा द्विवर्णाः समास्तु शुक्लाः वर्णास्तु वर्णा
वा देवाश्च लाहयाः समाख्याता ५६ रा
ज्ञा तेन विजयते वसेयरोणेनिःसप--
पत्वेवर्णाविकल्पाभवेतिजेचाश्वपस्य
तुरगस्य ५७ बहुवर्णापदशोः खोविज
यदनाबंदकृष्टपः पादानोचवर्णाम
कोयादिपांउरस्यपोवापि ५८ तुरगस्य
मर्त्तभाक्तस्य चिरेणापमसादने ५९ ३
कृष्णभगवाञ्चालिहोत्रेण ॥

ना है और यह ये सर्व विविध वर्णो के भेद कहे हैं न सो ने
ष्टा विशेषे होवें जिसके अरु बहुत वर्णा के सुंब होवें
सो घोड़ा विजय धन अनंद सख करके कहा है जि
स के चरणा दों के वीच एक श्वेत होवे अथवा श्यावि
द होवे जिस घोड़े का स्वामी सतावी यम के घर को प्रा
प्त होता है ५९ यह भगवान शालीहोत्रने कहा है ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
३०१
301

पोत्रपचिटेसद्यांवालाहै घोडावाइकालाहै त्रयस्थेनहै
नजिसके ५१ ऐसेकौनाकापर्विषेपरेनैनामहेलेले
वे ननीवररवे पर्हे घोड़ाक्लेशकेकरणेवालाहै
पापीहै इसकाकुलमोषली नामकहेणाहै ५१
जिसकेअगलेदोनंवचिटेहोणसोभर्तंपर्कोपनकेरे
णेवालेकहेहैन अरुपीछेदोनंवपिचलेस्थेनहोण सो
विजयकरहैन जिसकापादपकुचिटासजावास्वका
होवेसोस्वामीको निर्धनकरताहै ५२ जिसघोडेका

त्रिषुस्कंधचरणेवानोस्कंधैकचरणेवा
त्रिस्कंधाचरणेवापिपृष्ठैकचरणेहृ
यः ५१ नाष्टशांनुचपुंजोननक्षीणेयान
पारयेत् अभद्रकुलनेवाहः पापिष्टः
कुलमोषली ५१ पूर्वौद्वौसितपादौय
नदौविजयायपश्चिमौनौच पकाःस्खले
वामोयदक्षिणोवासितोनयकुन ५२
पूर्वौवामःयेनःपश्चिमपादस्तुदक्षिण
स्थितः तीर्थकस्थेनस्थैवमुमन्तुविमप्रदो
मतः ५३ पवमपरेतुपतेवलिमित्रवि
वर्द्धनोभवेस्थितः मर्वस्थेनपदौ सःकुल
विनयःपापकरःकथितः ५४ माईनिस
नच्चनपादामहाफलावाजिनःसमाख्या
ताः आजानाभृग्रकुपादःस्याद्धमफलोदा
यावाहः ५५

अगलापादतवेवाम्बेनहोवे अरुजिस
कापिचलासजास्थेनहोवे अथवाजिसकोत्रेडास्थेनवि
हहोवैसोस्वामीकोबहुतधनदेताहै ५३ ऐसेहियेदस
स्वनेहे रेहेणाहोसोभी बहुतमित्रअरुधनकोंवधानेहैन घोघो
डासभसेनपादोंवालाहै सोकुलसंतानधनपशाहनोके
करणेवालाहै ५४ घोघोडानचरनस्थलोकेसाथ अरुपी
हस्थेनहोन सोघोडावडेफलवालाकोहेयाहै अरुपी
घोडाजाणापरंजेनस्थेनसंबद्धहैन सोघोडाप्रगटफ
लकेउदयवालाहै ५५

© Dharmartha Trust J&K. Digitized by eGangotri

यह्रै शालिहोत्रनेकहैयाहै जिसघोडेके रोमोंनबाहुल
शिरविषैषेनत्रपविद्रुपदहोवे शुभवा अशुभफल थो
डाकहै ५८ योसार अरुपाटलपीलाचिटा अरु चित्ररंग
वाले रिछकेवर्ण अरु भमोलेरंगकु यह्रैगण इनोंवि
षै यह्रैश्वेतरोमअशुकचिपटहै ननदर्योइनाकी षेत
पाद दोष नहिंगहणकरे ५७ इसकेअंडुकासमयल
विषै हरदह्रोणसोपानहकेजानणेवाले निघनहिक
है अरुपोश्वेतम्ककनल रहिनहैयाम्ककुक्षहैसोला

इत्थं वदन्ति शालिहोत्रेण रोमाणि पाणिशीर्ष
वाम्बेनर्वृपववपदवेत् शुभं वा अशुभं वा
पि फलेन वाधमादिशेत् ५८ सारपाटल
चित्रवृक्षकेशेन रोटित्तु श्वेतरोमा न
लिदेषन गुणास्मिन पादमा ५९ कालेवा
यस्यवाहस्य दानहिसु कोनिहितः सर्पा
सैन्यैः अश्वस्यकोवाहकस्य राज्यलाभं नदा
भर्त्तुः ५८ विषमो वसम्यकोवास्यानोयदि
शुवलाभम् पकहयणाहि नीयो यदि व
श्लोमिवलाभाय हयंपयोदिभृशाभगासमः
संदष्टपनेलनीयलह स्याधिकेशभन्तेस्तेन
लेमेगणजानीयात् ६० पादनयनप्रधा
नास्तरगायस्मान्महर्षिभिः कथिताः

मीकोंराज्यविषैलाभकरताहै ५८ अथवा जिसकेअं
ड विषम लिंकअरुपकबढाहोवेतोभर्त्ताकोशुअशुभ
होताहै जिसकापकअंडहयणहोवे फेर हससपद
होवे तवमित्रकासमागमहोताहै यहदोषअंडयोकर
केयुक्तघोडाचरहोवेतो दोमिनेकरके मानयुक्तहो
ताहै तवजिसघोडेकीश्वपरककणादेहोण जिसके
स्वारकौं लिमकरकेरोग औरदुःखहोतेहैन ६० घोडे
योकिसंवक्रुहनेत्रपदइसवास्तेमहर्षिगर्गादिकौ प्रधानकहेन
जिसकारणते घोडेकोपरीक्षाविषै संवअरुनेत्रदेख

© Dharmartha Trust J&K. Digitized by eGangotri

प्रा
दो
३०२
302

णमैंवहुतध्यानकरणा ५१ येनेववैडूर्यमणिकेतुल्य
प्रकावाले स्फटककीप्रभाकीशटशदोणविसाल वडे
होणा अरुपेककृतरकेनेत्र समहोवे ओचूपहि ऊट मोर
हंसटिटीडुलीपरेह हाथी हरिण इनांकीयां अखियांकी
न्याई अखियांहोण जिनांदीयां अरु स्वेत महीन होय स्त
जिनांदे प्रसिद्ध हर्षयुक्त होण अरु मधीरक समपी
लेवर्णकीयां अथवा मालतीके वर्णकीयांहोवे ५२
स्थिरदीयां अरु वडीयां सुंदर होण नेत्र नारकाभुरीयांजि

शाफनघनपीडाया सम्यग्यनमदाक्रयण
न् ५१ वैडूर्यनिभेशाले नेत्रे स्फटिकप्रभ
विशाले च पारावतान्तसमटपाकौवाहम
प्रांहंसनिभे ५२ टिटिभगजहरिणसित
नितल्पप्रभाणि समानि मधुपिंगला
न्यथना निमिलिकापुष्पवर्णानि ५३
स्थिराणि महान्ति नारकाणिफलकप्र
भाणि शुभानि नायोटिहितानि च येषां
नेत्राणि ते धन्याः ५४ रक्तप्रान्तविडाल
वानरमहिषवराहपेनाक्षकेकेलणा वा
जिनः भेकानामश्रिपेक्षणा क्षुद्रभक्षु
रोक्षणा पिहृया वालाम्ननशुभाः स्खड़ःख
जननाभक्तैः कुलस्थानकाः रुग्णाः सुदृशनाः
सुसमाः स्वतणाः स्थिरासुसंस्थिनाः स्त्रियाः
५१

नकीयां अरु इकाडीकेफलके तुल्य वर्णजिनांदा सो
शुभकहियांहैन अरु जिनांदीयां नेत्रांकीयां अखियाके
पालेपासे रंगिन हिहैसोधन्यप्रएकहेहैन ५४
पेहोतेविड्ड कुनावकर विला - दासेहुरा खोना
वान ङ्गा के कपहि रनां हैसम नेत्रांवाले चोरनी
णक महिष वेल रनांकीन्याई कूर भयानक म
हिवाले पेहोतेहैन पहेलारेकेपापनहि पदे
पेहूनहि मनीके इवहेणेवालोअरु कलके

© Dharmartha Trust J&K. Digitized by eGangotri

नाश करे है न जिनां दे सवर्ण दुःहोए और बराबर चि
कणे ८८ अरु यथार्थ स्थान विषे स्थिर होए थिर होवै
खुसमोट कठिन गडुयाने रहित सरल होए आना
होवे चिट होए फुट देना होए अरु अकउना होवे
श्रेष्ठ वर्ण युक्त होवे अरु लिंडिज न नहि बहुत खोटम हो
ए ५९ अरु जोनि को संकोच्या ए नहि है न अरु ऐवद्ध
कारनें ऊगे नहि करे है न अरु मर खवडे न हि है न अ
सन्न वकी संधी न कर सदा वर्ण मन प्रय होए ५७ अरु

वहलानिर्बलिकावैरकाः स्नेनाश्च न स्फुटि
ताः अलक्ष्मनोन विवर्णान वेडानाति
हृस्वाश्च ५८ खवाश्वरामाकृतयो वंगभो
गमध्यानः कठिनाः चितः नवेशिवा
नावैदीर्घिकाश्च मणाश्चैव ५७ पादौ
गावैर्निर्मलाञ्जवरोमानापार्णीयः अश
नाऽजन्मास्लेचविदिनव्यानरोमभेः ५८
येषांकृर्वाश्च मस्त्र दीर्घाञ्जनाख्यसंपिण्ड
अवज्ञमांसोपचिताउन्नतास्तवक्षसे ५९
अत्यर्थं चकृसाश्चपृवे चात्यर्थमायताः
उदुक्वृक्षिकायचदीर्घाकाठेनसंहिता ६०
कुक्षिकाष्ठीलपाटप्राणीवरोमोन्नपार्श्वा
याः

ऐसंकंकेरोगहै ननिनांनेरहितमहै न अरु
उच्चेहैसवावतो अरु गामवे अरु सीमांजिनांके साथेइ
उनम है सोवेह अरु वीने जानऐ योगय है न ऐसे चोर ५८
जिनां के गुल्फ मिटे श्रेष्ठ अग्रभाग अरु गिर्दे अरु
संधियां विषे मिले है और दृढ मास करव है होय है
अरु रात्रे है न अरु ये कोमल है ५७ ये बढुन खोटे है न
ये बहुत विस्तार वाले है न अरु सेवकी संधि साथ उ बे
वरे है न ६० कुक्षिका सेव की संधि लो सीके दृक री

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा
हो
१-१
203

केसमकरहोयाहैन अरुहोसोनननोडीग्रडीयाहैन योवो
इसनादोषाकरकेशुभहै सोमाइलनसोवालाकहैया
है ९१ चलनेकोजानप्रयोगकरणोकेसमयविषेयोटसु
लक्षजाजानरखाकरकेयापादस्मटेसोमात्राप्रमाणकहै
याहै तिसमात्राकरकेचोडेयोंकेमव वेगकोजाणे
योवोडशोलोमात्राप्रमाणकेवेगकरके सर्वेपनव
जावे अरुफेरडसोगतिकरके चले आवे सोवडेवेग
शुभश्रेष्ठकहैयाहै ९२ योचौवीमात्र प्रमाण यावेर

पंचैदौषसमाप्रोक्तानिर्दिष्टाणिदिनाहयाः
९१ अग्रकरणेनजानदहिणस्यानतोचटा
यातः सामात्रानिर्दिष्टास्तथाजवोवाजि
नाञ्जेयाः ९२ मात्राभिः षोडशाभिर्वैव्रज
तेयस्तुगच्छतिस्वरगः आयातिनदेव
पुनः सोप्युत्कृष्टजवसमाख्यातः ९३
यातिचत्वय्वैशतिनिर्मात्राभिः समध्य
समाहिष्टः द्वात्रिंशमात्राभिर्गच्छन्यध
मस्तुरगः ९४ आवर्ताभुवाः शुभाशुभा
शुभास्तेत्रिविधायथासावर्तनावर्तेध
रायेण योध्वरणाद्दीमावर्तेयतीनष्टामान
केवाच्छः सर्वेशाशीरगोरोमजानेभ्रमणामा
वर्तेकुरुते ९५

सोमध्यमकोकहेयाहे योकेमलवत
रीमात्राचलनाहे सोनिष्टचोडाकहेयायाहै ९४ अवअ
वआवर्तकरतेहे सोआवर्तशुभश्रेष्ठफलवालेअरुअशु
भनिषफलवाले सोतप्रकारकेहैन येसोसहितआवर्तो
कोवर्तदाखानवाशु इत्थवीविषेभमीकेनरणकोआवर्त
वमेदनकेपरकोत्याइकरदेनाहे तैसेहिस्थानवाशुमारे
शरीरविषेभ्रमणवाला सोरोमोकेपे आवर्तेदेरे
वक्राकारलिनाकोकरदेताहै ९५ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

ऐसें गर्भके अंग अरु उपांगनि सकार के होते हैंन ऐसें
हि चोवीस कै दशा आवर्त भुवनाम होते हैंन ११ एक
प्रणाल कौ होत है अरूप कमधके मध्य और दोष
लकाविषै दोवालि पौविषै और दोरंधविषै दोउप
रंधविषै पहै आवर्तके स्वरूप कहै हैन एक आठते
शुक्ति सें यात सकल अवलीटक १७ ज्ञानपादी
पाडुका अर्धपाडुका पोतलके वसुदनकी न्यारे
वालौका चेरा होवेसो आवर्त कहे या है पोशियों के

यथा च गर्भस्यांगानि उपांगानि भवंति ए
वेषु आवर्ताः स्वाहरंगमस्यां भवंति ११
तेषु का प्रणालोपकोललाटे द्वौ मस्तके
द्वौ व्यतिश्रौ रंध्रोपरंध्रयोः आवर्ताः
शुक्तिमेचानो सकलो सवलीढकः १७
ज्ञानपादो पाडुकाउर्ध्वपाडुकाव आवर्ता
नामा ह्यतयोऽष्टौ जलायुणानापमा
वर्तैः शुक्तिश्च सक्ति प्राटपरी १८ सेचा
नो बहवो रोम जापकी भूताः सकुल
नामा सकुल संख्याने अवलीढके नवा
वलीढकमष्टधा ज्ञानपादो ज्ञानपादो स
मा कारः १९ वक्र स्या पाडुकानदर्शन
मष्टधा ऊर्ध्वपाडुकाम् आवर्ताः दशाध्रुवाः
शामवि ज्ञानशुभाः षट्शास्यसुभाः २०

समअकार है सो शुक्ति कहि है पोवहुत वालोंका एक
ठा होवे सो सेचान कहे या है पोमातिसालनो के
शुष्क की कली की न्याई होवे सो सकल है पोगा के व
टे होय पहे वालों का अकार होता है सो वली ढक कहै
या है पो कपोलके वांगुर वालों का अकार होवे सो
ज्ञानपादी कहे या है २१ पोबार कोणवाला होवे सो
आवर्त पाडुक कहे या है पोतिसने ऊर्ध्व होवेसो ऊर्ध्व पा
डुक है पहे दश आवर्त ध्रुव है सदा हि फलके कर्त्ता

© Dharmartha Trust J&K. Digitized by eGangotri

मु० ह्वै०
३०४
304

लेहैंन और सत्ताईस आवर्त्त शुभ कहे हैंन अष्टाविंशत र-
आवर्त्त निंद्य फलवाले कहे हैंन ४० तिनांविंशतांके
वीच एक कुकुन नामा कोंके विंष्णाकी त्याई गोइ यो
विंधि आवर्त्त होता है सो वीसद्रादिफलके देणवाला
है अरु और सभवाकीके आवर्त्त दशाके विभाग क
रके फल देण वाले कहे हैंन जिस घोडेकी वयसो वर्ष
आयुषा है तिसकी १ पवर्ष अरु दोम होने अरु वारां दि
न दशा कहि है और पवाकीके थोडे हैं व तिनोंको

तत्राप्यभानां मध्ये कुकुकाकस्य कज्ञा
न्त्यावर्त्ताः सर्वकालफलदाः शेषा द
शाविभागफलदाः द्वात्रिंशदायुर्घोट
द्यानस्य वर्षाणि त्रीणि मासौ द्वौ दिना
नि द्वादश शेषं त्वंयस्य यावदायुर्ले
ख्येनैतस्य दशाभाभागो दशा ११ उक्ते
व भगवता शालिहोत्रेण आयुषो द
शमे भागे दशा प्राह विभागशः ती
येदायुर्विभागेन तेत्र भिन्नभियोयते ७२
आयुषः प्रविभागेन वयसः तेत्र सल
क्षा लक्षणस्य फलं विज्ञेन कालां
तरानि स्फले १२ लक्षणं हेत्र संयोगान्म
ले मैव प्रजापते सर्वांगस्यामितै विघा
नस्य सर्वकालफलोदय १४ जितनी आयुषा
लेवेल लक्षण करके इसका दशमा देसा दशा कहि है
११ यह शालिहोत्रैने यस्य यह बालने कह्या है आयुका
जो दशमा है सा है सो दशा पृथा विभाग नै कही है यो
विभाग करके आयुहीण होवे तिसको तेत्र कहने
हैंन १२ यो विभाग करके आयुहीण हो आयुषाणाके
यो विभाग है तिसकरके और अवस्थान और लेत्रने या
लक्षणका फल कह्या है सो सभ फलकालके अंतर
करके तिस्फल होता है न १३ यो तेत्रको संयोग नैन

© Dharmartha Trust J&K. Digitized by eGangotri

तांकानिश्चयकरफलहोताहै सोसारेग्रहकेआवर्त
रूपादिकोंका सदाहिफलकाउदयकहेयाहै १४ जोदो
आवर्तोंकाफलकहेयाहै सोतिसकोसाईफलनहि
होताहै शुभग्रौर अशुभकेसमूहकेविषे बहुतल
ग्नोंविषे जेमेदो आवर्तमिलेकाकहेयाहै तैसहि
तिनोंकाफलकहेदेवे १५ जोसमस्थानविषेआवर्त
है तिनोंकासूक्ष्मफलकहेयाहै जोशुभस्थानविषे
श्रेष्ठ आवर्त है सोबहुत फलदेताहै १६ अरुजोश्र

हिआवर्तफलंयत्स्यात्तद्ददेतेभवेत्तु न
शुभाशुभमतिकरेडुत वनापिनिर्दिशे
त् १५ समेनमध्यमेत्तेयं फलमावर्तका
रये शुभेस्थानेशुभावर्तोदद्यात्‌विपु
लंफलं १८ अशुभस्त्वशुभेस्थाने शुभस्था
नेशुमनेयदि शुभाशुभंफलेनत्रतनवले
वविनिर्दिशेत् ११ शुभस्थानेशुभतरो
भवेद्यत्नतरोपिकोः वामपार्श्वेतथा
वामाद्दक्षिणाचापिदक्षिणः १८ अत
तोषमहोनास्तसवर्णःस्निग्धसप्रभः
स्थानेषुसुस्थिनोयस्तुःसर्वकामार्थ
साधकः १९

शुभआवर्त शुभश्रेष्ठस्थानविषेहो
वे जब अरुश्रेष्ठआवर्त अशुभ स्थान विषेहोवें १०
तिनोंविषेशुभनिश्चयकूलकोमलथोड़ाफलकहेयाहै ११
जेशुभस्थानोंविषे बहुतश्रेष्ठहोवे सोस्थिर अरुश्र
तिसैकरके श्रेष्ठहै जेलवेपासेवेवा आवर्तहोवे अ
रुसजेपाससज्ञआवर्तहोवे १८ सवर्णहोवे बडेवि
स्तारवालाहोवे अरुसुंदरवर्णहैवे चिकना सुंद
रकांतिवालाहोवे अरुजेअपणे स्थानोंविषे स्थिर
होणतोसभकामनाके वांछितफल कासाधन
कहेयाहै २१ जेआवर्तहीनजटहोवेछिनविचने
भजाहटाहोवे अरुजेस्थानोंनें कमारेहोवे अरु२०

© Dharmartha Trust J&K. Digitized by eGangotri

सा॰
टी॰
३०५
305

होए अरु वां है नाहोए यथार्थस्थितनहिये अरु वहो
वतीहैन अरुये अपणेस्थानतें भ्रष्टस्थानमेंनहिंहैन
अरुमांउरगकेहैन पहेसमपापलक्षणवाले निंघकरे
हैन ८० जिसचोरेकेमाथउथीकेउपरकिसीकारण
करकेआवर्तहोयाहादेखीये सोचोडासत्तावरेयांदामर
जानाहै ८१ जिसकेसजेकन्नेकेपासमूलविषें तिलकका
विह्नपदहेखीये सोचोडाजांगांवरेयांयमलोकसम्बस
जाणेजानाहै जिसकोया अस्त्रीयांकेवक्षुकारविषें तिलक

हीनविच्छिन्नविषमसंनीर्णकृष्टदाश्चवस्थि
नाः पृष्टकस्पष्ठलविषष्ठाविवर्णाःपापल
क्षणाः ८० यस्यानेयस्यावर्तस्याग्नेनरूपा
लकोते समसवर्णःलवगःपंचवर्षयमपाति
८१ दक्षिणेकर्णमूलेवतिलामंयस्यदृश्यते
यकादशाब्देसोयबोयमलोकगमिष्यति
असर्णीमध्येललामंव यस्याश्चस्पष्टं
दृश्यते कुशलस्तंविजानीयात्षष्टवर्षायु
षंदृयं ८२ नतस्मभवर्णासर्वलक्षणवान
कल्याण्यहृदयः दृढसनःसुभगोयः समप्रकृति
भद्रसंस्थानसमप्रमाणवान समहस्तैरूपेनः
सर्वांसनवानुदरः पृथुवताःकुलनःसा
हैयानवारवलेरुपेनः ८३

काचिहृहोवे तिसकों
कल्याणजाणें अरु शोलावर्षआयुषाहै तिसको
रेकासुदरवर्णाहै औरश्रेष्ठसभलक्षणवालाहै तिसको ८२ जिसको
यांविषेंसमर्थवालाहै अरुसमअंदृ१
लाहै श्रेष्ठगंधितगंधवालाहै अरुसत्वपराक्रमयुक्तहै दृढवलवा
वालाहै अरुसंस्थानअंगप्रमाण यथायोग्यवालाहै अरुसमप्रकृतिस्वभाव
मनल्पहेतअवस्थाभगयुक्तहै सभअंग अवयववालाहै अरुस
ग्रहे शुभभागजिसका अरुवडेविस्तारवालेहैन वक्षस्थल
जिसके अरुयोग्यजातिविषेंनमे आदा और सारवाल इनों
करकेयुक्तहै ८३

© Dharmartha Trust J&K. Digitized by eGangotri

कोमलसूक्ष्म रवा कोमल हैं ते रोम वाल के पा जिसके अम्बु
कल है और जलद नगारे के समस्वर अरु सिंह शार्दूल को ग्रा रे
पराक्रम पुरुषार्थ अरु बहुत उत्साह उद्यम वाला है १४ सो
कैसा है जिसकौं फल पापै हैं ते अरु सुगंधि लेपन वी जिसकौं
प्रय हैं ते सो ऐसा घोड़ा उत्तम वाला है सो ऐसा घोड़ा अश्वमे
धयज्ञ विषै अभिषेक करना योग्य कहेया है और जिसके स
मग्र लक्षण घोड़ा होता है दो प्रकार का एक सहज साथ
ही मूर्छ वे ते हैं अरु एक पीछे ते एक उत्तम आहार के सहार ए

तनुत्वक्सूक्ष्मरोमकेशो ऽम्बुकलः नलदेर
भिनिस्वनः सिंहशार्दूलविक्रमो महोत्सा
हः १४ प्रियमाल्यानुलेपनो यस्तियो ऽ
भिषिच्यो ऽश्वराजस्तमोऽश्वमेध हिविधे
स्तनमात्रा सहजे सजेच १५ सहजमनुप
स्कृतेरुत्तमं भागानष्टौ वहेत् केचिद्दे
तिभागांस्तिनुत्तमाष्टौ वहेत् १६ अष्टौ
नेमध्यमा दौ जवीयान् उत्तमो दिने के
न योजनानि दश गच्छति १७ मध्यमो
ष्टौ योजनानि जीवीयान् षड्योजनानि ग
च्छत्यधनः आधारविरथमुह्ह्स्तानि स्ले
नसो वाजिनः क्षिपेत १८॥ ततो मनुरादिरा
नो भगवंतं कमलयोनिं प्रणिपत्याहुः येना

वाला है एक उपाय करके होता है सो अस्वरूप है यो उत्तम
है सो अष्ट भार प्रमाण लेता है कैयी कहते हैं उत्तम घो
ड़ा नव भार इसी प्रमाण कैच चुकता है १६ अरु मध्यम
तिसने अधा अरु कनिष्ठ तिसनें अघ लेता है यो उत्तम घो
ड़ा है सो दिन करके चाली रूप भागी जाता है यो १७ मध्यम
वा है सो दिन करके यो छोटा है सो वेवी जी
वनरी क्रोश जाता है एकु दिन करके यो छोटा है सो वेवी जी
शामन लकरता है आठ विषै यो कहि है थोड़ी सामर्थ के
रथ कौं चलाता होई घोड़े यो को तिस ते पराक्रम करि दिनकर
देता है १८ तिसकारण करके तिसनें पर मनु यो आदि राज
सो यौ भव सो ब्रह्मा कौं प्रणाम करके कहना भया रे महाराज

© Dharmartha Trust J&K. Digitized by eGangotri

भा टी
३०९
308

पितामह्या ऐसो देश्रसांकों रत्नाके बालेदीय हैन सो अश्वयुग्
श्रुतानेत्र युक्त होयहैन अरुबडे शोक युक्त है औररोगो
करके पीड़ित बड़े दुःखी होयहैन १९ तिसके कहे के ग
यरत अत्रा अश्वनीकुमारोंको कहतेनभये तसीघोडे
यांनिरोग्य करो सो ब्रह्माके वचननें औषधीयां अरुहो
मशांतिकरके निरोग्य करतेभये यवफेर प्रसभगर्भधार
णकों प्रारंभ करने को उद्यत होयया को योसंस्या मर्यादक
रिहै तिनांकरके दियहेसेतान युक्त होतेहैन २० तृतीयाते

वाजिनो रत्नार्थं दत्ता सोमास्तन पत्ता:
परं शोकमवाप्याथ व्याधिभिः पीडितोंसने १९
अथाश्विभ्यां ब्रह्मणो वचनात् होमभेषज
काद्यैर्विज्वरीकृताः भूयः प्रसवितुमारब्धाः
संस्थाचेष्टां पत्नीकृता नैरेवप्रकृतिभिश्च ते २०
तृतीयायामामासाद्यप्रसवो यावदष्टके
निवर्तते च यत्संस्यामनिक्रामति हय
गामी अनुपनीत्वा स प्रसवो भविष्यती
ति २१ व्याभिषकशोषलक्षणाध्यायः
रजःस्त्रियाश्चितः शुक्रं जीवेनापिस्थितं य
दा मणिमत्स्येन पतनादेर्मार्यं च यागर्भसत्त्व
याभवन् २२ शुक्रशोणितसंयोगः पंचा
हान्तीरवबुद्बुदेन् स्यान्मसरागात्कलिलं द
शाह्नात्तद्गेदमभवेत् २३

अश्विनमासप्रवर्तेमानहै प्राप्तहोकरजितनाचिर
करतेहै सोसंतनयुक्त होनेहै यो रनोविषचोतीयोंकेसाथसंग
संगकरतेहै तिनके बड़ेउपनीतीकावाजीवरहितदेतेहै यो रसमर्यादाको उल्लंघके
न २१ यहव्याभिषकशोषलक्षणअध्यायकहेया है
सर्वकोनमा और सर्वकेसमागमकरकेलकड़ीयांने अ
भिहोतीहै नेमहै स्त्रीकीरजः अरु पुरुषपितापुरुषकावीर्य
यदजीवकेसाथस्थितहोवे तबगर्भहोताहै १ सोरुधिर
अरुवीर्यकेसाथस्थितहै योगते पंचमेदिनजल्पकीन्याई स्थि
ताहै सनराश्रीतेचिकट होताहै अरुदशमेदिन गोलाहोताहै

© Dharmartha Trust J&K. Digitized by eGangotri

अरु पंचम महीने विषें मांस के टोटे होय पैदे हैं न अरु दूसरे में महीने
न का नाड़ी शिर संबंध होने हैं न तीसरे महीने मचट ग्रतीयांना
सां नाल गे हृदय स्थल होता है २ चौथे महीने विषें लिंग प्र
गट होता है अरु नाड़ीयां के सहित अरु पंचमे महीने के विषें
त्वचा की स्थिरता और मांस के टोटे और उदर प्रदिपां हो
तीयां हैं न १५ छठे में महीने विषे हृदा फुफुस कफली
हृदय खों मंडूकी होते हैं न नाड़ीयां रसवाहक अरु धमनी
यां शाखाही नाड़ीयां मिं उजोड स्थान हड़ीयां पहे स्थान होते

मासे षष्ठे द्वितीये तु मासे ग्रीवा शिरः खुराः
रमो येन यन्नु पादै नामानस्ये हृदन्तमा १४
चतुर्थे मासि शिश्नाश्च नायते सागुभिः सदाः
त्वक्स्थैर्यं मांसयोश्च पञ्चमे मासि पंच
मे १५ षष्ठे हृत्फुफ्फुसं चान्त्रं सासहास कावमंडू
की शिराधमन्यो मज्जा च संधयो स्थिनि स
समे १६ अष्टमे सप्तमे मासे च मातृसैः पितृ
सैः सर सा एकमाकृता न्यंशुमही मकाम
कसमन्विता १७ अंगप्रत्यंगसंपूर्णो नव
मे दशमेपि वा एकादशे द्वादशे वा प्रसूय
ति निश्चयः १८ सापुत्र गाः केशाः स्मृकृ
ता स्योनि चर्मेव धमन्यः शिरामज्जा सवै
पितृशुक्लजनेनदास्याता १९

हैं न सप्तमे महीने विषें अष्टमे महीने विषें आत्मा के सहित
समस्त हैं मातृपितृके येर सविर्य रज के विभागों करके अरु पं
चभूत अकास वायु अग्नि जल पृथ्वी इनां के योलक्षण
प्रगट उत्पत्तिनां युक्त होता है नवमे वा दशमे महीने वि
षें अंग अरु प्रत्यंग्नों करके युक्त होता है ज्ञामरे वा वार मे
महीने सन्तीय है पहे निश्चे है १८ पहे अंग पिता के वीर्यते
होते हैं न साउ नाड़ीयां खुर केश वाल वीर्य हड़ीयां चर्म मधम
नीनीयां नाड़ीयां जोड़ेयां के अरु मासल हूको मसीह से डे
कसना वरीहृदय आदी यकृत वलि जरायु पहे समस्त

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
५७

307

नाकरनेकरकेजाणो ॥ यदिशुक्रवीर्यअधिकअथहोवेतब
बच्चेरअधिकवीर्यवालाहोताहै यदिरजआर्तवअधिक
होवेतोकिशोरीबच्चेरीबहुतरजवालीहोतीहै यदिदोषन
ल्यहोताणतबतनुअसकमोडाहोताहै १ कफकरकेगोरेका
श्चवर्णहोताहै अवरक्तकरकेलालरंगहोताहै पित्तनेका
लावर्णहै अरु रक्तकफतेदोवर्णकाहोताहै ओरसभव
र्णरलेमिलेदोषोकरकेहोतेहैन २ यहअष्टप्रकार
गर्भकाध्यायहुयाहै मर्मशिरानाडी स्नायुनाडीअस्था

नोसकृपिरंक्रमंसोहातुकाशनावरोहृदयं
घ्राणाच्छुकवत्स्त्रियाशुरितिमास्नेविद्यात् १
शुक्रेकैःधिकेकिशोरशुक्राद्यधिकेमहार
नोभवति तेयानदाकिशोरीमक्लिशुमके
समेयातं १ श्वेतकफेनवर्णःशोणोरक्तेन
कालमथपित्तात् रक्तकफादिवर्णाश्चा
पामिश्रदोषाश्च: २ गर्भमष्टविधानाम स
मोत्तरंमर्मशतंशिराःस्नायाशिस्थिसंधियं तथा
विंशतिसप्ताङ्गःसंधिमर्माणिवाच्चिता ३
नाववस्नायुमर्माणिअस्थिनामेकविंशतिः
शिरामर्माणिचत्विंशद्वेसमेनरशाने ४
मर्मजवाधिविलेयपवमर्मविनिश्चय कथि
तांगसमर्माणिषोडशाक्तिमहाविरणा ॥

सोहड्डीयां इनांकीसंधियोंनोडेकेविषें इकसौमनहैतेंहै
नतिनांकेवीचसंधियोंकेविषें वीहकैहैन चोटेयोंकोंअ
ड्डनतेंहिस्नायुमर्मकहेहैन ओरहड्डीयोंकेइकी मर्मस्था
नकहेहैन ओरहड्डीयोंकेइकीमर्मस्थानकहेन अरुमांस
मर्म ग्यारांकहेन अरुशिरामर्मतीहीकहेहैन इघानराश
मोनरशानमर्मकहेन ४ अरुशिरानाडीयाचोइकेहत्ना
रेहैन अरुअस्थीयांचपमर्तेनें सटकहोयांहैन अरुरोम
थानमेंकोइकहेन ओरस्नायुनाडीयां नतेंसेकाहिहै
५ ५ ॥

कह्ना कौं ग्रह श्रंगुलप्रमाणलेके मिलो बुद्धिमान् योमध्य
म होइ है नतिह्नांकानिश्चयकरणकहै याहै ५ जिसकाश
ग्रभांपिछी ---- शुक्रहोवेसोसतयाप्रमाणहै ग्रह पिच
लापासापंदराप्रमाणहै वासनाशेहोनाहै ६ निपहैशरी
रकानिश्चयकहै याहै बुद्धिमानवैद्य वचेकोनलावे ठंडे
वागर्भकरके उनकौंदेशाकेगर्भीविषैं ठंडेसाथ ग्ररुशी
नकालविषैं गर्भजलकरके जिसकोपरै मानाकेस्तन

सिंहास्यसहदेवस्थमथवा मूलं बद्ध्वा ष्टिमानवये सो
मकोलः षणाचर्तिनेवस्तासुशानानि च ४
कल्लानोष्ठं गुले भिन्नान्तरं गोविभज्ञे बुधः
न हि समध्यशरीरस्यान्तरगाणे विनिश्चयः ६
पीपयोगान्ने च सर्वाङ्गे हन्नपंचदशैव न
हृदन्तणमाजैपवंपचदशानि च ७ शा ८
रीरविनिश्चयः गर्भनाने निर्गते बुद्ध्वा वारि
णापरिषेचयेत् कृत्वे विलाप मतिमान्
शोनेमोस्येस्ववाधुनः १ ग्रथमानस्तनौ
पौनौपायपेत् परिरह्यनां विलग्नेसुव
गर्भेषुजराशुः स्यपतनस्य च २ समानेमेना
निसेपार्वोभेषजानसुपकल्पयेत् योनिक्ष
मीनेनवनीशंखेषुच्छीशनावरी ३ भार्ग
वीवचविशल्यावत्यालांगलिकामपि प
नसहृत्स्यसंभारंसुर्णायेन्सपिं षणासह ४

ग्रंनेटयां होया उपयलेपाणिकालेपकेरस्ननपिलावे येक
रगर्भलगारहै होया ग्ररुजेरके हस्कीनरांनाहिपयरेया पहैश्री
छपदेवे २ मालकंगुणी नेनवलशाबोवली वटी सनाव
री पहैसमभागलेवे नीलरवां टंदमदाने दिनइ कालहा
री इनांकौंकिटकरकेपीसे घोइकेसाथ ४ इसकेसाथ
उपनाहसेकदेवे इसकरकेगर्भमो होनानाहै ग्ररुजेरगा
रजानिहै ५ ॥

॥

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ टी॰
३०८
308

अरुइसकों गुड़के साथ थोड़ी कों पिलावे और बिल्वकी गिरी पी
सकरके कल्कनोयजल साथपान करावे अरु कलहारीकी ज
ड़ गुड़साथ देवे अथवा सिंबलकी जड़ोंका कल्क दूधके सहि
त ७ थोरका इसके साथ थोड़ी नारी देवे इसके साथ सूई दीयो
ड़ी शुद्ध होजानी है अरु जेरनेवी मक्क होनी है ८ अब तन्यउ
छूटगयकी शुद्धि कहताहै जामरा॰ काकाथमकोरमिलाय
कें पिलावे ९ पलाव बड़ीपिप्पल मलटरुवल इनोंसिकइ

ततः शिरीषबीजं वा पुष्पं केसरं वाप्युपनाहयेत् पचे
द्बिल्वमूलेन गर्भाज्जरां शोधयन्ति च ५ अथाम्बु
न्याद्का शाकेनाम्भसा प्रतिपाययेत् बिल्व
जानां सापिष्टानां कल्केनाथ पाययेत् ६
विष्कम्भे धनमेषु मेलागल्या मूलमेव वा
अथापि शाल्मलीकल्कं सर्पिषा वससम्मि
तं ७ पलावालकसंप्रकमस्थापयेटपेमेव वा
पवं तस्मुञ्जीमामाति प्रमत्तकाव जरायुषः ८
अथ त्वक्स्नायुवसा मित्रोरसपरिशोषयन्
मेपुरुक धायधनोदेगानगरत पारिपाययेत् ९
मत्स्यमत्स्यग्रापकाम्बुमेसमधुकोटवरसूवः प
लाल्पत्तनेरौद्रमवातिरामहसाथयेत् प
करागोपिनं सवंशाकेवाम भूमिखिनं वह
वा पाययेद्धः कणापयस्तन्यशोधनम् ११
अजानीभद्रमस्तं वस्पृगावेरं च शाकपान् दे
वमारीविडङ्गानि चित्रकं देवदारु च १२ ॥

पीपके पेर कूटके जलकेसाथकाढे फेनपकगातरखक
रके दूसरे दिन खंड और मरवीर गलाके वैद्य थोड़ी कों
पिलावे पके है का दूदकों शुद्ध करनाहै ११ और जीरा
नागरमोथा सेड सेरवा तिमरु वाय विडंग चित्रादि आ
र १२ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

सबों हरदल दालहरदल बदलबेलसहांजणाइनांकों
कांजीकरके कल्कबनाकेभोजनकेसाथदेवे १३ अरु
गुडतेलकषुकनीतणामदिरापिलावे इसकल्ककरके
पुष्टउत्पन्नहोना अरुश्रेष्टहोनाहै सवीरसखणखल
यकेवाचटणीचटावे १४ महीनेनैलेकरकेकिशोर
अवस्थाचारवर्षनकरदेवे तिसकेउपरांतभोजनदेवे

पिप्पलीवदरीरेववपाठाशिग्रुवपेषयेत्
कल्कंशोटीरकेणैवसंयोगप्रतिभोजने १३
गुडतैलसमायुक्तंनीलंगवाषायपेत्सुरां
अनेनकल्कशौटीरकेणैवसंयोगनाश्वा
याःप्रयुक्तेनविज्ञानता १४ दृष्टविमद्य
तेहीरमतुष्टचोपनायने होइवनवनी
नेवसंगात्प्रतिलेठयेत् १५ मासमेकंकि
शोरंतेननोभोजननावरेत् गोमूत्रागेय
वांग्बासमिद्धंऊपघ्रमाविते १६ मधुस
र्पिःसमायुक्तंकिशोराणांप्रशस्यते प्रवि
हारम्रगाखास्वासस्सर्वपवाभिसंमताः १७
सम्फवोहनसंपुक्तामभुक्तोरविमिश्रिताः
दानधात्रीकिशोराणांसद्योबलविवर्धनः १८
एवंकिशोराःवर्द्धन्तेवलवंतोभवंतिच ते
उद्देसिद्धिमोरहोकारयेच्छास्त्रकोविदः १९

कणीक अथवाघड़ी इनांकोसिद्धकरके दुग्धकेसाथ १६
सवीर देनेकेमहीनेकिशोरवस्थावालेकोंचारवर्षप
र्यंतकरश्रेष्ठगुणाकरहै १७ सोविहारयोग्यहै घोड़ेके
नतिनांकोंश्रेष्टहैन अरुमत्त घोड़ेसवीर उदके
साथा किशोरघोडेकों देणयोग्यहैनयहै सनावीव
लकोंवधानीयांहैन १८ इसप्रकारकिशोरघोडावधर
ताहै अरुबलवानहोताहै तिसकेउपरांततिनांकीसिद्धि
वासे श्रमकेनाशनेवालेरहाकरावन १९॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा हो
३०९
309

सेतीसेरेयांकोअनीभृगतौवै अरुमार्गोरानदीपजलायेआदा
रवे अरुयोप्रतिपानकेदेनेजितांकरकेयोस्रहोइयोगी
हैतिसकाकोष्ठसजेरे २० मेलठमयामरवस्तुडरहै मा
तकालविषेपिलावेयोगीकों अथवावारुणी मदिरानु
इतैलसथमिलायकरके देवे वेद्यः २१ प्रतिपानकेपवे
व्यपदेयो योगीनाईचामरवारोकौंदेवे पवनमालगोन
वमदिरापिलावै अथवागोमकरकेजलपिलावे २२
अरुप्रतिपानदोष्णबेवारुयानी देवे पेष्टकीनामवारुणीमे

मिनैः सिजाये धूपैः प्रदीपैः सर्वेगात्रिकैः प्र
तिपानैस्तथा कोष्ठप्रसन्नापाविशोधये
त् २० पष्ठीमधुविकेदकं मवो है पायये द
या पष्टिकीवासरांदद्या इ इनेलेन संयु
ता २१ अष्टायेदापयेत्पासमुज्जोलौ प्र
तिपानके नोष्ठतोपाययेन्मा सं यथाकु
क्षितेजले २२ द्विरात्रं वा त्रिरात्रं वा प्रति
पानेप्रदापयेत् पौष्टिकं प्रतिपानेनल
न्यकोष्ठवमुदति २३ यथा ग्रामेवि
स्याद्धमाकृत सप्रशाम्यति एवं मूत्रशारी
रं तोपापयेच्च हन्तोहया २४ चतुर्थेदिव
मेवं वन्तो यं चैव म्रतेपिवेत् ततः संमूत्र
कोष्ठाणारदे भवति लक्षणं २५ यदानुवेद
नाश्राणापानीम मौ हर्कं न वा मोणि ने वा
कफोमिश्रं यं वा रक्तमेववा २६ ॥

दिरापानकरकेसन्नाइदअरुकोष्ठशुद्धकरताहै इसप्रकार
शुद्धशरीरवालीयोगीकोंयोगीपिलावे २४ तिसकोंचौथे
दिनविषे काउकेनलपिलावे जिसके उपरांत शुद्धकोष्ठ
शुद्धस्वरूपवालीकाललक्षणकहे हैं २५ यव श्रोणीलक
विषैकीज्ञानाहोवे अरु योनोविषें अथवागर्भमें जलना
बलेवारुधिरनानिकले अथवाकफ साध्यपाक नाही
वे वारुधिरकप्रसाध्य नाहोणा २६॥

© Dharmartha Trust J&K. Digitized by eGangotri

अरुनिरोगपनाकेलक्षणोंकरकेयुक्तनारणकरके उपा
यकरे गर्भकरकेयुक्तचोडीकेउदरविषेंवायुवधयानाहै २१
छूनयोहैसोवायुकोयथार्थचलनाहै अरुउगयकोशुद्ध
करनाहै तिसकारणतेंस्नेहहोइचोडीकोछूनवङ्गतगुण
करकैहयाहै १९ अरु घासकेविषेंदूवीयश्रेष्ठहै तिसका
रणतैंचोडीकोंदेवे अथवा हरदल दालहरदल माश
के अनुसारछूनकेसाथपिलावे २० तिसकेउपरांतज
वास वेडेसाथपिलावे यवदशमेदिनांकारोपदेयो

ग्रोगस्थलक्षणेणयुक्तांखातांतामथ कल्पये
त् गर्भेणानग्रयुक्ताया: केष्टवायुरुदीर्यते २२
कुर्याद्वातानुलोम्यं च तस्मै वा विशोधयेत्
तस्माद्धृतेपशस्तं व गस्तकापानमेशयः १९
यवसां तेहिता स्वीतस्मादेनां शदापयेत्
हेनिशेवाशिवामाजेपाययेत् छनसंयुता २०
तत्परेपाययेत्पाव के संपिबासह दश
मेहनि से पोम सवत्सापाययेद्दया २१ स्नल
गंध वमाल्यं च धूपनामपोशदापयेत् २२
सूतिकोपक्रमः यच्चरोगसमुत्थानोवाजि
तोपविकित्सिते तेषामपिचयस्माकं बु
द्धिमद्भिर्ब कुर्ध्ब्रुतेः २३ शरीरेंद्रिययानवि
दोषाप्रकृतयस्तथा वालानांसमरुतोवे
वतल्पकृपाभवेतिहि २४॥

सहितवछेरेकेदोनांकोंपिलावे २१ अरुदोनोंकोंसुंद
रगंधिपुष्पमाला धूपधरवापहोंयाकोंदेवे २२ यहसू
तिकाविषेंचिकित्साकहिहै येदोउयांमेंरोगांकोचि
कित्साहै तिनांकीबुद्धिवालेयोंने अथशास्त्रजाणने
वालेकहिहै २३ शरीरअंगप्रत्यंगादि इंद्रियां नेत्र इत्या
दि याम रसादि अग्निजठराग्नि दोष वातादि प्रकृति
यां यहसम बालकांकों अरुवडेयांकों बराबरहो
तेहैन २४

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
३१०
310

व्यानि सोई रोगरूप हैन सोई चिकित्सा हैन सोरकाश सोर
पिन स्लेष्मके सहित होइ हपिर १५ भिन्नभिन्न विसेष
केवलका प्रमाण काकाहिणकहते हैं वर्षके चोडेको
इकहैसा मात्राकहिहै अरु दोवर्षकेकी टोहैसेनारो अरु
त्रयवर्षकेकीत्रपहैसेमात्राजाणो अरु इसके उपरंत शुरुमा
त्राकाप्रमाणदेवे १० पहलेकिशोरचिकित्साकहिहै अन
म— छवडेचोडके हडीयां अरु दंडीकेसहित इसकाप्र
माण इकमणने नारांसेर साडेत्रयपाकहेया है अरु मज्जा

नान्येव व्याधिरूपाणि तान्येव त्रिविकित्सिते
सप्तवर्षान्तरेष्वेन सक्षेमान साधारणानि १५
विशेषः केवलेनान्नमात्रयाः परिकल्पते
वर्षेनार्धभवेन्मात्रा द्वौ पादौ चार्द्ध हायने ३ २
नपश्चेहायने देयाः प्रोक्ते यानेनापरं १०
किशोरचिकित्सा अन्नमस्यास्थिमेहानः
सहदषानैश्चतस्लस्लत्वापंवदशापलानि
मज्जनस्तुलाद्वयं पंचविंशतिपलमुक्ष्म
न्नवबमस्तिकेस्याशनानेस्तनुल्याः १८
मांसस्यपलसहस्रपलमष्टौशतानि व
शिरायास्तुलाद्वयंतास्नायूनांमाणः समस्या
ट्केनि स्रोमेदसस्तत्समता १९ कफस्या
र्द्धकीपित्तस्यवकाशपरिमाणः पक्वा
शयेचन्प्रांतेपशिषस्यचशानेशानेचमलेश

सेर पंजो होनी है अरु वीर्ये धा इसेर है अरु इनाहि अदपासेर
मस्तिक मस्त संगहे अत्तला ग्रका प्रयन्तला साठेसन नदी
सेरहै इव अरु मासका प्रमाण पंजमण अरु पंजीसेर अरु
शिरानाडीयां सेर पंजी अरु लहू मण इके हेरसथान
वेकीसेर कहेया है अरु मित इसके वारांसेर कहेया है १९
कफ चोडेका चारसेर कहेया है अरु पित्त वारसेर अरुवा
युका परमाण चारसेर कहेया है अरु पक्काशय विषं लिद
मण इकसेर दशा है अरु आमाशय विषं सेर पंजी अरु मल

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रंथों का अरु पक्षान्तर कुसुम सकलेना हृदय मूत्राशय सो
हून लिंगमुख अंड पेट हैं सम भृगु प्रमाण ते सार पाई अरु
मवाल सांधे वा गांसे रहै न अरु छेदन अरु चार समस्त
शेष ल सरै वा गांसे रहै अरु रक है सा घट सब्यम चौड़े का
५। अरु अन्न मन ते अर्द्ध भाग हीन छोटे चौड़े का कहै पा है
पंच पृथ्वी जल अग्नि वायु आकाश ए है पंच अष्ट
अष्टांग चिकित्सा शल्य शालक्य कायचिकित्सा भू
तविद्या कौमार अगद विषतंत्र वाजीकरण रसायण

रसायणक तन कुसुम सकाले पत्र ध्यान हृदय
मूत्राशयाणी ५० मेहे न सु क्षाना पंचतत्
त्वाश्रानननेनाः छेदनेव चन्नः शानेशाने
पवसतमाश्वः पलमूदलामिपादहो
नोमध्यमः ५१ अर्द्धहीनो यथोपीन मध्यो
कर्षणात्रयो नव वानलामाने शारीरजे २
तिशारीरतलामाने पंचाष्टौ त्रीणि पथ हेव
त्वार श्राविपोषनः ५२ नव हाटशावत्ता
लाचत्वार श्रभवेत्रिषक् शालिहोत्रीयश्री
कः ५३ सकलेनशार्षसंग्राहकपनउक्ते
भवति अष्टपदार्थमपरिच्छिन्ने स्पाणुवै
रः ५४ पनेषु ष्टस्पादार्थपुचिकित्सिता
मागो पांगास्मान शैपादार्थांतामाभवेद
घःसुच्यते नत्रये वपंचवर्गः पृथिव्यतेजो
वायाकाशादीनामिति ५५ पतानिपंच
मूतानियाभिः शरीरे निबद्धमिति ॥

है अष्ट है और अष्ट पाजरसादिमन अरु तचा पहे अष्टक
है नत्रय वात पित्त कफ है अरु हार सु भूत्रादि ३ चार मा
ग वानादिक शनि चत्वार वंटने नरा मुन अंड ऊन ३ छिद्र
पहे चार और नव शावणादि हाटश सक्त्यादि पहे मा
ग सो वे घरे ५५ पहे मालो होत संग्रह है सो सब संग्रह
का मार कहे या है ५५ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

भा॰ टी॰ ३११

311

इनोंमें षट्पदार्थों विषें चिकित्सासंग्रहउपयोगकाहै है इनोंमें
षट्पदार्थोंकों नानतेकरके वैद्यक कह्याहै तिन्होंविषें पंच
पंचवर्ग पृथिव्यादिपंचमहाभूतकहेहैं इनोंकरकेश
रीरबंधनकरेयाहै अष्टवर्ग अष्टधातू त्वचा त्रिवर्ग वा
तादि इनोंकरकेशरीरधारिहाहै दोप्रकारआहार अरु उचार
चार स्वेदजादिभूतग्राम हैं स्थावरजंगमभी स्थावर
वीरुधा वृक्षादि जंगमा मनुष्यादि यहपरस्परऔषध
हैंन अरुपरस्पर आहार भोजन कहेहैं ४७ अथनवक

अष्टवर्गाः षोधावनवाः त्वग्रसरुधिरमा
मांसमेदोस्थिमज्ज शुक्रास्त्रिवर्गोवातपि
त्तश्लेष्माण एभिः शरीरंधार्यते द्वाविम
मतेआहारश्चोचारश्चनिआभ्यांसकामान्
शरीरस्यमानसृणातिकृतादोषाश्चतार
प्रोच्यते ४६ जराम्रजोजिरसाम्वेदनश्चेदना
श्चतुर्विधोभूतग्रामः सभूतविविधोजंग
मस्थावरश्चमत्वाभ्यांजंगमाः स्थावरा
वीरुधादयः अन्योन्यामभेषज्याः अन्यो
न्याहारसंज्ञिताः ४७ नवप्रोच्यतेप्राणोपा
नःसमानःउदानव्यानश्चमनोहंकारोबुद्धि
रिति एतेमनोदोषाजवाश्चानेकमवर्तकनि
वर्तकाः ४८ द्वादशप्रोच्यतेनिमित्तदेश
कालाउत्साहसामर्थ्यं अनलपवनमभि
योदृश्यशरीरबलप्रकृतिरिति ४९ इ
निक्तश्लोकव्याख्या ॥

इनोंमें प्राण पान समान
उदान व्यानयहपंचवायुहैं तिन अहंकार बुद्धि औरमनय
है मनोंकेरोगोंकोकरनेवालेहैं अरुहटनेवालेयहहैंन अवस्था
दमयोहैसोकहतेहैं निदानकारण देश काल उत्साह
ग्नि पवन पंचमहाभूतप्रकृति यहबारहहैंन इनोंसभ
नोंकोंजानो यहगुरुकटनश्लोककी टीका ॥ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

करकेअर्थकरेयाहै औरयोऔषधीयांकोवीसिद्धकरे
सोचत्वारः चतुर्वैद्यकहेत चत्वार कहतेहै आचारपाद
चिकित्साकहिहै एकरोगी दूसरावैद्यः तीसरोऔषधी
चौथीपरिचारकसेवाकरणेवाला होइहै चारपादचि
कित्साकहिहै ५ रोगीकैसाहोवे बहुत व्याकुलता
होवे अरुअग्निबलवीर्यवालाहोवे सहारणेवाला
अरुबडीआयुवाला अरुबहुतकुपथ्यमैंरोगीना अरुस
त्वशीलस्वभावस्रुतकहोहोवे वैद्यकैसाहोवेशास्त्रसम

एतानिभेषजान्येवमायपेचत्वारःसौख्य
ते आतुरभिषक्भेषजपरिचारकाश्च
त्वारःपादाचिकित्सादयः ५ सत्त्वान्वि
तात्माऽग्निबलवीर्यसमाभिजनतदीर्घा
युर्नात्यर्थातुरः सत्वशीलसंपन्नः भिष
गुपस्थितशास्त्रार्थबुद्धिप्राप्तोदृष्टिकर्मा
ध्यवसायप्रयोगसामर्थ्योपयुक्तः सर्वति
शीलसंपन्नउद्यापोहप्रारद्धोपमत्तः
सौम्यश्चेति ५१ भेषजमपिनहिमानप
न्नबुकीटभांडादिदूषितंवाप्यतिहवेत
चातिबालेयथात्वेजातेसम्यक्कालापसे
गृहीतंप्रयोग्यमिति ५२ परिचारकश्चस्व
नुरक्तःशुचिर्दक्षोनिपुणः सदावचनिमन

नादहोमनिनांकेअर्थजाणनेवालिबुद्धि अरुचतुर अ
रुचिकित्साकेकार्यविषेंअभ्यासवाला अरुयोगकरणे
विषेंसमर्थवाला अरुसबीरतीवालाशील स्वभाव अ
रुग्रहण त्यागइयोंमैंनिपुन अरुधर्मकेजानणेवाला
अरुसौम्यप्रकृतिस्रुक ५१ औषधीकैसीहोवेंयेधपप्राप्ति
जलकीडेआंडऊंनोंकरके दूषितविकृतनाहोवे अरुनाति
हुत बहुतखिरकीनातेबहुतबालकहोहोवे अरुअपणे
समयविषेंजमीदीहोवे अरु यथाविधिकरके घुटीदी
होवे सोहदवीकहीहै ५२ अरुपरिचारक रोगीकोटहु

© Dharmartha Trust J&K. Digitized by eGangotri

भा
टी
३१२
312

लकरणेवाला कैसाहोवे रोगीकोप्रीतोयुक्तहोवे पवित्रप्र
कृतवन्तरप्रकृतिविपिविषैनिपुनहोवे अरु हेदरवाणीकरयु
क्तहोवे अरुनिमयेदिकायंमे उद्यमीहोवे अरुयारोगीके
हितकहेयाहेजिसकोहितकरकेकरणेवालाहोवे यहे
योचारपादकहेहैतसोसमग्रहोवेतोसिद्धिहोतिहै अरु
इनोकाविषैकमतीहोवेतोअसिद्धिउलटाहोतिहै ५३
यहेचारपादचिकित्साकहिहै रोगदोप्रकारकेहै एक
शारीरहैदूसरामानसहै योविकृतिकोकरेसोविकारहोवे

धतोयथोक्तहितकर्तोवेति यथोचतुर्गुणपा
दानांसंपदासिद्धिसमस्याविपर्ययःस्यात्
५३ इतिचतुष्पदचिकित्सा शारीरमानसौ
विकृतिजनयतिसविकारोजनयत्यागंत
कश्च वातपित्तकफैरुद्भवः सयतयःशा
रीरमानिजः ५४ असमास्तविषाग्निभोआ
गंतकः इष्टनिहतोचानिष्टसलाभात्मा
नसोव्याधिरुपजायते ५५ असावप्यागंत
कएव यदेविविधंरोगकारणमिति सह
जागंतकोविकारः ५६ यानवःप्रोक्ततेवृत
विधाद्यरजोरसःकेपानवरणभोःसमाय
नःस्यानेतिक्षति दिनेरत्नोयावत्सेवापय
वर्णोभवेत ५७॥

सोआगंतुकहैयाहेयोवातपित्तक
फरक्षहोकरकेहोताहै सोशारीरजहै ५४ अरुशस्त्रकेमा
शस्त्रचानुविषअग्नि इनोकरकेयेहोणसो आगंतुककहे
हैत यावांछितवस्तुकानाशअरु विरुद्धवस्तुकी प्राप्तिइनो
करकेमानसरोगहोतेहैत यहेवीआगंतुकहै यहत्रयरा
प्रवमनयानकहतेहो चारप्रकारकायोआगंतकहै ५६
ते भोज्य चोष्य पेय इनकेलोणकरकेउपनहोयादायो र
सहै सोकफवतरकेसमरोगवालाचोइकेप्रिमस्यानविशेषिय
नमारसनीसेरवा चोषेहि तलालकमलकेसमवर्णवाला
होजानाहै ५७

सोपेटरूपं चर्ममें अथवा कोठेमें दिन् पलाके फल टपकेसम
रंग होजाता है अरुसो रस तनमें दिन् ३६ — पर्यन्त वही जठरा
ग्नी कर पाक होता है जिसके तुल्य रंग होजाता है ५
सनयो सो रस तनमें दिन लहवरणजाता है ५८ इसक्रमतें
रुधिरतें मास मांसतें मेद होता है मेदतें हड्डीयां अरु ह
ड्डीयांतें मज्जा गिरी अस्थियोंमें अरु मज्जातें वीर्य होता है
और रस नसोंतें हि नाडीयांके भेद सिरा धमनी स्नायु और
केश चर्म रोम सूक्ष्मवाल यहे सभक्रमतें उपधातु होतीयां

पंचमे हनेनमघ्वेवाकिं भुक्ताभःसम मेदनिश
क्रोणपक्वाभः पचे समग्राह्वार्दसारकंभवेत् ५८
रक्तांमांसंमांसान्मेदोऽस्थीन्यस्थिभ्योमज्जाम
ज्ञनः शुक्रमिति सिराधमन्यस्नाः स्नायुर्धिके
शाश्मश्रूणिरोमाणि तानि मनस्य जायते ५९
चक्षुःश्रोत्रंघ्राणंजिह्वात्वक्पञ्चानिपञ्चेन्द्रि
याणि पञ्चभिरिन्द्रियैर्जीवो विषयांश्रियेसुख
दुःखेवेदयति ६० इतिधातुज्ञानानि अनन्त
रंरोगज्ञानमाख्याने त्रिभिःप्रकारै रोगाणा
नीयात् दर्शस्पर्शानतःप्रश्नेनरोगी
समभ्येतःस्पर्श प्रश्नंपरिवारकमेवद्केन ६१
किमनेननाशितं किंपीतं केन कथं वा पापि
नकथंस्थाने संविशति कथंशेते तिष्ठति कथ
मतिकथमास्ते कथंधंके कथंप्रपवनेते ६२

हैंन ५९ और पंच इंद्रियां नेत्र कर्ण नासा जीभ चमड़ा यहे
पंच इंद्रियां हैन इनां इंद्रियां करके जीव प्यार दप्यार
सुख दुःख इत्यादिक जानता है ॥ यहे धातुकाज्ञान क
हेया है इसके उपरंत रोगांका ज्ञान कहते हैं इनां त्रयप्रका
रोंकरके रोगयां हु जानेनाकों वे यजनण एक रोगीको देख
करके अरु देहकों स्पर्श करके अरु इनाके विचार करणेक
रके रोग जाणीदे हैन चोट्टेकी रोगके हाथ देयां पहले यो
चोट्टेकी हलक रणेवालेकों पछे का ... इसने आला

ले

दाहे अरु कापीनाहे अरु कौकसनेक हांलेनाहे अरु अपणे
स्थानविषे कैसै वे हदाहे अरु षडाकेसैरहिनाहे अरु कैसै
सैनकरनाहे स्थितखडाकेसैरहिनाहे अरु भोजन कैसैकं
रनाहे अरु विलनाकैसैहे जलकैसैपीनाहे अरु वासकैसै
खोनाहे अरु पक्षावलि दकैसैकरनाहे कवरसकोमार्ग
विषे वाभार पायाहे किनने हरलेनाहे किसवाहन वाकि
तनाचिर चलायाहे अरु रसचोडीकोनसीरक्याहे इसन
रोपूछकरकेरोगकोंजाणे इसै देखकरकेरोगजाणे

कथमयंपिवकशेषवसंनिसेवनेकथंम
वपरोषाणीकुरुतीकदापंवाहनः किंयया
नः किमयंकियत्कालेकिंपदाहनः किंशो
लेनरगस्सेनिपर्वंहष्वाविकारमुपलक्षयेत
टष्वारोगंजानीयादिति १३ पनउष्मने स्था
नेशायनेनिश्रमकृतिर्विकृतिर्वीयकृत
कर्षोपकर्षकर्मासमशोणितेनापचयः १४
मलः परावः प्रतिमत्यउचेताभेदक्काया
वपोरूपमितिटष्वारोगंजानीयादिति १५
नरश्चनेस्पर्— रोगंविजानीयादिस्पेनदृश्य
नेष्टषेदंष्टवाबलावलेगात्रंसंकोचनेप
स्मरणेनासमानेरोघमेरोमदृष्टीनेमरवमव
नमरदाकृणप्रीतोमस्तमिति १६ ॥०—

लेवे परेचोरेकेकहे सपानसैन सभाव अरु विकृति अरु त
अरु बाप मद दोष वृद्धिहानि और मास अरु रुधिर को
वृद्धि अरु हीणता १४ अंगसोथ स्पर्शकोरा देहका और
अंगरुकजाणे अरु उजाणे अरु वर्णविगडजाणे अरु छा
याकोभिभेद अवस्था अरु स्वरूपएह देखकरकेरोगजाणे १५
सो कहेयाहे रोगीके अंगकोंस्पर्शकरकेरोगजाणलेवे अरु छे
दे अरु देखे देखे अरु बलनिबल और देहके अंगोंकासंको
चविडहोजाले अरु विस्तारहोणा अरु नासाका वेदहोणा
परेअंगोंके कोणने सख नस खहोणा अरु कोमलताशरी
रकी अरु करडे आई शीतलगर्म परे १६

© Dharmartha Trust J&K. Digitized by eGangotri

विचार करके लक्षण जाणके रोग पहिछाणे पहिले उपचारों का
रोग का पहिछान रोग का ज्ञान है १७ अब दुर्मन विमन घोडे
का ज्ञान कहते हैं जो दुर्मन घोडे का स्वार वा स्वामी तिसके
साथ रोग को और विरोध वैर पीडा और शत्रु के आगम
कों हृदय शरीर के राज कों अपवाद देश त्याग इनों को लभता है या
दुर्मन घोडे वाला है सो घोडे कों अजीर्ण रस तें अपथ्य वा मा
रने करके वा बहुत थके में करके अथवा खोटे स्थान वि
षे सोणे करके घोडे यां कों इनों कारण करके दुर्मनता है

पराभवो पलक्षयेत् पदैर्विविधै रोगज्ञान
मिति १७ दुर्नामनो ज्ञानमथाने विकारैर्वि
ग्रहैर्वा विपरचक्रागमेन तथा प्रवासमरणप
रिंपनः सेति दुर्नामनो मतः १८ अजीर्णाना
दुनाहाद्यै दौर्मनस्यं श्रमेण वा दुःस्थानश
यनाद्याद्वाजिनाम पलक्षयेत् १९ ला
घवे पवसे कोहासः सुस्वप्नपरीषता उत्साहः
सौमनस्यं च जीर्णे भवति लक्षणं २० दौर्म
नस्ये स्यात्तथा स्वं भोमूत्राणां मलग्रहः
पवसे भ्रुप्रकोपाच जीर्णे स्याल्लक्षणं २१
अवेदनामदुर्गंधिश्लेष्मणाचाविवर्जिते
तथा पवमसर्वाणां वपकमिन्स्व अनेकशन् २२
इगंधं चाविवर्णं च श्लेष्मणा परिवेष्टितं ॥

खीदी है क्या होती है १९ देह हलकापना होणा और वास खाणे
विषे बांछा रुचि होणी और मल मूत्र यथार्थ आवणा अ
रुचि नाविषे उत्साह उपम हर्ष होणा मन सुंदर प्रसिंन हो
णा पवे भोजन पचे दोष के लक्षण हैं २० जिस घोडे का म
न प्रसिंन ना होवे और अंगभा के उजाणा और मल मूत्र आ
णा अवाज बंद पकारो पहोवे और वास खाणे विषे इछा नहि
होवे पहिले अजीर्ण का स दोष के लक्षण कहे हैं २१ नि
र्विघीं दुना होवे और मरी गंधी ना आवे और श्लेष्म नेरा हि
त होवे और तैसा ना पसा पालो दा होवे और रवर्ण विष्ठा
लिदय को होर कहि है २२॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा
ष्ठ
३१४
314

योउनेंघीवाली अरु रंगविगडेयादा होवे अरु कफ केसा
थ लपेटी होवे अरु रस सकीटी अरु बोरी होवे अरु पीडा
करके होवे सो लिंटतब आमयुपचकहिहे १३ जिस
वायु समपयाशंना होवे कवजी मंदाग्नि अरगस्याकेडे होय
अरु आदरां विविंशह होवे ओर पीडामोना निस्तोद पीडा
जैसे सरकीनरां तुवणीके समपीडा ओर दोनों अंगोंसर्व
भागपममभागतिनोंविषुपीडा १४ अरु पायककावि
होफिरे अरु कफपित दोषांको ग्रहणकरना है निरंतर १

खरेदेहे समस्ले वणुरोसंबतदामक १३ ब्रा
ध्मःस्मोविंपथानि सादलमावक्रमवे वे
दनाशोफानिस्तोदे रवसागोहिपोऽमो १४
विवेरेतुगव वापिसरूक्ष्मानिकपिनाम्रुशा ते
हाघेह्रिमापानि वेद्रामेवादपेपधा १५
निरामोविषदोऽरू होऽनंगोपस्याल्पवेदनः
विपरीतगुणैर्यास्ति विगपेयानि विशोषनः
शनिरुमेनाजाने यथाशोदशनोप्यामन
विनः समस्लोमावलवनसबवषांवनः
समेहनाः १ संपूर्णोपचवर्षाणसमशृणव
लयोवनाः यावधोड्समवर्षाणि गर्भरूक्षाः
शजिनाद्वृषाः १८ कावोज्ञानांकुलेनाना
लयावानापुनादयाः दानादानानगोगेभुक्का
ह्रषाःकर्मसमजिना १९

अरु सोई हादिरदबों कारके
वपनेहेन जिसकोआवरछादकरने है जैसेवदलकाउदय
विषेचंद्रमाहै जिसकान्याई १५ आमनैरहित विषदनिमेल
हलहलअरुरंगपरहिन अरुपीडाथोडीपरहै विपरीतउलटे
कर्मोंकरनाकरके वपनेहेन अरु विगपयिंरदबोंकरकेशा
नहोनेहेनेनिश्चयकरके १७ परंतुमनवोडेकाज्ञानकरहेया
है थोडापयार्थदर्शनएसाहै जैसादरखणीयोगएअरुपीय
वाला अरुहेदरमोटेअंगोंवाला अरुवलमुकअरु वस्मवेग
गानिपुरक अरु यथार्थसंहितमिलेहोएरे अंगएदेसम पंच
वषकेवोडेके संपूर्णहोनेहेन अरु वलने जानीयहेसोलावर

नोठी बड़े बल अरु वीर्य करके पूर्ण रहता है १७ ये कां वो
न थोड़े के कुल विषे जन्मे हैं ते अप्यवाय वनाशनहैं ते दांत
मलवेऽः खे के महारणवावाले अरु जिनौं द्विपाइ नागला वा
ला अरु वीर्य पूर्ण अरु सभ कार्य विषे पूर्ण है सो सजन योग्य
है ये सब वर्णों के हैं ते योत्स्य के स्मरंग वाले हैं ते काले वर्ण
के श्वेत कृष्ण वर्ण के और लाल अरु पीत लाल अरु अलसी के
फूल की न्याई वर्ण वाले अरु चिक्कन वर्ण वाले सो श्रेष्ठ वीर्य
वाले कहे हैं ते १८ जिन की ग्रीवा बड़ी या कांडी या अरु शिर
बड़ा स्थूला अरु संबड़ टांगे दे अरु पाटल रंग के अरु विशाल

श्वेता यशसो वाः कृष्णाश्च माराः शोणाश्च पाट
लाः हयाः हेमा पुष्प निभाः स्निग्ध वर्णाः शु
भा हयाः १९ महाग्रीवा शिरो वक्त्रः ह्रस्व ऊरू
चरण प्रमाः पाटलाः कृष्ण वर्णा महतागार
कैसेरहताः २० रक्ताभा अगलेपांशो आश्व
कुमुदप्रभाः पिंगला ताम्र हिरण्याभाः मनःश
नकनकप्रभाः २१ जौ गत नमट प्राये च म
लिका वामस्तानवाः पश्चकां माधिकः श्री
मम ममः महहेमनः २२ अथ सर्पिस्मृती
रं च विदारी कंद मेव च कल्के न जीवनीया
नां सहसैस विपाचयेत् २४ नोदवरससंग
के भोजने हिप्रदापयेत् अथ स्ववाशिकर्मा
णि जीवनीयं प्रकारयेत् २५

कुर्वेषु कृष्णांस भ अरु
गिरद शोग अरु लाल रंग का लिंग शुभ सो डोडे यो डोडे रक्त लवर्ण
के हैं ते अरु जिनों के गले विषे रक्त कुमट की न्याई श्वेत होत नेत्र
पीले वा सह वर्ण की न्याई अरु वाले थे होय मन के सम कौंति होव २२
ये हैं मेघ वदल के रंग के हैं ते अरु मालती के फुल की नयां नेत्र से
वे अरु वड़े वेग वाली वाले अरु ये अधिक प्रभा वाले अरु श्री शो
भा वाले सो उत्तम श्रेष्ठ वीर्य वाले कहे हैं ते २३ अब सर्पि वीर्य प
ह करने का उपाय कहते हैं घृत दूध स्वामी अरु जीवनीय गणा
नां के क अरु महादेवी पीले फुल वाली प्रमाणी इनों के साथ
देसा रका के माहिन ओम खला वे वैद्य और बलि पञ्चकर्मादि

© Dharmartha Trust J&K. Digitized by eGangotri

भा
टी
३१५

३१६

कीविधिपवीरनांनीवनीयगण जीवंतीऋईसागग्रसनाखप
र्णीम ह्रयाली काकोलि हीरकाकोली जीवकऋषभमेदाम
हामेदामलटी यहेऋसमधुरगणकहेयाहै इसकेसाथकरे १४
अथवाइसकोकल्कवनायउपसाथसिद्धकरे निसकोक
ल्पकेमानणे वाले इसकेसाथ भोजनवनायके भोजनक
रावे वनरवेद्य: १७ यहेहर्षोपक्रमकहेयाहै येचोडीवडे
मटेयटेवाली अरुवडीविस्तारवाली छातीयिसकीअरुवडी
लंबीकाही वराटिदवाली अरुवैडे खुले अगअरुमोटेकाढ
वतस्थलयिसके उंहलेवे अरुमलोरकेसमपीलारगयिस

कल्केन तीर्थे सिद्धेन चूतमिश्रेण वा पुनः न
नःस्मापिहे ह्रोग्रस्यो तीरेण सहृणावयेत् १६
नरेवनन परिनिर्माणं भोजये सर्वं कल्पवेत् १७
हर्षोपक्रमः पृथुश्रोणिम हो रस्कादीर्घग्री
वामहोदरा आयताक्ष्यपार्ष्णीवलेवाष्टीम
धुपिंगला १८ पृथा मेककर्णा व भवेत्सह
काष्ठयवर्णिनी समरूपा देवकामीस्वपम्रा
ईमश्रेजसी १९ तोनाभ मनस्विनी स्त्रियामा
यतामक्तिया विना अयामसनी मचपलां दृ
ग्मायतदर्शिनी २० सुगीलां दीर्घ वकांव
रोमकांमधुपिंगलां इदगीवड्वालेमाहि
यत्रयविवर्जये २१॥

क अरुइककमकालहोवेऐसीचोडीहैवे
सेवकून संतानककेवधानेवालेहोनीहै जिसकेउचेसवडे
ण शतोयालालहोण अरुयिवलाकायासंदरसाण अरु
भाराहोवे अरुवडेवुलवालीहोवे १९ अरुसखउंवकोसदार
णवाली यीयवाली रगविकणयिंदाहोके अरुविस्तारगु
रुअंगवाली अरुउची अरुअपनेकोभोजनकराणवाली अ
रुचेवलनहिहै अरुवोडेकोनिकटमेंदववकरकेदिकेण
कण वडुमसील अरुवडेमुखवाली वारनवालावालीहै
अरुमलोरकेसम पीलेरंगवालीहै ऐसीचोटीकोलवके
सनावी वंशावधनाहै वोडेका २१॥

© Dharmartha Trust J&K. Digitized by eGangotri

जिसके हाथीकी तरां कुंभ कर्णांगंडुसथल होए औरसरीर वडा
सोघोड़ी वडेतपुत्रजन्माहै नीहै येकुंवडुके ओड़ेसमरं गशभा
वालीहै अरु वड़ीकुक्षी अरु उदर ९२ मोटे वक्षस्थल अरु
मुखमें सोघोड़ी स्वामीकी यांवाछा करतीहै येघोड़ी को
टी अवस्थामेंवालम गर्भ धारे वा सवै तिसको त्यागदेवे
सहित वचके अथवा ओसाछोटा घोड़ वडीवलीयां मु
खवाल त्यागदेवे अरु घोड़ी हट करकहि है ९२ इयव
षकी घोड़ी अरु पंचवर्षका घोड़ावलकरके मत्तहोवे तो उ

गजकुंभीमहाकायामास्यवाजनयेद्धृन्
कुक्कुटांड निभाघानमहाकुक्षीमहोदरी ९२
धुवेतां मुखोवाचामतः कामामयच्छति
वड़ेयेव उवावालाशिशुमसविवर्जयेत् ९३
त्रिवर्षा पंचवर्षाणा मसामसेन जोड़येत् त्रि
वर्षांतमवेदस्वाहषांवे पंचवर्षिका ९४
हुयाः षोड़शावर्षाणि असवेनिरुपद्रवाः व
षाणि विंशतिवाजी कल्याणान् जनयेत्स्व
नान् ९५ क्रियातुरोसमजननयेहयाश्वेको
नविंशति हयस्तजनयेद्धर्नैविनतैविशानिमे
वच ९६ अतउर्द्ध न संततिआत्माप्रःसमव
त्समः अविलम्बोव्रहीसिचनसकमसप्रागनः ९७
उभाभ्यां च सज्जाभ्यां मसवत्तु विगर्हितः ॥

नांकोंजोडे सोकहैयाहै त्रयवर्षकीघोड़ी अरु पंचवर्षका घो
ड़ा इसवीर्यपुष्ट होनेहैन ९४ घोड़ी सोलांवर्षतक रहतीहै
निरोगययाहै अरु घोड़ारोगरहित होवे तो पुत्रांको उत्पन्न
करणेकोसमर्थ होताहै ९५ अरु पुष्टचिकित्साक्रमसे ३
कीवरे नकर गर्भधारनेहै अरु हय घोड़ायोहै सो वीवर्ष
पर्यंततगर्भकरणेविषेसमर्थहोताहै ९६ इसकेउपरंत श्रेष्ठ
नहि योगमें होवेतो घोड़ीआसमाबालाहोताहै अरुनिर्व
लहोताहै औरकर्ण अरु अहिकार्य हीनहोनेहैन अरुका
र्यविषेसमर्थ नहिहोता ९७ अरु यवहोयबुजेहोवे तिनोंकी
संतानतिंयकहिहै यह माता पिता शोभा युक्त होवें अरु

© Dharmartha Trust J&K. Digitized by eGangotri

भा
टी
३१८
316

ज्ञागहीन अरुतेजहोवे तिन्नां तें जो जन्मे सो तेजबलकरके
युक्त होता है सो सभ कर्म्मविषे जो उपाहीणा नातो बलहीन
होन अरु नाक्लेश को प्राप्त होता है ९९ जिसका संपूर्ण श
रीर नहि है ऐसा यब गर्भ होवे जन्मे तिसको अष्टवर्षमध्य
अवस्था होता है अरु शोलावर्षमान कहे या है १० अवस
स्थाकोइ कालक्षण कहते है येकोई प्रसूतहोणा के लक्ष
ण कर के युक्त है अरु स्त्री नहि है संभोगविषे नित्य हि
चेष्टा वांछा धारती है अरु गर्भ नहि ग्रहण करती १ अ

यदानमाता पिता नरौ स्त्री मंतौ नक्रणातुभौ ती
नानसौपमायंतेते तौ बलसमन्विताः नरी
यतेनसीदंतीसर्वे कर्मस्वमोजिनाः ११ अ
संजातशरीरे णायदागर्भो विजायते स्वना
ष्टवर्षमध्यस्तु अन षोडशकःस्मृतः १०
प्रसूयकाललक्षणं ॥ प्रसूकाललक्षणे येना
वइवानमसूयते प्रसक्ताबहुयोनिसंग
र्भसंदृह्यातिनेवहि १ नामादौसर्पिषाक्ति
ग्धामस्यांशुरक्षिवेशयेन निरुद्धयेयथाशा
स्त्रविध्यं फांबानवासयेत् २ वाह्यंजसमरा
त्रेनघाणांतां वाश्ववाषनि विल्वचूर्णस्यकु
डवैतैलप्रस्थयदापयेत् ३ तौराफकेवापि
यचैतैलहिकुडवंबुधा नजापिपाययेद्धमयुना
सहमूत्रेण ४

सीवाडीकों पहलें घृतके साथ स्नि
ग्धकरके संपूर्ण अरुउरस छातिविषे वेपनाडीवेपकरावे ति
सके उपरंत निरुहवस्तिपद्धकाति उत्तावेतिरुहके पीछे अ
नवासनवस्ति भेदकरावे २ फेर सतदिन फेरे वाष्ववामार्ग
विषे चलावे विलका चूर्ण अरसेर तेल दोसेर पावे अ
थवा अठसेर दुग्ध विषेसेर तेल बुद्धिमान् वेद्य प
कावे तिसको घोडेको पिलावे सतवीरसाथ रलाय
करके ४ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

ये योनीदोष कहे हैं सो मैं रे करके कहे हो ये सब एक
योनी निद्धा योवि ना ये से ग्रासन हि ग्रहण होत नेसी है
रोग करके होनी है गंडी वाली होजाती है एक उपर ते
ग्रहण करणे वाली है एक थोडी वीर्य कों ग्रहण करती
है एक छोटी है एक वीर्य बाहर निकाल देती है इया
दि दोष युक्त योनी वाली होरही बाडी न हि संदी ६ एह रे
सा विषे चिकित्सा करे सो मैं रैते नाएण महा स्नेह सुप से र
योनि विषे बस्ति पक्ष कारि देवे ७ नेरव स्नि मत्स संश्रणी

योनिदोषमुपेके वितन्वोनिगदितं स्रण
जिह्माविनाय थापोनेमाथिवान्ताथिनात
था ५ उर्ध्व वीर्य कथ ग्रहा हृस्वा सुक्रानिवादनी
वपा एभिर्योनिकृते दोषैर्वे रवान प्रसूय
ते ६ एषा मपक्रमा कार्यः स्नेह हादिमिनि
वेयमे महास्नेह स्यात्कुर्वेयोनौ बस्तिंसदा
पयेत् ७ सर्व पहैये मे रैसंस्रणं हा दशांगु
ले किएवा स्वगंधापिषलीरसोनाशिगुव
चासिद्धार्थेस ८ त्रिफला भागें युतै स्तहु
शिनैः याव नुसं योय लवणा स्नु युतं कवा
वर्ग बापाभोजनं दधात् ९ मुख बिल्वचूर्ण
सहितं तो क्रशाद भाग दधा च त्रिफलाव
चामरव पिप्पली वमस्ता पामार्ग शिगुजं १०
सिद्धार्थ का स्वगंधा: सं चूर्ण विपाचयेत् ले पा
ने वस्नो देयतर्थे वमृ वौं के भेषजं वेव ११ ॥

बारांगुली हि देदेवे खल अश्वगंध मको थोम सहाजनाव
रे यां सरस्यां युटकेडा त्रिफला इनां कौं महीन चूर्ण करलेवे
पितानाविर संपार करे जितणा कालनि सिकार मात्र होवे
प्राणे रस होवे जिसको भक्ष्य कल्पणा लाय के थोडी कौं भोज
न देवे ९ और बिल्व का चूर्ण के साथ खिचरी मे करसाथ देवे ह
रेर बहेरे आमले वर्ष मरवे सगोम चर युटकेडा सहांजना
सरेयां अश्वगंध इनां कों चूर्ण करके इस साथ तेल पकावे
यह तेल पान वास्ते एक कोविषि देवे अरु योनि एक तैयोगोष
एक हि है सो देवे ११

© Dharmartha Trust J&K. Digitized by eGangotri

स्त्रा
रा
३१८

317

अरुपवैांकाकोह्वाददिए अरुग्य मलके साथ चोडीनाई लोगोंकों
देवे अरु पेभाभकरविधिकहि सासभकरे अरुतीह्णाविधि
करपोह्वय है सो सभकोटकरावे १२ महामेदापहेसभकि
ठकरके मणमलविषपकावे पवकाकोली तीरकाको
ली जीवक ऋषभ यमणी वृद्धीयमणी स्याली १४ मेदा
महामेदा मलटीकाली वेल कनकवेल उभागा पहेसभ
बराबरकाकल्कबणावे १५ इनांसभनांकोचौगुणाकरके म
लके हैंलेलहै तीलीमिटी आंचके साथ पकावे पहेसेहीविधि

यावकंद यवक्षुण्णं भोजने दयाश्चाय नि॰
स्थामांसकलाकुयानेहतांसर्वान्नथेवव १२
महामेदानसंयुक्तम्नलहीणे विपाचयेत् व
लभांगवषोषतन्तद्यान्न्हनाटकं १३ का
कोलीतीरकाकोलीजीवकर्षभकाउभौ
वलामतिवलाचैवत्यान्हीरविदारिका १४
दयान्मेदमहामेदेपाष्टिमधुकस्तारेव सम
भागानिसर्वाणिकल्कमेकत्रकारयेत् १५
पचनस्तैवसमालोड्यशनैर्मृद्वग्निनापचेत्
पचनस्तेद विधोश्चघृभवेमानानवामने १६
नीहणांचानिकलाबेववध्यावैवयसूपते गो
दीन्केकषायंपतवेद्ंगरोहणीनंव १७
मोरंमातिकमालोड्यपायिनानमनेद्व
पनीचापिइकोहूतायमानवानवासप
ते १८ ॥

अो इहै पानविषें पक्षकातिकमैंविषेंगुणकरहै अ
रुतीहणप्रक्रियासंप्रणकरनेकरके येसंदवीचोडीहै
सोकीस्त्रीहै इहै गाकाकाथ वावडिग मांसरोहणी
केकिंडकेनवा दालचीनी जीरा इनांकों मलोकेसा
थमथन करके पिलावनें चोरी हवकीर्णयुक्त चोर
कोनहिंलागनी अरुइसीदूधकीपिनीवनायकरके॰
योनिके विषें अनवासनवस्तिकरावे १८

© Dharmartha Trust J&K. Digitized by eGangotri

सोघोड़ी घोड़ेकौंलभकरकेसंगतैंगर्भकौंप्राप्तहोतिहै
घोड़ेसाथमिलकेफेरघेगर्भस्थिरकरणेवालीयां औषधांकों
देवे १९ फेरतिसघोड़ीकेंनलविषैवहावे अरुमसलकवि
षै मसकरयोइमहै तिनौंकेसाथनरकरे यवइसविधि
करकेनहिंगर्भस्थिररहै तबयहदेयरदेवे २० केशरना
ग गेरी जलपद्मी वावडंग कोड दालचीनी मलट इनो
कोमहीनचूर्णकरकेउदकेसाथघोड़ीकोंपिलावे
जिसकारकेघोड़ीमेंडनहि वेगकेरनाकरे अरुदोयय

अनुमार्यवर्षंलब्यावडवासफलाभवेत्
लेभयिनाहषानेमालव्यौषधिमनंतरे १९
मलिलेखवगाहेनामलकेवापिनर्पयेत्
अनेनयदिनोतिष्ठेदिदमन्यकयोजयेत् २०
केशरंगैरिकंजालीविडंगंरोहणीवचं
चूर्णंनिक्वाथस्महत्तानियष्टीमधुकमेवच
पाययेन्तीरसंयुक्तंहययानविवर्तते वि २१
गतेवाथिराडवानैनांसेमदर्शयेद्दृषं २२
नस्मादहन्यहनिसुहृषंतस्याःप्रयोजयेत् स
गर्भवाहयेद्घांगर्भस्यपरिरक्षणात् २३ कं
चिंस्थाजगोभूमानिविकारान्येहृषं का
विकेदुयमानाष्यागर्भवन्यपहेषते २४
कौविद्वागाज्ययाहापिसमूत्राताउये ष्ठषं व
डवापुरुषोकाविघोनिप्रछेनवेपति २५

रातीतिसकोंघोड़ानाहिखावे २२ अरुतिकेउपरेत दिनदि
नविषै घोड़ातिसकोंमिलावे यवघोड़ीगर्भयुक्तहोवेतो
चलावेगर्भकोंमवीरनैरक्षाकरणेकेकारणेंमें २३ कोइक
घोड़ी इयव्हिजडदहोके विकाररहित घोड़ेकौंत्यागती
है अरुकोइकघोड़ीगर्भवालीवीयोनिविषैखुकहोणेतें
घोड़ेकोंदेखके हिलकदीहै २४ कैइक घोड़ीति मपतेंवा
पश्चावकरतीहोइघोड़े कौंप्रहारकरतीहै अरुकोइकघो
ड़ी कटोर मोडेवकेसाथयोगमिकों वेधनकरतीहै क्याट
कलीनीहै २५ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

श्रा
हो
३१८

318

करणेवेडेकरनेसेअरुवेछाहोणी अरुअंगपररुणे कंप
होणा इसप्रकारकेअनेकलक्षणगर्भधारणकेलक्षण
वाड़ीयाकेलक्षणजननेवालेवैद्योनेजाननेयोग्यहैं २६
अबइसकेउपरंतगर्भवालीवाझीकेलक्षणकहतेहैं
वीनगर्भकेग्रहणकरेहैयायोनिविषें दर्भहोनिहै
शरीभाराहोताहै अरुहृदयविषैपीड़ा रोमहर्ष बालख
डेहोनेहैन अंगोंविषेंकटणाकीनरापीनिहै नेत्रभारे अ
रुथकेमासनीवीगर्भकेहोयदे योजीकेपहेलेलक्षण होता

सत्त्वलक्षणोसमेहृदि निस्फुरणि कंपने पवं
नानाविधास्तेयाधरणाहृदयकोविदैः १२ अ
नाउष्वत्रवत्रासिसगर्भाधस्तुलक्षणं यो
न्यांवीजग्रहोदस्मिगौरवंहृदयव्यथा १३
अहर्षस्तंगमाटश्वलोवनाविरनाश्रमः स
योनगतगर्भायास्त्वेतस्ववलिलक्षणं २८
शरीरोपचयः शोभानिहतिर्वशवनेदना
भवेदल्पासतेवेन शरीरस्पवसुहिता २९
स्त्रियोरोमवयःस्याक्त्वतरंगमवयःस्यात
हस्वपुनः ३० लोनारोगप्रसनाचविज्ञेयाग
र्भिणीरसा प्रथमेवदितीयेचमासेशोभावतापि
नै ३१ स्तनौपचवतेश्चमासेरकेचवर्धने पंचमे
वेवपष्ठेववाविरोमप्रमोदनो ३२

हैन २८ देहकीवृद्धिः अरुशोभायुक्तहोतीहै अरुवलनेविषेंवेग
वरनाताहै अरुदूचिनहोतीहै अरुभोजननेथोराकरतीहै शा
रीरउहमोटाहोताहै २९ अरुरोमसमूहदीर्घदेहोतेहै अरुरोम
रेमहाभरुलखानेहैन इनोंलक्षणाकरकेगर्भवालिकोजा
णीसबकेचोरेकीरक्षानाकरे ३० योवोहीलमावालीअरुइ
दिपकोंस्थिरकरतीहै अरुप्रसिनहै इनोंकरकेगर्भवालि
नाणे पहलेअरुदूसरेमहीनेविषेंशोभाहोतीहै ३१ अरुती
सरेचौथेमहीनेविषें मास अरुलहूवधताहै अरुपंचमेछठे
मेमहीनेविषेंमचाअरुरोमवाल हेदर प्रकाश होतेहैन ३२

© Dharmartha Trust J&K. Digitized by eGangotri

प्रसूतनमे अष्टमे महीनेविषें सभ अंगभो देहोजातहैन १
नवमे महीनेविषेंपाद होतेहैं न अस्तत्र विषेंबनेदाहैग
र्भ चोहीदसमे अथवाजनैं अथवा वारें महीने सतीहै ॥
पहेमर्भस्रुक चोडीकालहाणकहेयाहै येचोडे प्रानकाल
विषें बंधूंके शब्दकोंसुणके बहुत हिंणकण सो अप
णे स्वामिकोंमयदिखानेहैन येचोडे सूर्यकोंदेखकरहिं
णकदे है न अरुः भालीयांलेतेहोय सोचोडेयुद्धविषें
स्वामीकों जयका उदयकरनेहैन ११ येचोडेअग्निअरुआ

सप्तमे चाष्टमे मासी यानि संप्रयते ह्युः पा
दाः सूर्यन्नि नवने मासस्य चापि वर्तने ११ द
शमे कादशे चैव द्वादशे वाप्रसूयते १४ ॥
इतिगर्भलक्षणं प्रसूतेयत्र हयाश्च नावादि
त्रनिस्वनेः दृष्टा हेषंते यल्लवस्तल्लाजयंकि
निर्दिशन्ते: १५ सूर्यंनिरीक्षमाणाहेषंते
हावक्रमसमाणाः सग्रामेतत्रभवेजायोदयः
स्वामिस्तैव १६ अग्निहिनंकुमारिश्चर्णैपात्रेव
सुमनोस्थः दृष्टा हेषंतेयत्र हयास्तत्रजये
स्वामिनोविद्यात् १७ हेषंते खादंतो नचापि १
विस्फोटयंतिवदनानि तत्रार्थसिद्धिरविरा
त्रा तथ्या वाजिवैद्येन १८ दृष्टागजाश्रमसा
हेषंतेयत्रतत्रविजयमस्यान् हेषंते याबेनो
वद्धको विजया वहा वहा १९ ॥

लाण कुमारिकंन्या सूर्णि पात्रे पुष्प इनांकों देखकर
के यूहांहिंणकदेहैन तबस्वामिकों जय जाणो १७
येचोडे खांदेहोयां हिंणकदेहैन अरु मुखकों योस्फो वन
नीहूकरण तहां सनावी कार्यकीसिद्धि वैद्यने जानणे
योग्य है चोडेकरके १८ येचोडे धन्नाकों देखकरकरके
हिणकदेहैन तहां विजय होतीहै स्वामिकों येचो
डे दीडमेहांपहिंणक देहैं नवहुत सेचोडेभमीकोंजय
प्राप्त करतेहैंण १९

© Dharmartha Trust J&K. Digitized by eGangotri

शा.
हो.
३१९
319

हिमालय के देहों यां घोड़े यां देयां नम्रता ने अरु अंबर को ज्यां ते चंद्रमा
के समवर्ण वाली उग गिरि सो हेमखिन नाम कहेया है घोड़ा
सो घोड़ा यमनी के जय दयोण वाल कहेया है ४० जिस स्थान
विषे घोड़े सायंकाल को देखकर के हिणकण सो सेनाप
ति को सर्व अरु युद्ध फेर बुद्धिमान कहे तिस को ४१ ये
घोड़े छिन सब कटे हुये सर मुख हिणकदे हैन अरु ये
बहुत वीर शब्द करके हिणकदे हैन नहीं सेना का सरदा
र युद्ध विषे शत्रु बहुत होने है न ४२ ये घोड़े बहुत वार लिद

यथां सूकान्त्रकावेद्दतेभाः पतेनि हि खमा-
णाना हेषितेनाम हयानामेन हिनयः प्रद
भते: ४० हेषते यत्र हयाः संध्याकाले नि दे
हमाणस सेनापतेः सर्वे युद्धे न शहिशे
सनः प्रोक्तः ४१ छिन्नमचो खमस्या हेसने
युद्ध खेन रस्तानो सेनामानायकास्तत्र व
न्ते न शत्रुभिर्युद्धे ४२ बहुभिन्न पुरीषाः स्युः
प्रभूत मूत्रा ख्रमसनादीनाः हेषते यत्र ह
याः पराजयं तत्र जानीयात् ४३ उत्तिष्ठति
निषीदति मांसुन यत्नाः प्रभूत विमूत्राः से
४४ अस्थानो जदिमामिव दीनदीर्घ वेद्दवि
ने यत्र वित्रस्तानो विभवे पराजयं तत्र जानीया
त् ४५

करे अरु बहुत पखाव करे अरु हस्तीनरा उछल
करके चले नहि अरु दीन निर्बल पड़ा ऐसे घोड़े हिणकण न
हां शत्रु ते हार याणो ४३ ये घोड़े हिणकदे हुए उठने है न अरु
बैठ जांदे हैन ओर स्याति ने पखणत चलने हैन अरु
बहुत करना है अरु सायंकाल विषे अरु मल मूत्र
मूत्र मकोड़े शब्द करणा रणकल सो भय को देते हैन
जिनां घोड़े यां के रोदन की न्याई वुड़ा पुल करे हिणकय
हां अरु त्रास युक्त का नरां होवे न हा सो नि अपनी
हार जाणें शत्रु की जय करा है ४५

© Dharmartha Trust J&K. Digitized by eGangotri

योहोइसके कारहकों अनन्तरण वासकों देशनु कमारने
अरुयपादसंवाकोवडे होय दक्षिणको देहेन और सर्पको
देखदेहों यो दक्षिणको देहेन जिस स्थानविषे नहो अग्निद
हाकामे पनाणलेवे पदेहेसकाल दक्षिणको देखा है येसेपु
रखांकोंदेसकेर भावने अपवाकों धनेरोम हर्ष बालखडेर
होजाते हैं न नैमो हि चोड़ यांके ये बालप्रकीर्ण बालखि
डुजाते हैं न ४७ यदहोड़ बाल समभि विलरजाण नवविरका
ल वाहरदेशनिवास ओर सिद्धि वनरवैया कथनकरे ४८

काहेमुकंतरणावादेशान्नलेपदाबद्देषेने स
यस्मीन्नमाणांस्तनात्रिभयंविजानीयात् ४६
देखिनेनाम देयादक्षरोषाहाघटणांभव
तिरोमहर्षसन्न बालप्रकेरणामनाद्दियात्दव
रगाणां ४७ बालासवैहयदानरगाणांसवे
नःप्रकीर्यंते दीर्घेनदाप्रवासंसिद्धिश्चविनि
दिशोन्मार्गः ४८ अयदणाप्रकरणांमपते
नेवंसदाविजानीयात् वामेचापिप्रवासंश्री
ब्रंविनिवर्तनंचैव ४९ बालाकिरनिवीनी
भूमिंपादेनहंतिवामेन स्कंधपृष्ठंभुवंसलगो
द्योगंविजानीयात् ४९ यःस्नानमात्रपवाह
प्रकिरतिसोप्युः उपयतेयात् सखेवऊवस
कोंकीवालेस्वपराजयंविद्यात् ५० शीताशी
यत्रहूयात्सिहेनिलिखतिवेष्णुरोगाणिविक
रेतिननोबालान्जानीयात् ५१

यदराजेपासकेरिवलरजाणसो नवराजाकोंसदाजयकारना
ण अरुवपासकोविकीर्ण होवेनव प्रवासपरदेशगमनकर
केशानाशोमतुआवनहोनाहै ४५ जिसकोइकेबालाखिल
रेहोगिरुजाणअरुखवेसंवकरके पृथ्वीको ताड़नकरे
अरुमोंइकाअधिष्ठकोंकमाथे नहोइहामीकोजाणयो वो
इस्नाकरनेने बालखलारेसोपेइविषे श्रामहोनाहै येस
खबककोंमाई अकारबालखलेरेतो राजाअपणीहारजाणे
पसीनेकोशीनकेगर्भेनावलेहोयदेलिदकोंसंवसाथ

© Dharmartha Trust J&K. Digitized by eGangotri

पा
ह्री
३२०
320

फोलते है अरु वाल खेलाएं नटवी हानी जाले ५१ जो होवो
नमात्रनै हि वाल खेलारे तेजाणे भूखेका भौयहो पणा अ
रुरम केअनेनर यो किट कि उष्णादयो कर्नी होदे ताया से
केवाल ग्रिउजाण ५२ नवमनि निमसनैं महाभय वडा भये
कहते हैन ५३ परहे ठौरे केवाल खेलारेणे कालतण कोइ
याहे वोडके शरीर विषें देहमैं उग्र अग्रिरवीदि है यवन
गारीया वाउलको मसुरीयां की नरांअरुथषा अमन होव
उभयजाणलेवे वनर ५४ सर्वकेविषें अग्नि भगवान् रे

यः स्नातमात्रपवनजन्यं तत्र अथ कीटकिटा
यमानावा ह्यापीरपांशवो: प्रकीर्यते ५२ वि
घातनम हरूयमेन न कर्षयं निषेमनपः ५२
वालप्रकीरणे वानोशरीरेषुपन्नलनं मेट
षयनेस्फुलिंगावा उल्काबाधूमोवामहद
यनजनानीयात् ५४ पुरुकिलाग्निर्षिवधू
यदेवावमेवसम्यक ह्याकायगृहः नेना
मित्रावेस्तगणेविशेषान्मवैप्रदेशेस्तहया
ज्वालेति ५५ तेषामेवविशेषणफलं वेशे
षिकेस्मृतं पश्चाद्वैभागेज्वलितेहृष्यानाहि
प्रभवेनत्र ५८ मध्यन्दमस्यदक्षिणेभागेज्व
लितेनवगोत्रराष्ट्रंवितनयेपविनाद्रशेषं स्तसर्व
हे ५० स्याउनमागेपुत्रनामनाशः हुहेवपः
स्मानपुत्रोहितस्य ॥

वनेयांकौं कंपनकरके वायाग
केउमहोके वोउपांकेदेहमें वमननाभया तिसअग्निके अष्ट
गुणांकरके वोरेकेसमभंगप्रकाशअग्निकरहोते हैन
५५ तिहांकै अंगविशेषकरके विशेषफलकहण जिनांको
देयांकोपिछलोभागविषें अग्निप्रकाशहोवे तेराजाकों
शनवी भयहोताहै पवमरोवेअग्रेभागविषेंहोवे अग्नि नहय
वृसनरन गोत्रके देशकेसाथ राजाकोंनाशकरहै यासै
धेरे सरीशार गात्र अग्निकरके प्रकाशहोवे सवराजाकोंद
शकेसहितनाशकरहै ५७ नवशिरविषेंहोवेते हिके

कानाशाकरै है राजकेघरमेहोवेतब पुरोहितकोनाशक
रै है तबलेवेहोवेतोमंत्रीपाने मंत्रिनाशकर कहेया है ५८
जिसघोड़ेकेस्कंधमोंढे अरुपेर विषे अग्निके चनगारेनि
कलन तिसको सेनाके पतिकानाशकहेया है जिस
कालिंगमेढ़ज्वलित होवे तिसराजाकेअंतःपुरकेलो
कोंकोभयदेवेजाना है ५९ जिसघोड़ेके उदरकेबाल
अथवानखनविषे अग्निप्रकाशहोयदे अथवाधूम
निकलेपिछेविषेतबतिसस्थानविषेबडाभयजानणा

वाजिनःपार्श्वज्वलितेहयस्यअमात्यनाशोभव
दंतिनस्ताः ५८ स्कंधेनयाग्निज्वलितेहयस्य
सेनापतेस्तस्यवधःप्रदिष्टः मेढ्रेतथैवज्व
लितेहयस्यचांतःपुराणांभयमादिशंति ५९
गुह्येवालेषुयथाजघनेवाप्यथवेदर्शनलि
ते धूमेवापिहयस्यात्मस्तुरंगेनतपतानीपान् ६०
नेत्रायोगोगंडवक्रेचज्वलेनिवाहानां सप्त
मेशात्रुतदासाहुंचाविनाशमुपयाति ६१
किंचित्स्नेहणवहृन्नाज्वलनेवेसर्वगात्रेषु न
शुभंभवतिहहयानांतस्मांतिसदाकुर्याम्
६२ ज्वलनानिहयानांनिचवालानांमर्कर
णानिवाहानां ग्रीष्मेशरदिवसंते नेत्रानि
विनिर्दिष्टामानः ६३ उक्तंचभगवताशालि
होत्रेण ॥

लेवे ६० जिनांघोड़ेयांके अक्षिके अपां
ग नेत्रकोण गंड गला वक्र इनांविषे अग्निज्वलितहोवे
तब राजका राज्यनष्टहोजाना है अरुदेशकाभीनाशहोना
है ६१ अरुबहुतविस्तारकारकेक्या है सर्वदेहविषेकिसी
स्थानअग्निलागेसोश्रेष्ठनहि है तिसकारणकरकेशांति
करमसदाकरिणा ६२ अग्निकालागणादेहिविषे अरुहि
णकणा अरुबालांविखेलारघोड़ेके ऐसेघोड़ेयांके ग्रीष्म
शरद बसंत इनांविषे यतर कथनकरे श्रेष्ठनिफलक
हेहैन ६३ यहशालिहोत्रभगवाननेकहेया है ॥

© Dharmartha Trust J&K. Digitized by eGangotri

यहेसमसंमूर्ती जगत प्राणेप अग्निगुणविशेष सौम्यलोमगु
णहै इन्होंसमर्नोविषैघोडेअग्निगुणविशेषकहेहैन अरुघो
डे अग्निकरके रवेहोपरनाशहोनाभया १४ जिसकारणतें
घोडेग्रीष्मअरुशरदऋतुविषे अग्निकरकेप्रकाशहोनेहै
न इसतें तेजअधिकहोनेहैन तिसकारणतेंघोडेयांकों
ग्रीष्मशरद वसंतविषे विसेषतें वहेनहि येवैद्य अग्निकेज
ाननेवालेहै अरुयहसावीमलेवीनालेवे इन्होंकरतें जोवि
ष १६ सोस्नानासवअरुउपवास वाहनविषे विशेषतें फ

सौम्याग्नेयं न गन्तव्यं हयास्तेनाधिकाः स्मृताः
हुताशनगुणोनस्थ परमास्तुः प्रजायते १४ हे
याने ग्रीष्मशरदोर्वनतेनामनारूपाः तस्मा
न्ग्रीष्मेशरत्काले वसंते चैव वाजिनां १५ न
र्वाह्याणि विशेषेण ज्वलनानि विजानता
स्नानानि विशेषेण तु हवानि तांव विशेषतः
१६ स्नानाशे वोपवाहे च फलं विंद्यादि शेषतः
शेषे स्वल्पफलानि स्युः स्नानादिके षु च १७
सम्यक्फलप्रदानि स्युर्यात्रिके ज्वलितेन पत्
ज्वलितानि च सर्वाणि न स्युर्भावि भवेनहि १८
तस्माद्वाजिनः सर्याक्तज्वालितेषु विजानता
न मध्येसर्वभिषाभक्तं प्रोतयेनोरसर्षपैः १९
आपादलोमसंवीतं तस्माल्पाहारविभूषितं प्रद
घाटवनायोवाह्निजभ्वः शावबंधिवा २० ॥

लेनायेसे अरु वकोकेभस अरुसंनादिकविषैथोडाफल
होताहै १७ योसनतकावाडाकेअग्नि प्रकाशहोवे तबसंपूर्ण
फलकेदेनेवालाकहेयाहै औरयेसभघोडेज्वलितहोवे
सोसंपूर्णफलदेनवालेनहिकरनेवालेहोनेहैन १८ तिस
कारणतेंअग्निकेजाननेवालेयोने ग्रीष्मादिकारणेंयोग्यहै
तिसघोडेकोंचूनकीमर्दनकरायकेफेरसंघनसेतीसरसों
करकेस्नानकरावे १९ फेरतिसघोडेकोंपटवस्त्रसाथ
लपेटअरुफूलोंकेहारपावे फेरतिसघोडेकोंदेवताकों
वाबालणोंनाई अथवाशास्त्रकोदेदेवे २० ॥

© Dharmartha Trust J&K. Digitized by eGangotri

पहेज्वलितध्यापकहेयाहे जिसकामूलबोडाहे अरुज
पकामूलगामाकहेयाहे जिसनेंब्राह्मणोंकोंजपवाले
पात्रकहनेहां ११ श्वेतअरुसुगंधिवालेफूल अरुकुमा
रीकन्या मटावेल अरुवेलोकेसहित गउ और मछ
अरुपुस्तक इन्द्रादिकेदर्शनिकरोव अरु धान्य पुष्प
उपरछत्रे इस्त्रीयां १२ अरुभरेयादापात्र और मांस औ
र पूर्ण कलस ब्राह्मण पहेसभयात्राविषेमंगलकों
मंगलकेदेणेवालेसगुणकहेन १३ अरुनिंदपणाअरु

नालितांध्यायः विनयस्यांगमूलोनयस्ब्ला
हिणोदिवाःसमाख्याता विजयायननस्तेषां
यात्रांवैसंप्रवक्ष्यामि ११ सितस्त्रभिंकुसुम
कन्यादधिहयनवपूर्णकुंभातमत्स्याव पुरु
पहवेदघोषाउन्नतिमाव समनीवैव १२
मधपूर्णपात्रमांसंसपूर्णकुंकलसविप्राघ
यात्रायांमांगल्यायनेविजायप्रदाभवेः १३
मूलनेविलग्रमंडजटिलनष्टैवगनस
संवैव कोमंगल्यावाणः प्रस्थानेवर्जये
होमान् १४ कुशलायपाणकालेवामाः
भूषानेतानिविशेषु नेवापिदर्शनंसु
सेकेकथितेमहामानिभिः १४ यात्राध्यायः
अपस्मापंपनेनिचविंमूत्रंघोनरवेनित्रवणेनि
अपसर्पणंनिचविंमूत्रंघोनरवेतिवणेनि अमहाभयदाः १५
आर्मेनेसंग्रामंयायाणकालेमहाभयदाः

लीनहोजाना अरुशिरमुनेपाटा अरुजटावाला अरुनि
सकहयमाहोवे पहेएजप्रस्थानविषें मंगलकेनाहि दे
णेवालेवहेन अरुपहेसववेयात्राविषेसिद्धकरहेन
१३ यत्नसर्ववैमिलेनोश्रेष्ठहै अरुनेसहिसनेपंवीधे
ष्ठ फलकरेहै सेष्ठबुद्धिवालेयोंनेकहेयाहे यात्राध्या
यहे अरुचलनेकेवेले चोरडिगपंदहेन अरुलिद अ
रूपक्षावककारण अरुचलनेनाहि संग्रामयुद्धकेसमय
विषे नववकहनभयदेणेवालेकहेन १५॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा
हो
३२२

322

पृष्ठके मध्यकालविषेजिनांघोडेके भ्रवरे लहूनिकले
अथवा धूमनिकले तब वहू भयके देणेवाले कहे हैन १६
अरु पेघोडे रोगरहित होण अरु दीनमन अरु गोदरेके र
हिण अरु भोजन नहि खावें सो भयके देणवाले कहे हैन
जोघोडे पादकोपृथ्वीविषे प्रहारकरने हैन पदोकर
के अरु पादपीडाहोवेनिनादे ११ अंगभंजजाए अथवा
दंतगिरणेवादेनवाहूगनिकलजाणे पहूवाघुनेहोने
हैन एकवेषकहनोहूसेरहनादि एकमस्पदोसेरवि

उपविष्टनेवडुवेपोधारकेमरवाहिनियोनि
धमेधापिहूयानोविनयोस्येमहाभयदा १६
निकयाकदंतोदीनाःसंगाहेमाःखादनहेषा
भयदाः पादाविभादिनोपेपादेनिवतिभूमि
व १७ भगवलपानोवादंतोनीपादभवेद्या
नान एकसेहमस्याइवंवनगुणइति १८
गगंपुनेरवाहू पेक्ष्याणाहिपलंगभेन्तेरप्र
स्थोविपावधेन तेहावनगुणवाजीतोरमा
नसमघये १९ कायहिनदेहपोठोवनःप
पुष्टिनोवुधैः पवंसवोणिपेक्ष्याणिनतिलि
नरनियामयेन २० अनीरःसप्रभःस्निग्धः
समकपकोगुणचिनाः प्रपासेवाजिनां
स्नेहः सर्वरोगविनाशनः २१ अथ कुःसो
दकोनेयोनिर्दयः कलमउच्यते नस्मादेव

विषेहूवनलादि वारगुणपावे १८ गर्गाचार्यकेरकहेनेहै
रके एकाव अरुसेहपाकवालेपाणि उदमेसारसघ्रोरद
ववस्सेहने वारगुणपायनिरकरे १९ कायविषे प
कोदिनमहि स्वेहपावे अरु वपेहूपाकायमाणेदेवेचन्द
अनेनमहिसमधपष्वद्दरवानिसहिदेनिविषेमिलावे २०-मि
निसहूननेलविषेमलनावडे अरुगंगसहरहोवे स्निग्ध
अरुहकीनरो एकावेवे सोगुणवकहोनाहे सोस्नेहघोडु
योकोपुष्टिदेनमहूनेविषेदेणेमेसभरोगोकेनाशकरहेना
है २१

योसेहकचारहे अरुजलविचरहेयादाहोवे अरुजल
जावे कालाहोजावे सोसेह मेसामभरोगाकेकरणे
वालाहोताहे २२ सोमांसकोवधानानहि अरुहित
करतनहि अरुसमभरोगमेंमाउहे तसवारअरुअन
वासनवासिविषेंमदुपाकसेदेवे २३ अमेगमालस
वासेखरपाकसेहकरे अरुपानवासेमध्यपाकसेहे
करे योसेहदहवोनरापकानहि अरुवउनपाकहो
वे अरुजेमसपहीनहोवेसोरोगकरदेताहे २४ ॥

अपकः सोदको ज्ञेयो निर्दिष्टः कफ उच्यते २२
तस्मादेव विविधस्नेहः सर्वदोषप्रकोपनः
अस्नेहरोगा सान्न्यस्य सर्वरोगेषु निन्दिताः
तस्मान्नवासने वै स्नेहं मृदुपाके मृदुना तथा २३
खरमभ्यंजने कुर्यान्मध्यपाके तु पाययेत्
अपके दोषजननं नैमत्निपक्कमतोषधं २४
समाकत्पक्कस्नेहः ससर्वगुणवान्भ २५
वेत् स्नेहस्वेनेन कल्पेन येवयासंप्रयोजितः
वातपित्तविपडुष्ठेस्मान्नेवगतं न योजयेत् प
नन्नमात्रासम्मानां समभुमात्राविनिर्दिशेत् २६
पादहीनेनमध्यानामल्पहीनेनफलानां समां
उत्पलिम्नोपधाराणां पधिप्रिमः सूर्यरश्मिभिः २७
पक्कमोषधयोगेन तमरगाः शांतिमच्छति २८

योहवनवानेल औनरांपकापाटाहे सोसमभगुणांवालाहो २५
ताहे अरु स्नेकत्यकरके पंनोनरांकरकेदेईदाहे
वायुप्राणादिभिटपंनप्रकारकाकहेयाहे सोदहो २६
काविकन होयरे अरुखोटस्यानिविषेंस्थितहोय
देनितांकोंजीनदाहे पदहेसेहप्रमाणवेडुधोंदेदाकेहे
याहे २६ योतोउमध्यगामीकेहेन तिनांको १कहेसा
सटदणा अरुयखोटहेन तिनांकोंप्रदादेणा जैसेरात्रिवि
षेंकमींयोनाय अरुदिनविषेंकमलनीयां प्रकाशमये
कोयोंकिरणांकरकेहानीयांहेन तैसेहि औषधीकेयोग
करकेवोउरोगरहितहोकेप्रकाशहोनेहेन २८

© Dharmartha Trust J&K. Digitized by eGangotri

भा
प्र
३२३

323

पहेमात्रऔषधीकाप्रमाणकहेंगा है देहकीअग्निचारप्र
कारकीकहिहै एक मंद समतीक्ष्णविषमहैन योमंद
हैसोबडेदुःखकरभोजनकोंपचावैहै योसमहै सोतुल्य
कालविषैपचावतोहै १६ योतीक्ष्णहै सोस्वभावीपाककरा
है योविषमहै सोविषमकालविषैं थोडेयाके भोजनको
पाककरतीहै योथोडासदाग्निवालाहै सोवीर्य इनआम
योविषैप्रोष अरुवर्णऔशरीरहिनहोताहै १७ योसमअ
ग्निवालाहैसो पराक्रमरूपबलइंद्रियबल अरुसत्वगुण

मंदः समश्चतीक्ष्णोविषमश्चानलोविधाकाया
ग्निः मंदः कफाधिक्येन समानलोभवति
समपाकी १६ आशुपाकीतीक्ष्णोविषमो
विषमपचनतंरोगालो नानासेंद्रियतेषा
वर्णेरहितलमंदाग्निः १७ नवरूपबलो
पेतनःसमत्ववासवेंद्रनतसमश्च पदोद्दि
ष्टःसत्वयुक्तःसमाग्निरवःसमाख्यातः १८
नवसारबलेयुक्तःसत्वाभमीभवतितीती
क्ष्णाग्निः नवबर्णबलेहीनोवहुरोगभी
गीचविषमाग्नि १९ अग्निलक्षणं येवन
भोजनाबाहाभोज्यायेनान्नवक्ष्यामि नभोजयेद
तिमात्रकान भोजनाभिषणवा २१ उमेनसम
मधगनापिपासितेनवापिविशेषेणनै २४

समकार्यकर अरुसमरहिताहै अरुपंचइंद्रियोंकेयोवि
षयग्रहवैहै तिनोंवालाहोताहै समवायग्निवालेऐसाथोडा
मबलवालाहोताहै अरुभंगअंगभनतानरेहाने विषमा
ग्निवाला वेगवर्णतेहीनहोताहै अरुबुरेगुणअंगमंद
होताहै २२ पहेअग्निकाललक्षणकहेयाहै नेचाहेभोज्य
भोजनकरावेपावरेन अरुअभोजनहैनसो करजेहा
पचेतो वहुत थकेहोवे देविमनहोवे मंदाग्निवाले
इवेल मकोकरकेरोविन रषापुकारोकोविषेणेवहन
भोजनमनाकरावे २४

© Dharmartha Trust J&K. Digitized by eGangotri

पेचोड़े पान नहीं एलहोंवे हवउ अरु पेमावकरलिसे हो
वे दुःखीकों कृस इंद्रिय बलहीन ऐसे अवस्थानसरीअ
वस्थाकों प्राप्त होवे इनांकों भोजन करावणे योग्य है ९७
नवसारि कालविषेंक्राथाकरहलदेशके घोड़ेकों चाउ
ल दोसेर एक सेर स्नेह विषेंदेवे फेरमर्दन करावे
इसनरों भोजन नहक्षीनरां पचावदाहै ९७ मदिकुल
थेकायूष कांजी वारुणिमदिरा अरुमैरेय मदयद
इनांकोंमलेहोंपरेयांकोंचेऊमसाथभोजनविषेंदेवे ९८

भोज्यापानहीरोहज्जो भारावकर्षितो दुः
खितः क्षीणेन्द्रियबलहीनो यश्चावस्थान
स्त्रमाः ९५ क्वाथामथापराह्नेदेशपरषी
विषादेश्च स्नेहार्द्धप्रस्थपुनेमिडंवेतुल
प्रस्थं लवणेनयावेपायां श्वेदयादनेन
रेस्नेहः प्रश्चान्मर्दनमेवंभक्तंपरिपश्चनेस
मकं ९७ दधिकोलमयूषंयाम्यामस्लेवारु
णीचमैरेयं पनानि मादनानि लहूनगुके
भोजनेदद्यान् ९८ पतीणेसनिमामहि
षानि लहूनगुके भोजने दद्यात् यूषं नवा
दकं प्रयोग्यानि पनानि मादितानि न्दद
पेसहूनभोजनेचैव पक्वमाषशालिपिष्ट
कगोधूममानां पश्चादेयां दद्यान् सोदूपथो
गुडवामवेमदावनेपेलवणानि ले १००
मदाम्लापीनस्नेहेहक्षशोकफार्थेच वातामेव
लवणास्नराहितामर्दनार्थेच १॥ जोबनहीमांस
केरसकायूषमोरनोरांकाकांजी इनांकोंघी मलकर
केवेउमसाथचोडेनाई भोजन में देवे ९९ मरो महांगास
मलीकेचावल शाठीकेचावल केएक इनांकोंघोविपिक
हिवेनैपींहदेवे अरु मलोरहदगुडवायहदेवे अरु लूण
तेलकोंस्याणे १०० अरु मदिराविषेंअरु जिसनेस्नेहपानकरे
होयविषे अरु लिशकों अरु कफपीड़ितकों अरु वायुकरके
केष्टककों नेपवल्ल्वणमअरुमर्दिरामालमविषेंहितहै १

शा. टी.
३२४
324

यवकर्मकोप्रविकारहोवे तबको नीरुग्म मदिरा मद्यसा
थमर्दनकरावे येत्रुदे है वे अरुचिगवालेको सुकभो
जन चोडेको देवे २ भोजनकरने होवे वोईको अ
रुगर्म जल साथ धोनेदे पिचलेपासके वोडेको अ
थवा समश्लोके विषे कोपदणो उपरत जलपान
करावे नामर्दनकरावे ३ अरुभक्तके अनुपानवि
षेवोडेणाकोमदिरा मेश्रक देणा कहेयाहै सोता
यदा भोजनपचानाहै अग्निकरनाहै दोषहरेहै ४

मदात्ययानां वेकिलिकोष्ठमर्दनेनगात्र
चैः लेउकासिनमेवसम्लेक भोजनेयदस्य २
नरेगतंभक्तवेनेस्याते न वल्कस्य खोतुनाप
स्नान गात्रवृषसर्वेपानपायमेनमर्द
येच्चेव १ अनपानेभक्तानामर्द्धेप्रसंमव
त्समाया: अभ्यसि तेषाव पानिमदीपनी
दोषसंसमनी ४ उक्तेवभोजनानापनेमा
तेरकेवेवोपवीपने वर्षनेपानवः हितेप्रव
लेकाप्ततयेवव ५ तर्णामोपानवः सर्व
शाभाक्तापायानेस्मृतिः मनःप्रसादनेन ८
मिभोजनेनेनोपजापने ६ अथखोदनेनवा
हाभाराधसहमेवतिवलिनस्य मुदिनेहिपा
पजेविनः स्थिरमांसबर्वेनस्य ७ इत्यपमह
तेयन कमिमि लेउपुराणमस्त्रीणां तेष
मादनमनमलेस्थितेयदामिश्रफ ८॥

कहेयाहै भोजनतेमांसहोनाहै अरुजलदुवलेपनाहै के
रथानेवधनीणाहै केरवल देहवधनाहै ५ अरुरंगडे
नेथानेवलनेमसन शोभा काया धारणा बुद्धि स्मरण
बुद्धि प्रसिद्धमनः स्वमि पेहसभभोजनकरकेहोतेहै
न ६ अरुखादनकरकेवोउ भारके अरुमागेलेदके
महाराणी वालेहाने हैन ७ पहने अरुवलंईटेपहुंच
वेगरफमास मतवृके होमहैन ७ येहणे जलदे
परहेणोमम अरुपतिमिगोविषेजोमरेहोण ८

© Dharmartha Trust J&K. Digitized by eGangotri

योग्य हृदाणा है सो घोड़े यांको वेगरूपछायाते न अतिशा
रीरशोभा प्राणहारिरनांकोंव चाता है अरु खादनतैवी य
वशा बाय विशेषतें पुष्टेयाभवे कहे हैं न तिनांकोंवधा
ता है ९ ऐसे घोड़े यांकोंवाय मनलयोग्य है ऐसा द्वार
कोइ ग्राहक रहित नहि खासविषे प्रमाणयहे है न रसका
रणतैं खासविषे यत्नकरे १० त्रिकुटा ईद्रयगोकों उप
तीसमर्दितसाथपीसे सेवनतैंवणआयु बल वदता है ॥
उद्वेगोमास अथवा तिल खलमर्द करके देवे अथवा

नवरूपच्छायाने जो मेधैश प्राय: प्राणावर्द्धनो:
ष्वाना यवसखादनादपि भवेत् विशेष
ण ९ मायोयच्याहरणानोयवसोनामोहित
खाहर: यवसप्रमाणसेनेयवसेयत्नसदाका
र्यं १० त्रोषविडङ्गैर्दनवकदकानिवेषाघ्रुने
सरया प्राणिनोपिष्टं कावर्णापुर्वंउनेवलं ॥
हीरसपिमोसाम्यवादमाषुतवतिलपिष्टं
मावाणोचूर्णंवालवणयुनेभोमनेदघात् १२
तोईववघालिपिष्टंचप्रविदारीसमायुनेते
नन् सपयस्कंज्ञद्रमदनाज्वेवलंरूपमानि
केव १३ लवणोपवाद्रमभाष्लेनमर्दितं
विपिवत् वलंनरंगमाणांभोजनेमनहितं
दिष्ट १४ स्नावेकालोपलेदनेयोगेनभोजने
सम्यक् तणामनजेप्रयगंमयोवलवर्द्धने
हितयं १५॥

महाकाचूर्णलूणमिलाय भोजनवि
षेघोड़ेकोंदेवे १२ वाममौर प्राणीका चूर्ण ववक १
सालिकेसहित पहेडदमाप्यत्रयदिनरावानेकरके
वल अरु स्वरूप होता है १३ लूणनउोकाकोटामर्द १
केसाथवा अमलकरके विधिसमलकरके पर भो
ननघोड़ेयांकोवलके करणेवालाकहेया है १४
पोसमयकरके स्नानहे अरु पथ्यायोगमें भोजन अरु
यथायनकाल्परणवाय सेदर पहोंजयपसनावीमलो
केवधानेवालेकहेन १५॥

© Dharmartha Trust J&K. Digitized by eGangotri

इतिविधियोगः ख्वाणदाणभोजनवास पान इत्यादि
पदेपुष्टघोड़ेयांकोअंवशोभाकरतेहैंन तिनोकेनाम
कहतेहो १६ पहलीशोभालोहितहै दूसरीपलनीहै
तीसरी भिन्नावलीहै ओर चौथीठिभिन्नमांसाहै १७
पंचमीशोभाघोड़ेकीद्रोणिकानामकहिहै यहेपांच
प्रकारकीयाशोभाहैंन तिनोकेलक्षणमेंभिन्नभिन्न
कहतेहो १८ जिसघोड़ेकेलिंग ग्रैवेत्ततुदाम्रेन हार
लालहोन ओरुमासकोमलसत्वहोन सोलोहिताना

विधायोगः खोटनभोमनपवसैःपानैःसीर
दिस्थपुष्टानां शोभापंचहयानांनामांसानामां
निवक्ष्यामि १६ प्रथमालोहितनकाख्यानयाप
मपलनीशोभा भिन्नावलीस्तनीयाविभिन्नमां
सावतुर्थीस्या १७ अथपंचमीनुशोभाविशे
षा द्रोणिकानंगाणां पनालपंचशोभाल
क्षणमांसांप्रवक्ष्यामि १८ मेढ्रंड्कोपवक्त्रः
पायुः ओमोनिपस्यरकानि मृदूनतुमांसव
भवेल्लोलोहितनाशोभकोगनो १९ सर्वैरपि
प्रदेशा मृदुमांसविनेत्तयाम्रुरंगम्य स्कंधे
ऽभिवलिभिः साश्वपभालिनहोति २० यः
स्यात्मीनोवक्त्रः कटिमोमेस्यादनपार्श्वोल्लह्म
किविजीनवलोमःशोभां पामलभिनवला
२१ पार्श्वोदरत्रिकवक्षःमांसविभिन्नानि
संपयोस्थीनि दर्शाविनष्यशोभां साभमेत्तोभिन
मांसान् २२

सोशोभावालोडाहोमाहै १९ जिसघोड़ेकेमध्य
भागमेंदृशाकोमलमांसोकरकेयुक्तहोन
जिसकोको सोलिमानाम शोभावालेघोड़ानने २० जिसघो
ड़ेकावक्षस्थलपुष्टहोवे ओरुलकमासकर्केटकेपाहे
अवलिशोभावालाजाणो २१ जिसके पार्श्वउदरत्रिकवे
लमासनेभिन्नहोतोमेस्थीयो ओरुदृत्रोणांओरुदरकाउ
कद्रोवेसोघोड़ाभिन्नमासशोभा युक्तकहियाहै २२

© Dharmartha Trust J&K. Digitized by eGangotri

निसकोउके उपांगविषैमासवहुतहोवे अरु छहवंशाभमे
कीनहींहोवे अरुहोनावत्तीयाविषैमास उचाहोवेजिस
का २३ अरुमासकेवहुतहोणेकरकेलकनीमाहै सो
शोभापचमीहोणिकानामसुनीयोनेकहिहै २४ जिस
केपहेपवशोभाशरीरमेनहिहैन ऊरुकायाविषैमांसअ
र्वनेनहोवे सोरोगमेजूरनामहै अरुमांसवडिसयाहि
हैनिसको २५ योसथूलमोटवोडाहै तिसकोदमहोताहै
१३ सोकार्यवासेश्रेष्ठनहिहोना अरुसोमार्गविषैचलने

मांसाल्पांगभागेनिर्मंजितानीवहछवंशा
स्य पार्श्वेभ्यामपिमांससमुच्छ्रितेस्मानरंग
स्य २३ मांसोत्कर्षेणाभवेत्कर्मसध्येनिम्नग
प्रदेशास्य पंचमाङ्गोणिकेनिशोभामहर्षिणं
पंचमीकथिता २४ पंचमांऊरौननकायेमां
सप्रवर्तनेयस्य सोयत्नमेजूरोवैमांसमहतिव
यानस्य २५ स्थूलस्यभवत्कायासानकर्मयोगे
नवाधानिसमर्थः नसहत्सोवातोछाया
कामाःपिपासातः २६ भिन्नेस्तजनिपुरीषं
वहूनेकश्चभवतिवक्ष्मूत्रः एवंस्थलोवाजी
महर्षिणांप्रोक्तंभकुलन्याविंदितःकथितः २७
शोभाध्यायः शोभानांलक्षणंप्रोक्तंभकल
नोग्रवृत्तेन मूकालव्रामलेभवतिवैनेरसम
वोचेषां २८॥ को समर्थनहिहोना अरुधुपकोवीनहि
सहारना छायाविषैवहुतवाछांरखदाहै रणाकरकेउः
रिवहोनाहै २६ अरुलिद्यतलीकरनाहै अरुवहुतरोगां
वाला होनाहै पशावबहुतकरदाहै इसकारणमेंस्थूलवो
डाअरुषीयोनेमाडाकहेयाहै॥ इतिशोभाध्यायः शोभाका
लक्षणकहेयाहै अवभकलाकालक्षणकहनेहो पशुका २८
लकोउहैसो लनाअरुशीलस्वभाव जिनोंकानहिहोनाहै
पशुकलकोउहैनसोजोपी अरुलज्जाकेहोनेहैन अंगके
वोरहैन अरुदेहां करके वेचदेहैन सोलनेहैन अरु
गिरदेहैन २८॥

श्री
श्री
३२८
328

अरु ग्राममात्र है सो जननिसबको संवोकरके खलारदे है न
अरु छुड़देहैन अरु येवार उहांस्थिर न है सो निश्चय करके
पृथ्वी ऊपर गिरपड़े है २९ अरु पापासके है तिनाके मारणे
वास्ते चक्रवान कोप्यार भ्रमदे है न अरु जेसो अरु मोड़ेवड़े
है न अरु हाथीकी नरांगर्जना करते है ३० अरु बिलते है अं
गकमाते है न अरु मगहरणों को नरा उछलते है पहे कूदे
है न अरु गर्ने अरु कनारे वक्ररनाकी विदारण करते है
अरु नदीयांको नरपाते है अरु विषमकराउस्थानवउड़जाते है २८

ते प्रकलालुवाद्याविज्ञेयाः कोपनाश्चदंडाः
ध्वंनिकर्षनिवदनेलेभनत्यनिमिषनेनि
२८ निष्ठत्वात्तनमात्राद्विनिवपादेषनभेले
स्व पंसादिनापिवाहाश्रयिहिनाविलपने
निमेदिन्या २९ अथवक्रवडपनिषादमनि
वैसादिवानये भत्यानिनेयेकेधनामर्षेप
निगनवत ३० भवस्थपवनेनेमरण ह्वाला
स्ववक्रवैनि स्वभावपाकुलानेदोदावैर्या
निवेवविषमाणि ३१ मसेनमादिनासह
पावस्थानिइवलालेन मयाणियानेकानि
वदनिविषमाण्यनानिकर्माणि ३२ कवंनि
प्रकलाप्पालेखांच हानिवसामि विद्धेम
निह्रवप्तालललाटीलमाखवरमेद्योप्राम ३३
ह्रवणैलेवस्त्रेमहन्निरपिकालनाबोद्धा हंस्ता
विषमाखेखांवे कयेदापायासकोपताम ३४

सोसनकारकेसाविसारकेसाथरोउमेहेन अरुमोवड़ानिर्व
लैहव पक्षीकरकंमेहेन अरुअतिकठिन कार्यहेनसोसभशुक
लेवोरकरमेहेनु ३२ पोम्यकलोंकेलतणेहेनसोकहना
हो जीअनिसकीकुटीदेहोनीहे अरुमनक पटालेपल
गकीनरांहोनेहे तिनावउध्यानाव ३३ मेरकोस्थानमेवि
रांवालेवरेकरकेशुकहोनेहे अरुमालरोरकाले हा
रांपटवट होतीसीगी अरुवोडाकपिलरंगहोनानाहै
३४॥

© Dharmartha Trust J&K. Digitized by eGangotri

येवोरुस्मगटीजोड्डीयुन्कामरवेवालेहैन येमोटीयुलिंग
लेहैन येइलकीवांगुरुनेश्रांवालेहैन येइकोटेउपरलेशेटा
वालेहैनजिनांदेगरुस्थानस्तुलाहैन येवोरेकानेपीले
गद्रोवालेहै येमोटे पिभीत्रिककर्णावालेहैन येब्रपकीय
द्विवांगुरनेश्रांवालेयेहैन येवमकेहैन अरुये इकस्थेनेसंग
संवांवालेयेहैन येत्रयस्थेनसवांवालेहैन जिनांदेकंधो वि
हैं वलियेवालेयेहैन येकले अरुयुइगवालेहैन पहैरन
ने अरुम्मोरवीवड्डनमूनीयोनेमुकलेवोरेकहैन १७ इनां

स्मगुरीमुखोश्चयेश्वाःस्थूलाताःयेवयम्माताः
हृत्योनरोहृगोजस्तनुस्याःकृशापिंगलायेव १५
स्थूलाशिरस्त्रिककर्णाश्चापिकनेजाश्चवेमका
स्यैव श्वेनेकशाकयेश्वायेवत्रिश्वेनेयादाश्चः १६
स्कंयेवलिनोयुश्चायेकृसवर्णाःश्ववर्णाश्च
येतेवाम्येवहवोमहाश्चिरापूकराःकथिताः १
येवांक्रियाचक्रमेवजनेवोमेसमासतोवदे
स्थानेनतोनिवानेगुभेसुपरिक्रमम् १८ ने
त्रादेश्मपर्शसरकुत्वापरांवत्रियांकृपीन् श्रोष
धपानंभ्यास्नयानंनेवेवकुर्वीतः १९ कटु
कानामीयत्रंतीविकरवीरयुछसंयुके सह
पायपेन्कुलम्मोहिंनिहियेमनचैमानि २० गो
हृरुकमथतारंसवर्विकानमैत्रनिलतारे न
क्रेणसमायुक्तेसमाकेसस्थितेनन २१ ॥

कीविधि चिकित्सासंहेपकरके कहतांहो इनांकोस्थान
नहांवाहूनाहीयेनहीवर्णना अरुफेरनागुभ वाउपाय गु
मकरणा १८ नहांनिनांकोरुयांकोस्पर्शकेसहारलेवाले
पहलेकरकेफेर श्रौरचिकित्साकरे ओषध अरुपान श्रप
सला इत्यादिविधिकरे १९ कौड़ नलपत्री खीरणीफ
लगईलेदेफलकेसहितपीवे श्रौरकुलथीकोसमकरके
पहेवसंगपीवे भलहैदातार सजि अरुनिलीकातारे क्षा
इके साथमिलायके सनदिनाश्चिरकरकेरहे २० श्रौर
क्षारकरके इकहेसामिलाके थोड़ेकोसनरांत्रीदेवे ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰ टी॰ ११२

227

इसप्रकारकेघोडास्पर्शेद्रपशाब्दप्रकाशवलीहोताहै ४२ कर्णो
कीमैलगोमूत्रघोडीकापक्कावसेनोसेरपो घरीजिनामधो
कादिसमालवीजलवण मरिच वंदन पहेसमभागमपीसके
सलाईसदापवैपर्वेलिनविषेपावेनोपकलकोदूरहोताहै
जिसका ४४ प्रकारिव्वकेनख हाथिकेनख गौकेनख
सेनीमरेपां मोरकापिपंगेरनाकौ मिलायके प्रणवारका
रघोडेकोदेवे वत्सवंघ ४५ पद्मप्राग्रहमीप्रकचनदे
प्रीविषेनिम्नप्रकार प्रपवावेनिसप्रपकारकेघोडास्पर्शो

श्वेतेनकेणपादमिदंप्रदापयेवास्यसप्रयाचे
न पवस्यशोत्रपशाब्दंचसत्वोपनेवाजी ४२
कर्णमलंगोमूत्रंवरवाम्रंचसर्षपाः सैलाः
पिप्पल्यःकाशीसंरोमलवणानिमरिचंच
४३ चंदनघनसंवेणिहानेवारयेस्राशः श्वेत
नमेनन्कुशोमंवणिपवणिसदानस्य ४४
श्वेतस्यगजस्यनखागोनखस्मिग्राखेकाःसि
ताश्रापि पिलिविषिनविमिश्रमशुसंदद्याद्द्रु
शल्परोगस्य ४५ अहमस्यानविशोषणमथप्रय
हैनयावनदस्या नेनस्पर्शेत्रपशाब्दंचसत्वा
यनेवाजी ४६ मलाहकवनालपादनला
स्यतिलनलाटंच वद्धेनत्रिकटुलनलाठंच ४७
वद्धेनत्रिकटुकेचलपयेदानन्नावद्गुणाः
स्याद्दंशोमपमादापलेपमेवास्पसवेगाज्ञाणि ४८
मधुनासहपाकेरपालपयेवानरणा स्पात्तमद
णालवदनकुष्ठाणरुकाणाराणुष्पसनेरैसिः ४९

परस्वप्रपशाब्दस्यालनै संदरहोमेहैन ४८ पीराहोनीहेश्रकरकोप
रक्तानाहे संकोमेनालेने श्रलिपां मस्लक लिंगाविकरनांते
इसकापानैचोरकौवदनस्यान शेरविक विषेवदनेनेपक
रालो जिलागोहालेकरकेसारदेहविषैलेपकरावे ४८
मलीरावेरकरकेउमरार्दनाकरके लेपकरावे अह कम
लकीजड चंदनकुट अगर नागकेशरगलप्रपरनाकर
केस्पानविषैलेपकरावे ४९

© Dharmartha Trust J&K. Digitized by eGangotri

अरुरत्नों करके हि घोडे पांकोंनेल माथ वाहरा विषें प्रगीट
वे अरु घोडे पांकोंस्थान विषैस्थित होय दया प्रपभुरतावे
पत्नीयोंकु हने होयया ५० तिसकरके शब्द स्पर्शरूप स्पर्श
सुख करके होने हैन इसके कारण करके गोड सत्ता वीर
नाविकारों तें मुक्त होजाता है इसकी नो विधि की पत्ने अरु
क्रोपवीन हिं कर दे तिसकारण तें शांति कु सवे बुद्धिमान् ५२
इति शुक्लाध्यायः ॥ बोशालि होत्र ण पा विनके दया है
सो अब बालि पहे गुण अरुदो इसग्रथ विषें घोडे याके

नैलेन वालमेनन्नरंगं पारिभ्रमपदेभिः स्थान
स्थभूपपदमंस्थ्रमसेप्रुहिनालिप्त ५० नेनशा
स्व्रुपंचस्पर्शंचसरवापने नदाम्यनिहलोवा
जोयाकामसम्पर्गेनाहिना ५१ नचकोपंप्रकृ
रुमेनदाप्रोनेतिनिर्दिशेत् ५२ शुक्लाध्याय
शालिहोत्रेणगदितेधाविनेनमोल्लमेत्रना
वन्नारिंशाद्गिमेमया गुणादोषास्सवर्जिता ५३
यावनेनरविंत्तेणदोषाणापंचविंशतिः गु
णांपंचदशोवस्यंप्रकंस्यात्सुधाविने ५४
येकनःपतिहरन्तेसेनिहतिवगाविनः ग्रीवं
प्रगल्भस्वलितंबालंग्रीविषकल्पनि ५५ नेत्र
वानिमिषउस्टमीपंकंवारपसापि योघवा
लव्यशष्टिप्याक्विलानप्रनिपघने ५६ नदाभ
स्याविलोकोपःसोकोकशीर्षप्रकल्पने विन
स्यग्रवणोऽस्सलजिनस्तादिनोध्रुवो ५७ ॥

कहते हैं सो जानाणे ५३ नहीं धावितबिषें पंजी प्रकार के दोष
वतरजाणा अरु गुणपंदरोंक हेहैन जिसोंकरके वो तुरतथा
विनहोताहै ५४ घोडो तुरामेरया वाजिसप्रतिप्रहारकरता
है अरुघोगवेपुक्त हलिन तांमारताहै अरुग्रीवाकातुपाप
करके रेविचदाहै इसोकों अरुवालोकों प्रदेपकरके॰
सावधान होताहै ५५ अरुअहियांकोउडकेदेशैन नरकुर
नाहै अथवा कानिश्चल दृष्टिदेखताहै अरुशिरकों ने
हि पटनकरता ५६ घोडा हृषणीके पासदेखतिसको

© Dharmartha Trust J&K. Digitized by eGangotri

अर्धांकुशिषंककरकेहैन योवोड कर्णविषेशब्दकोंथा
रकरकेड छवित त्रासकरेदेअरुमेरेरवारंवारकमरहाहै
अरुपिरमारेसोप्रलमन्नामन्नाण याहंडकेप्रहारकोत्रा
णकेहेपकरताहै अरुवेगकरकेदौडे अरुशालकेसहि
त दंडांकोचवे अरुदंडनेवीयानाहटे अरु-- केसबंधके
किठकरके मरि फेरपकडके परीडे ५९ अरुघोवधाहो
याहाऊंपकरताहै वामोहब्याकुलताकोप्राप्तहोआवे
अरुदेहकेपिछलेहैसेकरकेसावधानहोके खडाहोताहै ६०

मुहुर्मुहुः शिरो धुन्वंस्तत्रानोऽप्यवलिमकः
देहप्रहारंविहृष्टिप्रस्तरमानिवगवान् ५८
ग्रासबद्धविदेशांदंतान्दंडयोनोन्निवर्तते संहि
प्यवापिवराणौविहिप्यचानकर्षति ५९ क्र
ध्येनधावधमानेमोहंवाप्रतिपद्यते पश्चा
द्देनतकायस्यप्रचलेदवतिष्ठिनः ६० उत्त
म्रवाहोवेगादस्त्रवायेनमादिते विकरत्प
इतेतवेभगोगाविज्ञानवानसौ ६१ विहिप्य
गात्रवलनिस्त्वंगोगावलागके कटिवो
नियदांगानिवनियत्ताडनेनतत ६२ क्रोशा
म्रवतेमेवापिककेशंगासठ्याने अनेक
रूपगांत्राणांत्ताभीमोव्यवस्थितः ६३ सक
टैर्विषमैर्मार्गैःस्याज्जिमोयोनकोपनः अनीश
णोत्वमपहोवाकरेभानसोमने ६४

योजलकेप्रवाहकेवेगनेडरे अरुस्वारकोंदुःखीकरेदुष्ट
लेगाहोयाग्रेगान फेरदाहै सोयोग अरुविज्ञानरतोकेजाने
णवालाहोयावा ६१ योघोडाअंगाकोविहपविस्तारकरके
चलताहैयानिष्ठलअगहै योंवबधन ग्रेगावालोहै योकर
डेअंगावालाहैयोप्रहारकोनहिकछुमाणदा ६२ अरुदुः
खदीहेनतिसकोदौनहिमनमाघाककेसांगवोडाक
हैयाहे अनीकनराकेगात्रदेहकेअंगोंकरकेस्थितहेवणा
लिसेभयानकहलगविहैसाम्यहै ६३ योमकटोकरकेड
लोकरकेमागोलहकरकेमेहकोप्राप्तवीहेयोकोपकोप
नहिकरता योवनेमिलापाहाबी योवाणिसम्णकोपकर
याहमारेसोश्रेष्ठनहिहै ६४

© Dharmartha Trust J&K. Digitized by eGangotri

और छिद्रकाणीकरके रखनवीहै नदवीकुपितहोना
है यह दोषकहे है अब गुणसुणो घोडाअकर्णीवाल-
सकुंभरखे अरुसम अंगसावधान १५ चलनाहै अगले
खंवीकरके अरु टांगि छिद्रगुणोंकरके प्रकाशहै अरु
नलविषे अपरोपराक्रम अरुग्रजाकरके खाती कर
के नरनाहै स्नानकरताहोघोडा १६ अरुकैकघोडीयों
केमध्यविषेस्थिरहोकेविहारकरनाहै अरुश्रममध्य
वीचेनेनल्पदेरहे है संतिश्रमहै सम शरीरवालास्थि

अश्वायायोग्यसौवाश्वोदेशानुपनेगुणं
स्हग कर्णोवालमणिह्नतःसर्वेगात्रसमा
हितः १५ अस्थितस्याग्रपादाभ्यांभाति हूः
द्विगुणैस्तनः किंगाहमानोस्तरसापवश्या
सप्रभाविना: १६ रमेतकानिमध्यस्थः स
मोपश्चादिमध्यतः संसेविसोपविस्तिमाः
समकायःप्रतिष्ठितः १७ श्वादौरहोमोघो
गच्छेन्मम्युरःस्तपनःपाने वेगेनवारितः
प्रोक्तेसमसोपगुणाःस्तनः १८ वरसौ
वेघोपवमनाकाशेलवनेहयाः स्रोतप
वपराभागेनवृमोपंगुणाःस्तनः १९ स
रूपवेहियादाभ्यांपोसवारस्यावपा पा
र्श्वांभ्यांहितमवेति नवमोसोगुणाःस्मृताः
स्थिवेत्रपेणमानेनसर्वेपस्यस्तपोभने स
मृत्वेःसोहिविज्ञेयोदशामेवेपनोहयाः २०

नहै १७ घोश्वादिविषेपकडेघोडा सोउपजेअसरलवले
वेगकरकेमनाकी यहेमनमागुणहै १८ घोसेदरघाद
सदेअरुश्रकासविषे उछलेकवले अरुहष्णकीविषे
प्रवाहाकीनरावले यहेसरमागुणहै १९ घोडाशरीर
कीवाणीकरके अगले लकाके छिद्रगतिचलनाहै अ
श्वोपचलेवोतिनो अनुसारसदद चलनाहै सोपहेनवमा
गुणकहेघोडे २० जिसकोसंदरस्वरूप अरुमानकरके
स्थितहै घवजिसको यहदशमागुणजाणे २१

शा
हो
३२९

329

यो निकलदा होया नकुल की गति चलता है फेर पक्षी
को न्याई उलना वलता है फेर उसी प्रकार के चलना जा
नता है पहेला र मा गुण कहे या है १२ यो घोडा अग्रोला करे
ऐसे उछलता यो चले अरु वागणों कर के हट्या वे अरु
अहंकार से राहित होवे अरु सब कर्म के करे उछले सु
ख करके आवे १३ यो रथ कार्य के विषे सावधान हो
के पांपस की न्याई बडे वेग कर के चले पक्षी को न गा
ना वीले जावे यो घोडा इन्हां गुणां करके युक्त है अरु

निर्गच्छेन्नाकुलगतिर्यः प्रयाति विहंगवत्
प्राप्नोति नत्रपे राज्ञगुणा पकादशः स्मृतः १२
बोद्धितः क्षिप्रमनिष्ट इव मा वनिवर्तने अ
नहंकृतिकर्विष्टनसु विह्वमः सुनिग्रहः १३
रुष्टः कालापसरवर्यो बुजन्तस्समाहितः
वेगाप्रान्तः सवेगश्च हाघीन स्वनोयते १४
एतैर्गुणैः समायुक्तो दोषैश्च परिवर्जितः
अदिग्मामादि गुड प्रोभवति पार्थिवे १५
वलादड्ढपाद्यकघाधासनमेवच पं
च धारणास्तासि धराः पंच प्रकीर्तिताः १६
विक्रमा प्रथमा धारा द्वितीया वलिताः
तृतीया तु प्रकंटास्या वनस्तुपनवास्मृताः १७
उत्तमा पंचमी धारा न चार धं प्रकीर्तिताः द्रु
तोविलंविन श्चवनयाद्रुतविलंविताः १८

दोषयो कहे हैं तिनों कर के वर्जित है सो आदित्य विषे पा वि
न विनमें मुख्य है सो सुना करण योग्य है १५ वल हुतुलगु
मजि पाद कौरडा आसन पहेपंच धारणा नाम पंचधा
याका वर्णन कीया है न घारा के नाम ने वा या ने १६
विक्रमा नाम पहेली धारा कही है दूसरी वलिता नाम
है तीसरी उपकंटा नाम है चौथी धारा उपकंठा नाम है १७
पंचमी उत्तेजना नाम पंचम धारा कही है सो दो प्रकार की
यो है एक सीघ्र है एक मंद है एक उतस्थो चविलंबी एक
गदुनमंदगति १८

© Dharmartha Trust J&K. Digitized by eGangotri

चोरयोंकी प्राप्तिरूपप्रकारकी है अरु रसकी रूपप्रकारका
है सो लग्न योग्य इत्यादिके विषे देखनेवाला है अरु लग्न
कार्यके जाननेवाला अरु संदेह देखनेवाला है अरु गतिमे
चारको इच्छाके जाननेवाला सो योग नेत्र सो है अरु
दोइयोंविषे उत्तम है योग्य गट प्रसिद्ध मन स्वामिके अरु
सार बलता है १० सो योडा समरजाणे सो सभकर्याविषे यो
ग्य है योजनाओंविषे सारने प्रशंसा करया हो या बड़ गुरु मद
गनि बलता है ११ सो समवार योडा कहे पाहे कार्यविषे

नयस्य त्रिविधे योग्यानां रसो ह्य त्रिविधा स्मृता
प्रमानानवरिसो वाजी स्त्रस्ये वेदी सवाहिनः ९
गमने पि तद्विख्यस्ते नेत्र सौहृद्योनमः यो
ग्यानि मदितो ब्यमें साद्धिक स्पवमानुगाः १०
नैयास्समरसो वाजी विधीयः सर्वकर्मसु प्रा
जनैर्स्त्रोपमानस्त्र प्रशास्ति गुरु वाहिनः ११ र
मावरहनि त्रयो वाजी कर्मसु निंदितः अतउ
र्द्धं प्रवक्ष्यामि मंडलानां तु लक्षणं १२ त्रिकू
टे मेघपुष्ठे च वर्मे घावर्ते नेत्र वर्त्ते उत्तगोमूत्र
का चैव बन्धवापृष्ठे मंडले १३ श्रीवत्सः स
स्तिके कूर्मे छिद्रमंडलमेव च वज्रे मालोद्वप
द्मे च सर्वतोभद्रमेव च १४ श्रीवत्सक स्ववा
पीच मंडले निर्दिष्टोत्र विनिवर्त्तने नाल
च मंडले च वशालिके १५ पंचनक्षत्ररथाज्ञे
[illegible] मंडलेषु के
त्रिकूटमंडले भवेत् १६ ॥

निर्दिशकदेखाहे अब रस
के ऊपर रथमंडलस्थावर्तों के लक्षण कहते हो एक त्रिकूट
मेघपुष्ठ मेघावर्त नेत्रवर्त्त गोमूत्रका पृष्ठमंडल १३ श्रीवत्सः
स्वस्तिका कूर्म छिद्रमंडल वज्रमाला पद्मसर्वतोभद्र
श्रीवत्सक वापी पृष्ठमंडलक हे इनिवर्तनेन नाल
मंडल अवशालक १५ यहे चौदाने प्रकारके मं
डलनामक हे इन इनमंडलमिलेहोवे सो त्रिकूटमंड
ले होता है १६ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा
ख्या
३३०
330

योमंडलतुअष्टदलाकारकेपुष्पकहोवेंसमर्वतो भद्रनाममंडल
कहेंगाहै योवालहै तोयाकेचंद्रमाकेसमान होवेंसोचंद्र
मंडहै यांस्वस्तिकामगलयाउकेप्रकारहै सोस्वस्तिमंड
लहै याहोनोकासंपुटकोंसारहै सोसंपुटमंडलहै यो
श्रीवंकोंस्थानहै सोश्रीवत्सकनाम मंडलकेहनेहै
८८ योनिसकेसदृशसंस्थानवाहहोवे सो श्रीवत्समंड
लहोनाहै योपद्मकेसमप्रकारहै सोपद्मनाममंडलहै
योकछोपडसमप्रकारहै सोकूर्ममंडलहै ८९ योवद्

गष्टभिर्मंडलेप्रोक्तंसर्वतोभद्रमंडलं अर्द्धचं
द्रनदाकारवालंचंद्रंवनाटम ८७ स्वस्तिके
स्वस्तिकाकारंसंपुटंसंपुटाकृतिः श्रीवत्स
कृतिसंस्थानंकुर्याहोवाणकंतुयाः ८८ प
मनामेकृतिसंस्थानेश्रीवत्समंडलेभवेत्
पद्माकारंभवेत्पद्मकूर्मःकूर्माकृतिर्भवेत् ८९
वेद्राकृतिर्भवेवंद्रोवनेवज्राकृतिर्भवेत् वापी
संस्थानसदृशेमंडलेवापिसंज्ञितं ९० उग्र
यानेनपद्मोक्तेयाः संस्थानतोद्भुतः अनः
सगरेशुपदाद्द्यानोपरस्थितोवाधनिविष्टने
व समाहितेचाप्यवसादमानेमकृतनावेसव
नोनप्राप्नोत ९१ पतघयावकृयिनेमनीह
रयेस्तनेम्फावघुनासमस्ते नाभेयोवस्तिग
देनरेमोवायुःशरीरेविकरोतिकर्म ९०

याकेसमप्रकारहै सोवृंदमंडलहै सोवज्रकोंयाईहै सोव
जमंडलहै योवाउलीकोनरोंचिह्नहै सोवापीमंडलनामहै ९०
उग्रनिकारकेयकहेंगाहै सोबुद्धिवानोंनेसंस्थानने ना
नसोयोग्यहै यवकोउयोकेहहकेमध्यविषे वानाहे वि
कमहोयपहेंगा मार्गकरयोदिनहो। देगा अलदहके विषे
आवरणकेरहोगा स्वारके चेरहोगा एववेगवाले चो।
योकावायुनारहेंसमरहोनाहै ९१ यहेमनतोयोनसमभयसायु
नाकरकेकहेंगाहै अवकोउकासवकण्मम नाभिके
हेटयार वस्तिगदाके वकुकारस्थिनवायुविकृतनहो
यादा यहेकर्मकरनाहे ९०॥

© Dharmartha Trust J&K. Digitized by eGangotri

निसस्थानविषैस्थितयेप्राणोवहा रसादिपानके वाह
नेवालीयांनाडीयांसोशाखामेप्राप्तहोके औरशिरावा
रे अरुकोशाविषैनाशके स्थूलहोकेसोबलके वेदना
अनोंकोसंधीयांअरुकंठविषै शब्दकरनीयांहै वायुके
वेगकरकेभरीदीयो ९१ यवबोरावेगविषैस्थितहोत
है तबविस्तारकोप्राप्तहोकेनहिशब्दकरनीयांनाडीयां
यवहैसोलीचलनाहै तबशब्दकरेहै यदशरीरकोरोकके
दौडेनवबेगविषै प्राप्तहोयेतो ऐसेशब्दरहितहोताति

मन्दस्थितावक्षसियस्यवायुःशिरासमन्तात्सह
णागृहज्जाः स्वंवहत्येनचापितयोपकेटकूजं
नितामारुतवेगयुक्ताः ९१ विरायतासेनिय
ब्रोस्थितस्यतस्मावकूजेनिशानेगीनेन ग्राप
स्यावेनिहिवेमवस्योनिःशब्दतांयांनिविजृ
म्भणेन ९२ पक्काशयेयस्यविकाशिकोष्ठत
सवशाहोनवबाहकोष्ठे नतैवशब्दोभवति
इत्यस्यकस्मापिविरोधताचभवेकदाचित ९३
एवंनिकूजंनिशिरात्र्यनंतविकाशयांवप्रव
लमणीनाः पचेवयोनिदेशस्यावद्दवनोम
योसवी ९४ अथोमवर्वातानासोननचकू
निमारुतः ९५ यापिनाध्मायः कुपलशालि
होउक्ताःसमासेनोध्यनेभवा कुपविकृप
कारणंयोभिमेनःसविकृयः ९६ ॥

गोइन वेगबधनेकरके ९२ अरुपक्काशयविषै योकोष्ठ
विकासितहैनिसमेविाराशब्दनहिकरनी शीघ्रगतिविषैके
नरिशाउहोताहै अरुकूजनेबीनहिकरेबीशब्दहोताहै ९३
इसप्रकारभयोडेकोयोनाडीयांकूजनेयोहै वायुकेबलकर
केत्रिक सम्यगप्राप्तअरुपरेहैतोउकेपानिदेसाविषैश्रि
नुनिदस्यतवालीयाहैन ९४ अरुतिनोआनवदहमाडीयों
कोनिदाम्यखहोंगेतेवायुशब्दनहिकरता ९५ इतिया
विध्मायः अवयोशालिदोत्रमनिनेबाडेयोंकाकूपवरी
दनाकहेयाहैसोकहनेहैं अरुयोखरीदना अरुवेमनार

© Dharmartha Trust J&K. Digitized by eGangotri

शा॰
हो॰
३३१

331

नेवाले उत्तमघोडोंका योवांछा है सो विक्रयकरणेयोग्य है ९६
ये घोडे के विषें शरीर आवर्तसत इत्यादिगुणऔर दोषग
सरेदहमें स्थित हैं तिन इनोंको एकबार देखके न ग्रहण करे
तिसकोपरंतरहितपरीक्षाकरलेवे ९७ इसप्रकार बुद्धिमा
न बारबार घोडेयोंको देखकरके शालाविषें घोडेयोंको
भिन्नभिन्न करदेवे ऐसे घोडे सम्यलक्षणोंकरके पूर्णहैं त
तिन्होंको भिन्नएक शालाविषे रखे ९८ जे घोडे बहु
तगुणयुक्त हैं अरुथोडे दोषयुक्त हैं तिन अरुथोडे फलवा

सतीतावनेसल्लाघा गूढदोषा गुणायताः सकृ
दृष्टान्नसंत्यजेन्मासाद्वै नपरीक्षयेत् ९७ एवंपु
नः पुनर्दृष्ट्वा विभजेत्कुशलो हयान् सर्वलक्षण
संपूर्णांस्तान्संस्थापयेत्पृथक् ९८ गुणैर्बहुभि
राक्रान्ता दोषैः स्वल्पफलोदयैः मध्यमायाः
स्तेपूज्या नेतन्तायां वाजिकोविदः ९९ अ
मध्यमालक्षणयुतैरसमस्तैर्हीनलक्षणैर्युतौ वो
मूल्यत्रिभागसंयोग्या दृष्टास्तव्यायावश्यान व
वत्तर्थभागसंयोग्या विषमगात्रितिं हितं नाभि
वमंसमावहीनांगसैर्युक्ता विवर्जिताः १ पं
हलपञ्चशापादेरवर्णौ विषमैःखरैः २॥

लेहैं तिनोंको मध्यमशालाविषें घोडेयोंके लक्षणजान
नेवाला स्थित करे ९९ अरुपघोडे गुणयुक्त बहुत दोषवाले
तिनकों निरशालाविषें घोडे येमध्यलक्षणोंकरके युक्त हैं म
समलपराक्रमकरकेवहहै निसके मूलकौ ----- . अथ
मानकरके पूजनकरे घोडेकों अवस्थाके अनुसारतें येघोडे अ
वस्थाकरके होवहतीहैं अरुसभावमा जोहै औरस्सकलविका
रयुक्त है १ घेवजीनतिनकरकेनिदर्हैंतनिनोंके मूल्यके चौथे
भागकोपूजकरे घोडानिमासावर्णोनहिं अरुकोंजिनेवर्जि
मेहै २ निसकापवमाहै सावरकेघोडे वाहमा -----

ग्रहयेमहाबहुतनलक्षणोंकरकेउक्तहै येते विषमवयवद
संगवालेहैंन अरुयेछ्वालिकरकेहोनहैंन येअगभंगके
हैंन अरुयेरतेमिलेलक्षणांवालेहैंन येहीनगलहैं येमि
लतेवालेहैंन ५ अरुजिनाके प्रकोष्ठनेवांकाअग्रस्था
न मेंटक प्रकुंचपदे होनहैंन अरुवटवागपहैंन दंदअरु
अंडजिनांदे अरुअधिकअंगावालेयेहैंन सोत्यागे ५ ये
वोडेमहादोषांवालेहैंन अरुनियवर्णांवालेहैंनये रो
गीहैंन जिनांदे गल पुरपुंडंधे अतिपाम प्रोथ गेउरद

उरोहीनाश्चभमाश्चसंगग्गाविजलक्षणाः
मकेटरोहिणोश्चक्षपाश्चप्रज्ञानयेवच ४ म
कोष्ठिकामुंडकिनाखग्याघश्चप्रकुंचकौ
मृनाधिकौदंनमकेवर्णायेवाधिकांगिनः ५
महादोषास्तथावर्णयेवाश्वाःस्युर्विकारिणः
केटशंखाश्रुपानेषुप्रोथेगंडेनथारदे ६
कटेपुच्छेस्फिकपिंडेकक्षुदिकाकसाशने
श्रावनेमोत्रनेवास्येलथाहुसेसनालभिः ७
इत्येतेश्चमहादोषेपुंकाःस्युःस्तंगमाःरनकेपा
वापिविकेयाहयोरम्यश्वनापानः ८ यद्यप्य
गेगुणेस्तेवरसंयनेसंयुनाहयाः नैवतेस्था
पयेद्धीमानमस्त्रजेमोपवेश्मनि ९ अनथैथैन
येवलसंस्पर्शादपिवाजिनो येवापिनेवाम
यंगमवेयुःषुकलागुणाः १०॥

य९ कलहेउंवस्फि
केअंडस्थानकवाडिकाकसहनीविधं श्रावणेमोरहीयांहोन
तिनांकरके गुरुहोन ओर आन जेहांमेहोन ओरकलि
नालु वालेहोन इत्यादिकमहादोषकरकेयुक्तयेघोडे हो
न ओसघोडेनालेएछ्वीदननानेवेवन पहेदोहै निश्चय
करकेघनके नाशकरणवालेकहेहैंन ८ यद्यपि ओगुणा
कगुणयुक्तघोडेहैंवीये नरसुखीवालेयुक्तय ओस घोडेयां
को पंडितलोकीघरविषेनाहिरखावे ९ ओसघोडेहोरनां
घोडेयांकोंवीस्पर्शकरणोतें अनर्थउपद्रवाकोंप्राप्तकरादे

© Dharmartha Trust J&K. Digitized by eGangotri

कृ० ह्री०
३३२
332

नेहैन येरेइनां वोरेयांदेऽग्रेगोविषैं वरे फलोंवाले गुणकी
हैन सोवो महादोषांकरके अभिभूत निराहारको प्राप्त हो
करसभनिष्फलहोजातेहैन असेवोरे तिसके वरविषैं स्थि
नरहितेहैन सोवोरेवडेललमी वालाधीरवामी है तिस
को माडलक्षणकानिर्धनादिदोषोंविषैंविषैं प्राप्तक
रहतेहैं समनावो अकृतेपअष्टलक्षणांकरकेपुरुषवोरे है
नसो स्वामीको श्रेष्ठस्थानविषैं प्राप्तकरदेनेहैं पेडलिये
स्थानविषैंहै नतिनेगांको तिसकारणोने वेगलक्षणांका

महादोषाभिभूतानां निष्फलाः सर्वपर्वते श्रीमं
नमपिमनोरपरेलिहनमर्जिने ११ अनिष्टलेन
गोंडकानोपयंमाशुतेहयाः नथाप्रशस्तेसं
मकालनेगो स्वामिनेहयाः १२ हीनस्थान
मपिप्राप्तस्थापयंत्युनिनेपदे नस्मात्प्रशस्ता
होयाहजेयेसापलक्षणं १३ पतिष्ठायांप्रव
भाद्रमूलांयांवोत्रराप्तव गौरवोप्युभोलने
हयानोक्रयविक्रये १४ क्रयाध्यायः विनया
उपनीनेष्ठुनरंगेष्ठशालिहोत्रेणवालाघ्ये १५
नः वानेरिनाश्वगनावहै तिनहयोक्रमवः
लाग्रहणकरण अरुमाउलक्षणवालाप्रा सपास्ते १६
गरेण १६ अरुपतिष्ठाप्रवीभाद्रपदा मूलाउत्तरात्रय अरु
क्रयलेणदेणाकरना १४ इति क्रयाध्यायः नयकोरक्ष
वालेरवेनेपांशुरविषैं रंमोकेमारणोदीरक्षवाले
कोनेपरा शालिहोत्रनेस्वामीवहितियरे सिखाकोप्राप्तवोरे
करेहेतिनांरहसप्यमेकेवरहैसोकरोनेसेवी हैजेहेमि
स्यागमहै १७ इसकेपरे पकप्रष्ठवोडायप्रवंकरहेति
नां मेलवे तिसका प्राप्तहै मेनवलवेग उत्कहै असा
वोड्सातिविषैं धाइनेपायाहैन मेसेवायुकरलां
कोवनाकरकेउडालेमेहैन १८

अरु उदय की इच्छा वाले देवतां होयदे इंद्र को यह कहते
भय हे भगवन् विमनचोट्टे सोहे अपणी सच्छंद स्वाभा
वगति करके नहिं असां को वाहन करदि अपणी इच्छा
करनेहैं न इसतें यह देवसकरणेयोग्य है जिसविधिनें व
स होवे सो करणेयोग्य है नव ऐसे हि विधि ना होवे तें व
नयक ह्यो है नहि होने है थोड़े बिना जिसनरो यह वस हो
वे सो कार्यनुसी करो १८ यह देवतें की वाणी सुनके इंद्रने
शालिहोत्र ताई कहि है तिस शालिहोत्रेण नाडीवेधन

अथ उग्र कालिंद ग्राम चवंतमिदं वचो ब्रुवन्
विमना स्वच्छंदेन तुरंगा वहंति लवणाकिना
मास्माकं १७ नोदिध्येय थवा नियुक्तमशोव
कृतो भवेद्धि नयः वशमायाति यथा ह्यालय
ति नः संविधमेव संभवान् १८ पुनरुक्तः सुरा
णां कथितं शक्रेण शालिहोत्राय तेनाथ व
शीकरणम् उक्तं परिवेधनेन तु १९ तेन नः सा
रस्याने हम्म नो नरस्वेसमदिष्टं अथ न व
वापविज्ञा वश्य पंचयानि वे तुरगाः २० मर्मा
णि निहन्तम्य नाशेण यथा भवे प्राणिनस्तथैव
हि तेषां नः सन्नुपरा भवस्त परिवेधः समाहि
तः २१ दोषेभ्यः परि इ होस्यापरिवेधं व्यलयः
स्पृशः २२ तस्मात् दृष्ट्वा दोषान् भिषज्ञा परिवे पा
चकः कार्यः कालापशेनुषा स्वदशांगुलेन स्ह
नपरिणामहनी हनावेत भवेत् तेन वशमकेन
ते २३

नाम वसीकरण कह्या है १९ तेन ममृतसार केयल्या
नयना के मध्य विशेषस्तव कहें तिनां के विषे वेधकरणे
करके घोड़े निश्चय तें न मर होजाते है २० मर्मां के नष्ट होयदे
जैसे प्राणियें के प्राण नष्ट होता है जैसे हि तेन मत के हटाणे
वास्ते वेधक कह्या है २१ इह दोषों के ऊपर ध्यानके दाणे वरा
बर करणा २२ वैद्यने दोषों को देख करके परिवेध विधि किया
करणे योग्य है कालेक मलोरे को वा स्वदशा अंगुलितमात्र
लगा स्त्र अग्रभागा शिव अरूप करणे वाला विवला भागकी
तोलकरणा २३ ॥

© Dharmartha Trust J&K. Digitized by eGangotri

शा
ही
३३३
333

सन्नस्त्रका आवरणकेदर्पणवेधकेसमगिरद्दवणावे
ष्टिके साथवेधकोहोयो वडवकावरवेरकरे २४ मुल्लावाले
को शोथकेहेठलीमकास्याननेमे उपर जिसकी सुंदर शस्त्रको प्रवे
शकरके नासाअसविषे वेधकरावे २५ छेदहिंगपत्रकीस्या
इनिसकेऊपरवेधकरे अरुदाडोमेंअंगुलउपरअथवाहटवे
धकरावे २६ इसतरासमभागविषे स्फीतरोवेधकरके स
हिन सारोकें वसहोजातेहैंन २७ अरुअष्टपाससग्रहणाश्र
रुअष्टयोगअष्टपरिवारकटेलकरणेवालेके अनस्नारव

सपसत्रवानडवरंऊर्पान्नविवेधनेसमंह
मे शस्त्रकृतेपर्विवेधप्रवेशयेन वडववर्णा
२४ मूलीनामथः शोथसमोपस्तान्तीतिको
परितेवाकृष्णकमवधापसानावेसेचवेध
येत् २५ अच्छिद्रवेधत्रसंकासनयेवोपरि
वेधयेत् देष्ट्राभ्यामंगुलाद्र्धमथवानवेव
धयेत् २६ एवंविधासमेभागेसम्यकारिर
हितामवंतिवधोन्ह्णापतिकमंगुणहृयः
सप्रहृत्यपयोगश्चसादिकस्यवनापुनः अ
नवनानिवेनांरुविज्यनिवेधने २८ नेत्र
भावाविसर्पश्चग्रंथयपश्चदेनया हनमय
ग्रहोवापिद्रविज्मापनापने २९ विज्मादी
वकंनेत्राकेउत्तीवानमोरकोस्यापयेत्स
गात्रेनलतुनारेयनमजेने ३० ननासपस
मृत्रेणाकेउत्तीमभिरुपयेत् नानत्रेपम
योगहाराननीवापनेनर ३१

योगपरिनवेधमें सोहसमवसहोजातेहैं लनाहै अष्ट पष्णा
वगनाविसर्प ग्रंथिरोगरसोली अरुदोहीकाहीनाकउजाली २८ अदितेनल
पहरविजयष्णार्थनाडीवदनहिहोणेहोनेहैंन २९ वधा
केरेदपरवीडाहोवेनो सत्रवामनकी फुडली हाकोकरे
जिसकेउपरसनदिनवेनरखे फेर ढ्टा देवे २ अरुवेध
वालेसेनदीवारुपकीपालाकावणावे सोअनिलवीयने

© Dharmartha Trust J&K. Digitized by eGangotri

अरु हौली होएतैं श्रेष्ठ कहिया है अरु वेधन विषै लो
है का अरु त्रामे का श्रेष्ठ कहेया है १२ बडे की कुंडली
चार पल की अरु मध्यम की त्रय पल की अरु छोटी उ
की तिसथैं अर्धे की दोय पल की १३ उन सबी उडे विषै वा रां अं
गुली कुंडली वेध के उपर स्थित होती है अरु मध्यम वि
षै त्रय अंगुला निकटे विषै दोय अंगुली १४ अरु वेध वा
ले कुंडली छोटे को अर्ध अंगुल करे फेर तिस वायकों
प्रात अरु सायं काल विषै गर्म पाणी करके धोवे वैद्य १५

पीतनवीयं न वा वेवल स्तनाव मशस्यते
लौह मौ त्रुज्वरं वैव मशस्तं परिवेधने १२
पलान्यष्टै वनव्यां णाउत्तमायाश्च कुंडली
त्रिपलामध्यमायास्य नथाधम द्विपलाधम
१३ द्वादशांगुलमुत्तमायास्मैव वेधोपरि
स्थिता मध्यमेव पवीने वयंगुला अंगुला
नयाः १४ अष्टांगुल नयायाश्च स्पकुर्याद्वेध
स्यकुंडली सायं प्रातः सुखोष्णेन वारिणा
परिषेचयेत् १५ सर्पिस्तैलेन वाभ्यज्य कुं
डलीं परिवर्तयेत् अनेनैव विधानेन सर्व
दोषविवर्जिते १६ कुर्याद्वापि स्वरंगाणां नि
र्मूलमधारयत् तस्मिन्नन्यं नेरवालंक
टकं प्रतिपीड्य च क १७ परिवेधने च नंदशां
गुलं कार्यमुत्तमस्य प्रमाणतः त्रयोदशांग
ले मध्ये अधमे द्वादशांगुले १८ ॥

छोटा मलीर सा च्छा यकों धोय करके उपरंतै कुंडली कौं र
हटाय देवे इस विधि करके सभ दोषों तैं रहित मोडे या कौं क
रे जी वाके मूल विषै वेध करे तिस के बीच कटक मा स्ह गेह
उ सवि च वले रूपि के निकास न के वास्ते १७ बडे छोटे के
वास्ते वेध के निमित्त सलाका चौदां अंगुली करे अरु मध्य
म कौं तेरां अंगुली अरु छोटे कौं बारां अंगुली करे १८

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा
टी
११४

334

पहेमैनेमलीनसंकहेपाहै दोषोंकेसमनकरणेकोसम
र्थहै चोडेकेशास्त्रादेकर्मकर्त्ताहोया पीर्घकहेवैय ४९
इतिवैपध्याय: जिनोंकीनीराजनविधिकरीहैतिनोंको
देयाःकरके ग्रहलोहाभिहा पत्तविषेराज्ञाक्षकेअभि
देककरेहोयगां के उपरंनराजनकीयात्रा होती है ५० अभि
नमहीनेके शुक्लपक्षके दतीयानेंलेकरसतदिन एकस्या
तिनामकोजीकाअपमानकरके सूर्यकेरथविषेलगके व
लनीहै ५१ सोस्वातिवडेभारकरकेदवाइहोइ ऊपकरके

मृगासमस्यकअविहृनेदोषसंशामनेमरे
हांनिवेपत्तसैवकुर्यादसुखस्यकर्मसु ४९
इत्याह्वाथुवेदगणाक्रमेसिद्धयोगसंग्र
हेपनिवेयानामाध्याय: ॥ नीराजिनेस्त
रेगैःक्रनेवलोराभिहारकेषतेश्वभिवि
केराज्ञाक्षेनतोरपाणांभवेयात्रा ५० अश्व
युक्तिशुक्लपक्षेतिथौद्वितीयादिसमरात्रेन
वडवात्रूपेणैकास्वातिसूर्यस्यवहतिरथे
५१ साभारेणाक्रांता:ऊर्जायांनिरीहनेवाह
नं तेषांतेज:सतेवलेचकान्तिनिरहाणो ५२
सेजायतेचरोगाउपसर्गसमातिनाय स्मात् न
स्मान्वाजघनातेवाजो:पीड़ाभवेन्महती ५३
एवेवसमराचेस्वातेसंपातनपवनिर्दिष्ट: नत्र
दिवाकरेणरसेहावाजिनोरक्ता: ५४
शालांतवोपलिमोसनोरमांववाजिनोरवि
रेगै:नानाप्रकारै:श्रवरलेक्रनोभ्यनोत
पो ५५

तिनामोडेयोंकीदेवतीहै तिनांदातेनसवनवलपदे
समग्रहणकरलेनिहै ५२ सत्तउपसर्गकेरोगनिसहेहोतेहै
नेउपदुवोकेसाथ तिसकारणतें स्वातिके प्रभावनें वात
पीड़ावहुतहोतिहै ५३ तिषयकरस्वातिकासंपातसतदि
नकहेयाहे तिसविषैसूर्यकीकिरणाकरकेस्पर्शमेंरलाक
रे ५४ तोडेयोंकोऐसीशालाविषेरखाकरे कैसीहैशि
लीहोइ मनकोप्रसिनकरणेवाली नानाप्रकारकेफुलो

© Dharmartha Trust J&K. Digitized by eGangotri

करके अलंकृत धूपधूमकी सुगंधिवाली रुद्र यज्ञकी प्रद
करणेवाली ऐसी शालाविषें चोडेयांको स्थान

नस्यां स्थानानि वराणामसप्तजिताभ्यर्चिताहिनी॰
याद्यो गुरुर्विधिज्ञः शास्त्रवद्भक्तैः समाहृत्य त्रिन
यास्तु ४८ गुग्गुलद्विरुवयत्नाववाश्यपा
मार्गेनेदुलालोहे सिद्धार्थांवेलदमानभी
याहानिनाकेत ४७ वेदीवकल्पयित्वाथ
गैवेदविधानेनानलेनऋयान् सायंप्राता
हमुविः पुरोहितो ब्रह्मचारीस्यात् ४८ न
हृणायवतिलतंडुलमाज्यवाशालिहोत्रेण
वेदीमपिच प्रोधामंत्रेणानेनलेपयेत्स्था
नः ४९ गेहिनास्यमहाभाग हव्यवाहन
लोनम धूमध्वजकृतद्वारस्वर्गस्य प्रापिनः
पच्चः ५० उग्निहूहोमंयस्त्वाणमांशांतिर
स्तत्रयेभव स्वाहान्तिमंत्रेणादापयेत्प्रथमा
हुति ५१ ततः प्रजापतीन्द्रायसोमायवरुणाय
च विवस्वते कुबेराय सर्वेणाद्याहुतिपातयेत् ५२

यवतिल चावल वेदीकरके हवनकरे शालिहोत्रकरके
योकरेणाई अरुणप्रोधा इसमंत्रकरके वेदीकोलेपकरा
वे वनरवैय ४९ अग्निकी प्रार्थनाकरे हेगेहिनाम हेम
हामहाभाग हे हव्यवाहन हे नलोनम धूमध्वज हे कृतद्वार
हे स्वर्गपथः प्रगटहोयके यो होमद्रव्य है तिसको ग्रहणक
रो सौजकोविषें शांतिहोवे इसमंत्रकरके प्रथमहोमवि
षयआहुतिदेवे ५१ तिसकेउपरांत स्वाहा इसमंत्रकरके
प्रजापति इंद्रसोम वरुण यमकुबेर सर्वेण शेषपर्वे
कसाहुति ५२

© Dharmartha Trust J&K. Digitized by eGangotri

आदित्य अश्वनी कुमार रुद्र वसु रनों पितर विश्वेदेव साध्य
मरुत रनों कों स्वाहा पद उच्चारण करके आहुति देवे अ
ग्निकों फेर विद्याधर यक्ष गंधर्व नक्षत्र ग्रह हय है ५४ वा
सुकी ने लेकर नाग गरुड पौर्णमास यों हैन देवता न
दीयां समुद्र वनस्पतियां स्वाहा इस करके हवन करे ५५
रेवार अग्निकों देव इसी नरां और नां देवतादि कों कों स्वाहा

आदित्यापनयाश्विभ्यां रुद्राणां वसुभिः
सहः विश्वासा विश्वेदेवानां साध्यानां मरु
द्भिः सह ५३ स्वाहेत्युच्चारेण जुहुयादथ मरु
द्वाहने विद्याधरयक्षगंधर्वनक्षत्रग्रहा
श्रये ५४ वासुकीप्रभृतीन्नागानां गरुडस्य
पौर्णमासीनां देवतानां नदीनां सागरा
णां वनस्पते ५५ स्वाहाकारेण जुहुयात्
द्वितीयेन ऋतामसंवे एवमन्येषामपि स्वाहा
कारेण होमयेत् ५६ अग्निर्वैवस्वतो यनये
न इहागानि हिरण्यतांसि मन्यषे बलेनेन
सा इवति नस्मात्मन्यैषपापयेन्त्वापये
रूपान् ५७ पुरोहितस्तिदिः कालवर्षवि
वादिनो नमान् पुण्याहकारयेन्निःस्व
स्यापतीभिनों लेपने ५८ नटनर्तकगंधर्वाः
स्तनवारणमागधाः नेरंमानपानि हेतुः समा
हस्तोतिकारोणा ५९॥

५९ अरुपीछे ने अग्नीरवादेरवे एमाक्षीपं हनिर्यावाले नाद्य कारशब्द करके हवन करे
यैइन सोग्रात कालविषेवा अनेज करके असनाने हैन निसका
रणने घोड़ीयों कों पनसम पविषें स्नान करावे और पान करावे
पुरोहित घोड़े सो टोमो काल ग्रान सनों विषे ब्राह्मणकों न
मकारके पुण्याहे और स्वास्तिरत्यादिमंत्रों करके जलसेचन
कराके आशिषा करावे ५९ नटईत्यादि नीनके रसकर गाय
क सूत भाट वेणा गुणा कहने वाले स्तुतिकरणे वाले यहे
मसन्नरट नपर यैन घोड़े की शालाविषे स्थिन रहिन
शांतिके करणे वाले ५९

गऊयोंहैं नमो संदरमधुरमनके हर्षकर शब्द हुए कर
केवलेजाते हैं तिसकारएतें घोड़ेकी शालाविषें वंदित्र
सदाहि रखराजा ९० यहसन दिनवीतजानतव नवमीवा
लेदिनघोड़ेयोंकों स्नान करावे अरु वहुतभांतके वृत्ति
दानदेके फेरपीछे तैंनलविषेंनारीयांकरावे ९१ फेर
मालाकरके विभूषितकरे घोड़ेकों अरु तैसैंहि सुगंधि
धूपादिकरके धूपितकरे तिसकेउपरंत विजयदशमी
अश्विनशुक्लपक्षकी तिसविषें घोड़ेकों नगरकेवाहरकाढे ९२

मनोज्ञान्मधुरान्सद्वा शब्दानगच्छन्ति वै गृहाः
वादित्रवाहनागारे नस्मात्तेषु प्रयोजयेत् ९०
अतिक्रम्य नवम्यां तु दिनं तस्मिन्पयेउद्यान्
वरुणाय वलिं दत्वा पश्चान्नीराजयेद्धयं ९१
विभूषयेच्च मालाभिस्तथैवाधिवासयेत्
ततः शुक्लदशम्यां तु निष्क्रम्य नगराद्बहिः ९२
दिशिपूर्वोत्तरायां तु देशे चाकम्पवर्णशुचौ
ततोरणं समाप्याथ दशहस्तसमुच्छ्रितं ९३
विस्तरे चैव समाख्यातं ध्वजमालाविभूषितं
अरत्निमात्रसपादं चतुर्भ्यःस्तंभमनोहरं ९४
शुद्धस्नानानतोद्वाराः न्तामाहिकशुराम
राः शुण्याहप्रमत्रोषश्चगीतवादिप्रमेष
नैः ९५ स्नानमागधगंधर्वोपमानस्वलंक ११
ताः प्रातहूनैश्वयुक्पैस्त्येवाश्वोपनीविभिः

पूर्वोत्तरदिशाविषेंका उत्तरमें अरु पवित्रदेशस्थानविषें सुंद
र तोरणस्थापितकरके दशहाथउंचास्थानवनावे ९३
विस्तारहुतामतिसकाकहे याहै ध्वजाअरु मालोंकरके
शोभायमानकरे अरु सभ तोपासेतें धुपांतिवास्ते रत्नाक
रे पूर्वद्वारकेरमनकेहरणेवालास्नानस्थानवनावे ९४
फेरशुद्धस्नानकराके घोड़े पेटहलकरणेवाले केसा
थ तिसयज्ञभूमिविषें शुण्याहत्यादि वेदमंत्रपाठ गीत
वैमनर इनोंशब्दोंकरके ९५ अरु स्नानवंशकेगुणकरक
नेवालेमागधगंधर्व अरुयज्ञविधिकरणेवालाजयमान

© Dharmartha Trust J&K. Digitized by eGangotri

भा
द्रो
३३९

336

अलंकृत वस्त्रभूषणोंकरके अरुशास्त्रहथलयेदेवुरहणों
करके अरुचोड़ेकेअनवार उपजीवकाजिनांदीतिनाके
रके नेरणविधिविषे रहाकेसाहिन लेवचोड़ेयांको नहूं
दक्षणकेलेभके सपुरोहित अग्निकोविषें हवनकरके
फेरदशदिशाविषें बालिदानदेकरकेराजाके नाईस्न
तिनअग्निषाकथकैंनकरे अरुराहसमशङ्खामस्माटीयां
करकेउरनेहै सोउक्तनेउरहै चोड़ेयांकोनहिंमारने १८
तिसकारणनेदतिणउअरविषें उल कोजगाकेअरुठग
रुथदोनोंपासेसावधानहोके दोनोंपासेंखड़ेहोन १९

नेतृब्याहतमाणानवनोरणांसविधौ हवि
णांलभहिट्केरवावामौपुरोहितः १७
दिशाबलिंनतेनोट्वावस्तिवातेनिवदेयन्
उल्काभोद्रणिरहांसिनेवत्रेनिहिवाजिनः १८
उल्काप्रज्वालयेनस्मादतिणोनरणांस्थयोः
अष्टौमनख्यानखगाटनउल्काहलानिवया
स्यिनान् १९ नेनाग्निख्यातेहांवेणकुर्यातनव
प्रदीपनेहविः शेषणानानांथ्योहविभान
नयेयेन् २० अश्वराजपुरोधासहविर्हिंनपु
रक्षितः वाहनाःपाणाहलसाहूहलस्व
भरतान् २१ वेवस्नकवेशेवपाथ्यपास्व
भिरतानो वेशांदेवाहहवेशमटरहपथ्यको
पणाः २२ रहेनवक्रांगपर्वांबालभिंद्रोदयानने
हविषांवनेसपाशपविनेपाथ्येमहोपतिः २३
तिसअग्निकेआहारके हवे नहीं प्रकाश करे अरुअग्निसे
वाकीयाहुनरहे तिसकरकेराजसको मंगलकरकेरमक
रे २० अश्वराजकोंकालिण प्रोहितः अग्रविषें स्थितहोके
हहनेरहाकेर २१ एमराजकुवेरदानोंवहीयांकोरहा
करने अरुचंद्रमाहर्षपिचले पासनेरहाकेरे पवेन उर
रकीरहाकेर २२ अमलकोंगंधर्वरहाकेरे इंद्रवलकोरहा
करनेसो राजानपकेप्रहोनाले पमहविमोहकोंपिलावे २३

फेर तिसकों वरकुबेलायके वैशम्प्रेष्ठस जनन करे अरूप है
नय चोड़ के अनेक रूप विघ्न पे वैघ ७४ कुल जन्म मातिव
ले लक्षण अमनन्तरना के युक्त है सो ते अपणे स्वामि कों र
ख अरु तेरे कों कल्याण होवे अरु ये कोई अनिष्ट नियक मैं है
नसो है नरगो नमस्तमा करे इस नरों में विन चोग वेद घोष
वेदध्वनि साथ प्रवेश करे ७६ तिसके उपरंत राजा वजी
रों के सहित नगर के मध्य विषे जावै जैप नैपप है धुनी शा
ब्द के है करके ये और बाकी के लोक हैं तिना करके ७७ इस

ततस्तं प्राविशन्वाद्यं ध्वजपंक्तिविराजितं वरः करेण जा
यमिदवामदक्षिणे प्रवेशयन्स्ततः ७४ कुला
भिजनमाम्याचलक्षणं युंजनवाविमाः भर्ता
रमभिरक्षस्व शिवं देवेभवेदिति ७५ पंकज
मनिष्टानिरू मनेतरगो नमः एवं नमंत्रितो
वाजीवक्षवोष निनादनः ७६ ततसौरण
मध्येनमंत्रिभिः सहपार्थिवः निगच्छेनयमि
मुख्यासैरोरनगनैर्जनैः ७७ एवं नीराजितेर
श्वे लक्ष्यालोकाभिहारकैः ततः कुर्यात् दक्षिणु
नः कर्म पव मेनदर्शनः ७८ इति श्रीम
हत्गणेशकृते योगमेगरहे अश्वस्थानं समाप्तम्॥
समामाश्वाधेननिमतानदुउयोगसंग्रहः हे
वैशम्पायन प्रस्थानं शालिहोत्रेण यथामति ७९
सेवनतामधुहरदपेन लोवाहन संविधिः वि
नेयानैवयावातिनेरगमसमसनः ८०

प्रकार नीराजन विधि करके संपूर्ण फेर ये घोड़े यों कों कार्यों
विषे चोड़ने वाले हैं सो लोक भिहरों करके शुरू करे अश्वनमे
पारदर्शन करावे ७८ इति गणेश कृत नीराजन स. अश्वस्थान स
माप्तम्॥ अरु अब निमत करके जो व पयोग है सो समास करता हूं
वैशम्पायन विषाव प्रजापाशालिहोत्र मुनि इतना ज्ञान करके
घोड़े के वाहन की विधि नतने यथारूप विषे करे है सो स
भ कर रना है घोड़े के विस के मन कों नहि मारणा है इसकी

© Dharmartha Trust J&K. Digitized by eGangotri

ग्रा
ह्रो
३३७
337

नरो महांतिसनेचोडे नहि चलने सोटे चावकइ नांदे मारणोर
करके नहि डरे यो मारे देवने सो निंघ है यो वाणोंके नरन्न
रकरके चले सो मध्यम है श्रुत विश्वास नी ह्लग बुद्धिवान् देव
पदे वाहन का निश्चय है ८२ जिसके चलक मलके मूलके
नल्प है नपाद श्रुतकांणमध्याविषे रहि श्रुतकमनिनल्पल
के श्रासन विषे है नपट जिसके श्रुत चोडे के हृदय कीवानी
जाणे श्रुतपथा कालविषे दउग्रह्नारकरणा सो श्रेसाचोडे
के वाहने वाला श्रेसा राजे योकरके भजायोग्य पश्चाता है ८३

नवहंतिहयालवदंडपातेन नाडिताः अर्थ
मंदं उपातेन मध्यमंवासनेनच ८१ नीह्लग
विश्वासयंत्राहः पथवाहननिश्चयः ८२ च
लकेसलयपादेकणमध्येचरश्मि नेलनि
कटिदेशाश्वासने संस्थितोरः हयसदयग
नितःकालदंडाभिवाति सभवनिहयवाहः
शनिनःपार्थिवैह्रः ८३ वसीनेवहयेदयाद
भिमंमथुरोहितः नवेदश्चाभनेदनेराजोवि
नयमादिशेत् ८४ यस्त्रानयस्त्रमंवाहयव
वंधहयःस्थितेन मध्यमंजातिमानेस्यामला
निपववृिंभूति ८५ हयपलानिरश्ययोग्या
नवनिवंधपंचमध्रुकः नथातिषपार्श्वेयो
मुर्धिसंयुतैःकटकैस्त्रिभिः ८६ सत्तिको
योजयेवववधीपावमंदपणे संयोग्यादम
लायवमलिमानस्यचानरे ८७

श्रोहित घोडे नाई लली वेलमंत्र करके देवे सो चोडा हित नोहार
हे जिसको महिजा णेन वणमा को विजय कर ८४ यो श्रेष्ट चोडा
रे जिसकों पंने वरे उपरेत

© Dharmartha Trust J&K. Digitized by eGangotri

मह्यांतेवादशपलानिसमारभ्याणकेसिनैः
वाहैनिपुंजनावाहाभवेत्तिसरुजोरणे ९८
विमस्वाभ्यासखेटकरणेनैवनश्यायोस्यः
दत्वाजिलानितिनियमंपर्यायेपिरणसंयो
न्यः ९९ अस्यहृपाद्दृगेनहिपाश्चेत्तन
छ्यवारदमनेन भूत्वासनोहृपःशिकि
त्व हिज्ञोलिदिनानिपंचपाव्यथवा ९०
केवलपवक्रमशोदमनीयःपठेमेवस्या
त्वभ्याकृत्तिमेषपवनःनिपुणेनवाहनीयः
स्यान् ९१ अनुवर्तिनानदीपंवेनोमागेभ
पवेन प्रवेनतिलपनेहृपाःशिशवोवाह
नीयाःस्युः ९२ पवनःसेषांकांपंपुत्रकेव
नयानदाक्रमणे आक्रांतवाहनायेयादेशि
ष्याकोपणेनारहाति ९३ नवदमयेवपु
नेयोभ्यासस्युःरणेपर्भ्यस्तनिम्मातवमसमाव
हमेहृताधानिहानिनोमारी ९४

गेहूंकोंक्रमकरकेचलेनासिखावे प्रथमविधिंदृष्टपकेरक
रकेअभ्यासकरणेयोग्यहै फेरवनेरसने ऊपरचडुकेवा
लसिखोणीकहेहै ९१ फेरसोपवनकरके अभ्यासकरणेन
जिसगतिकोंचितरख्याकरे तिसकेअनुसारचलनाहै येतो
है पहलेवाल्हिगेहवन्द्रःखसहारणविषेसमर्थहोवेसो
घोडेस्वारियोग्यहोतेहैन ९२ फेरतिसपवनतितेनांकाका
येजिसमातिकेविषेहिलनाजानेहैन योवाहनप्रक्रियोंकर
के प्रकोपातावीओयकरके पदनहिग्रहणकरें अतेको

© Dharmartha Trust J&K. Digitized by eGangotri

ईकों येरणेमें दृढ होणेवालेकों फेर धीर्य देकरके फेर तिन्होंकों
उठे स्थानविषे नीमे सममार्गकर इमार्ग हरजाणविषे हा
थीयोंके रस्तेविषे अरु रात्रिके चलनेविषे अग्निविषे रस्ता
केविषे घोडे अरु भयग्रामसहटावे असोसिखाय युक्ष्याद वि
षे घोडेकों करे घोडेके गमनके जाननेवाला है स्वारथ व
यहकें यहवाहनसंविधि कहिहै ८५ अनेकाण स्थाकरके
कहे येमंत्र अरुपाठतिनांकरके युक्त होके अरु अग्रणे हा
थ उठेकरके दोनो कर्णोके मध्यविषे देवे घोडेकों तिक

गत्यागमनयोगानां दहनेऽभ्रमिकुर्परादयो
स्मितिर्नेतुरंगं सादिविज्ञानेन सर्वस्माद
ध्वाहनसंविधिः ८५ नानागमनिर्दिष्ट
मंत्रपाठसमाधृतः अन्त्यमध्ये दपाणिगो
पश्यत्कर्णद्वयान्तरे ८६ सन्दाक्षौ निनेवो
र्ध्वदृष्टेर्नासवनेोवली निमास्वोवानेव
ध्वीरश्वानवपोपिव ८७ नचिकेवचनेचा
सलदेहिस्वरपदद्दनिः भ्रमिवजासनपद
प्रनानापिकननविन् ८८ नायोविमुख
पादस्तनाभीस्त्रणामस्तोरवः नकोलदट
दास्त्रवमार्गलदेवनाशनः ८९ कशाका
वलक्षणान्तःसकलपनेवेदशासनः ९०
टष्टावृत्तोदयद्वभिकोरणनटशरणसम
घः सर्वक्लेशनाशहिम्मः समेगोदिरदः सनाति भी

नेत्रा रवुरोनोंविषे वहनकार इत्यंतर्नाकरे अरु नेः
पृथ्वीविषे आसन अरुपादसमरखे पुंछे पिछे वहनारखा
से घोडेके शास्त्रके जाननेवाला नाशहिन स्वेपार नोदेव
देव घोडावेवारपावु करे अरु - - - - - - - - - - - -
केदरवतोविषे भोजननहिकरे - - ८९ अरु मार्ग
कदेहलिमा अरु सारकेघोडेदेव हनवलकरणा घोडेके
ललणोके जननेवाला अरु समयपन शास्त्रके जाननेवा
ला सोपुर्वविषे घोडीको स्थानीदेवे कोंको णारणभूमी

© Dharmartha Trust J&K. Digitized by eGangotri

विषे प्रेरणमें समर्थ है ऐसा भङ्ग रथों कों संहारणे वाला है अ
तम्रत्वक् है अरु हाथीयों के विषे निर्भय होके साथ चले अरु
हृदय जिसका स्थिर अरु नित्याहि स्थिर आसन वाला है अ
रु रोगरहित है श्रेष्ठ कुलमें जन्म्या है अरु शस्त्र प्रहार
के वेले कों जनने विषे वन्तर है अरु अपने कार्य विषे व्यस
न रहित है ऐसा घोड़ा राजों विषे श्रेष्ठ कह्या है २ अरु
जो सवार है तिसने घोड़े के सासों का ज्ञान जानणा अरु य
थार्थ हृदय घोड़े का जाणे सो सिद्धि को प्राप्त होता है ३

प्रणामितवाहहृदयः स्थिरासनो निर्मत्सनिष्ठ
मः १ निर्व्याधिकुलसंजातः प्रहारवेलाविप
श्चितः स्वव्यापारे व्यसनो यो हयवाहः से स
न्तेवहः २ सर्वव्याप्ताश्वविज्ञानाभिरूपेण हयसा
दिनः सम्यग्विज्ञानहृदयतुरगो सिद्धिगामि
नः ३ हरेः सर्वाणि नामानि देहिनां भवलोप
येत् मंत्रवैद्यादिनेदिवसः सादीवलनभा
षितेन ४ अश्वायुःशास्त्रमिदं नकुलेन समीद्रस
हावकेणानि ष्णामीति स्वस्तिमा संपादयो
नलोदितो वाहकाध्यायः ५ मंगलं लख
कानां वणिक्कानां च मंगलं मंगलं सर्वदे
वानां भूमौ भूपति मंगलम् ६ ॥

तिसके संअ
शालिहोत्रः यो घोड़ा नखम है सिद्धाकरके तिसके सो अ
कर्णोविषे यो नलराजाने कहे या दायो वेदमंत्र है सो अ
लण अरु घोड़े का सवार पढ़े अश्वायुशास्त्र नीतमवर्तस
मीदृस्पहावकेणनिष्ठति पढ़े मंत्र कर्णोविषे पढ़े पढ़ने
लकरके कहे है या दाध्याय में कों कल्याण करे इति वाह
काध्यायः मंगलं भूयात् सर्वजगतां ॥ इति श्री गणकृत
शालिहोत्रे उत्तरस्थाने समाप्तम् शुभम्

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri

© Dharmartha Trust J&K. Digitized by eGangotri